आचार्यसोमकीर्त्तिकृत प्रद्यद्युम्नचरित्र

संस्कृतभाषायाम्

शोधार्थी

मामराज शर्मा:

निर्देशने

डॉ. बलदेवव्यास:

सहनिर्देशने

डॉ. उमेश प्रसाद दाश:

संस्कृत विभाग

श्री जगदीशपप्रस्रसादझाबरमलटिबडेवालाविश्वविद्यालयय:

विद्यानगरी, चूडेला, झुन्झुनूं , राजस्थानम् –333001

वर्ष –2016

(i) भूमिका

भारतीयसंस्कृते: विश्वे महत्त्वपूर्णम् स्थानमस्ति इयमेव संस्कृति: ''हिन्दुसंस्कृति' नाEना आहोस्वित् ''आर्यसंस्कृतिरिति'' नाEना बोध्यते। संस्कृते: जीवनाय भूतकालस्य वृRाान्तस्य अपेक्षा भवति। आत्ममनसो: बोधनार्थं वर्तमानभूतकालयो: ज्ञानमनिवार्यं विद्यते। भारतीयसंस्कृति: प्राचीनकालात् आरHय अद्यावधिपर्यन्तं जीवितमस्ति। स्ववैशिष्ट्यात् संस्कृतिरियं विश्ववन्द्या वर्तते। अनेका: पाश्चायत्यसंस्कृतय: कालकवलिता: सञ्जाता: किन्तु भारतीयसंस्कृति: नूतनेव जगत्समक्षम् तिष्ठति। भारतीयसंस्कृतिषु अनेके सEप्रदाया: धर्माश्च प्रादूर्भूता: तेषामास्तिकनास्तिकभेदेन परिगणनं भवति। ये सEप्रदाया: धर्माश्च: वैदिकसिद्धान्तान् स्वीकुर्वन्ति प्रामाणत्वेन च वेदान् अङ्गीकुर्वन्ति ते आस्तिका: व्यपदिश्यन्ते ये च वेदान् न स्वीकुर्वन्ति ते नास्तिकत्वेन बोध्यन्ते। यद्यपि भारतीयजीवनपद्धतौ आस्तिक धर्मानुयायिनाम् बाहुल्यं विद्यते किन्तु नास्तिकधर्मानुयायिनामपि अभावो नास्ति। नास्तिकधर्मेषु जैनबौद्धप्रभृतय: समायान्ति।

संस्कृतभाषा भारतीयसंस्कृते: आधारस्वरूपेण विश्वसमक्षम् समायाति। जैनसEप्रदाये अनेके संस्कृतविद्वांस: सEबभूवु: तेषु आचार्य: सोमकीर्ति: सर्वोच्चस्थानं लभते।[1] स: स्वकालस्य प्रकाण्डसंस्कृतशास्त्रवेत्ता साहित्योपासकश्च आसीत्। तत्कालिकसन्तसमाजे अस्य सर्वोच्चस्थानमविद्यत स योगी आसीत्। आत्मसाधनायां तल्लीन: सन् स्वशिष्यान् धर्मानुयायिनश्च साधनापथे चलितुं प्रेरयामास। प्रवचनं कुर्वन् साहित्यग्रन्थान् विरचयन् च स्वशिष्यानपि साहित्यसंरचनार्थं प्रैरयत्। संस्कृतसाहित्यस्य अयं प्रकाण्डविद्वान् आसीत्। स्वरचनाप्रतिभया संस्कृतभाषां, राजस्थानानीभाषां, हिन्दीभाषां, प्राकृतभाषां च उपकृतवान्। अस्य कार्यक्षेत्रं राजस्थानप्रान्त: गुर्जरप्रान्तश्च आसीत्। यद्यपि अनेन अनेके ग्रन्था: विरचिता: किन्तु तेषु ''प्रद्युEनचरित्रम्'' सर्वोच्चस्थानं भजते। प्रद्युEनचरित्रस्य वैशिष्ट्यम् संस्कृतक्षेत्रे जिज्ञासूनाम् ज्ञानपिपासाशमनार्थं सामर्थ्यं च वीक्ष्य शोधकार्यार्थं मम मनसि प्रेरणा सञ्जाता यत् अस्य ग्रन्थस्य सEपादनम् संस्कृतजगत: जैनसमाजस्य च कृते कल्याणाय अलौकिकपरलौकिकाHयुदाय च भविष्यति।

(ii) विषयपरिचयः

प्रद्युम्नचरित्रम् जैनकविषु प्रसिद्धतमो ग्रन्थोऽस्ति। अस्मिन् काव्ये श्रीकृष्णपुत्रस्य श्रीमतो प्रद्युम्नस्य जीवनचरित्रम् वर्णितम् अस्ति। अस्य माता रुक्मिणी आसीत्। प्रद्युम्नस्य गणना पुण्यपुरुषेषु क्रियते। विक्रमाब्दस्य[2] (1531) एकत्रिंषदुत्तरप×चदषषततमे वर्षे पौषमासस्य कृष्णपक्षे त्रयोदषम्यां तिथौ बुधवासरे अस्य ग्रन्थस्य रचना सञ्जाता। अयं ग्रन्थः षोडष सर्गेषु विभक्तोऽस्ति।

ग्रन्थोऽयं भट्टारक [3]श्री भीमसेनस्य प्रसादात् विलिखितोऽस्ति। अस्य ग्रन्थस्य मंगलाचरणे नेमिनाथस्य वर्धमानस्य सरस्वत्याष्च प्रार्थनाकृता अस्ति। यथा–मंगलाचरणम्–

श्रीमन्तं सन्मतिं नत्वा नेमिनाथं जिनेष्वरम्।
मदनो विष्वजेतायि बाधितुं नो शषाक यम्।।
वर्द्धमानंजिनं नत्वा वर्द्धमानं सतामिह।
यद्रूपदर्षनाज्जातः सहस्त्रनयनो हरिः।।
प्रणम्य भारतीं देवीं जिनेन्द्रवचनोद्गताम्।
चरितं कृष्णपुत्रस्य वक्ष्ये सूत्रानुसारतः।।

प्रथमसर्गः– अस्यग्रन्थस्य प्रथमसर्गे नवषष्टिः (69) श्लोकाः सन्ति। अस्मिन् सर्गे राज्ञः श्रेणिकस्य प्रष्नस्य कथनम् अस्ति। तथा च जम्बूद्वीपस्य वर्णनम्

अस्ति जंबूद्रुमाकारो द्वीपो जंबूद्रुमाभिधाः।
वाहिनीनाथ संसेव्यः सुवृत्तोनृपतिर्यथा।।

भारतक्षेत्रस्य वर्णनम् –

तत्रास्ति भारतं नाम क्षेत्रं च क्षिति विश्रुतं।
तीर्थं तीर्थकृतां स्थानैः पवित्रं पाप नाषनम्।।

मगधदेशस्य वर्णनम् –

तत्रवै मगधो नामदेषोऽसौ विदितो भुवि।
वापी कूपतडागादिवनैः नाना विधैः युतः।।
श्रीमद्राजग्रहं तत्र विख्यातं नगरं भुवि।
जिनेन्द्रः भुवनैः भाति भूमौ स्वर्णनगरीसमं।।

श्रेणिक नाम्नः राज्ञः वर्णनम् –

तत्रास्ति श्रेणिकोनामभूपालोविदितोभुमि।

शत्रुराषिविजेया योनिर्मलोऽतिविवेकवान्।।

दुष्ट निःक्रन्दको नूनं साधुपालनतत्परः।

श्रावकाचार संयुक्तः सम्यक्यतवे न विभूषितः।।

राज्ञी चेलनायाः वर्णनम्–

तस्यास्तिः चेलनानामजायामायाविवर्ज्जिता।

निर्ज्जिता स्वर्वधूरूपा निजरूपस्यसंम्पदा।।

पापभीतागुणैः ख्याता गुणराषिप्रपूरिता।

सम्यकेन च संयुक्ता श्रावकाचारनिर्मला।।

कुलद्वयविषुद्धा या पतिस्नेहभरालसा।

जिनेन्द्रमार्गे कुषलासतीगुणधुरन्धरा।।

राज्ञाश्रेणिकेन अष्टांग नमस्कारः विधिपूर्वकं जिनेन्द्रार्चनस्य वर्णनम्–

इति स्तुतिः विषेषै सः स्तुत्वादेवं जगत् गुरुं।

प्रणम्यपरया भक्त्या पूजांचक्रेविधानतः।।

जलगंधाक्षतैः पुष्पैनैवेद्यदीपैर्धूयसत्फलैः

पूजामष्टविधानकृत्वा नरकोष्टेन्यवीविषत्।।

द्वितीयसर्गः– अस्मिन् सर्गे एकसप्तितिः (71) श्लोकाः सन्ति। सर्गेऽस्मिन् भगवतः श्रीकृष्णस्य राज्य विभूतेर्वर्णनम् अस्ति– तथा च जम्बूद्वीपे स्थितस्य भरत क्षेत्रस्य वर्णनम्–

अथास्ति सर्व द्वीपेषुमध्ये जम्बूपलक्षतः।

द्वीपोजम्बूद्रमोनामविख्यातः क्षितिमंडले।।

तत्रैव भारतं नामक्षेत्रं भाति विषेषतः।

दक्षिणस्यां दिषिर्स्थं यं तस्य का वर्णनापरा।।

तीर्थं तीर्थकृतां तीर्थैः पवित्रं पापनाषनं।

यत्रागमनं देवानां जिनकल्याणकारिणं।।

तत्र क्षेत्रपरं ख्यातोदेषः सौराष्ट्रिकाभिधः।
राजते स्वर्गतुल्योयं प्राणिनां पुण्यकर्मणां ।।

यत्रेक्षुसरसावाटावालैराकंपिता अपि।
नायांतिपामराणां हि भूमौ वंधभयादितः।।

सरौवरानि यत्रैव कमलैः पूरितानि च।
राजहंसैः सषब्दानि राजन्ते सर्वदा भुवि।।

सरितो यत्र भांतिस्मजलैः राप्तरिताभंष।
तटद्वयस्थवृक्षाणां वसिताः पुष्पराषिभि।।

राजंतेवापिकानूनं नीरराषि प्रपूरिताः।
कुर्वन्तिः कोकवदनैः स्वागतंताः प्रवाषिणां।।

स्थाने स्थाने प्रयांरम्यादानषालाः पदे पदे।
कुक्कुटोत्यातसंलक्षा यत्र ग्रामामनोहराः।।

उद्यानैर्विविधैर्युक्तः स्वर्गलोकइवापरः।
कृतपुण्यजनानां हि सृष्टो सौवेधसा भुवि।।

शालिवप्रावभुर्यत्रसाकपिंडा पदे पदे।
शालयस्तेषु राजंतेनम्नाः पातुं जलं यथा।।

सर्वधान्याकरायत्र दृष्यते सर्वदा ध्रुवं।
दोर्भिक्षं संभवीवार्त्ता श्रूयते न कदाचन।।

सरसाः शाड्रूलादेषा राजन्तेवाह्यभूमिषु।
सर्वायत्र प्रदर्ष्यं ते गोधनैर्ध्वलीकृताः।।

द्वारिकापुरि नाम्नी प्रसिद्ध नगर्याः वर्णनम्

मोचचोचमयावृक्षाः स्फुरत् द्राक्षादिमंडपाः।
संवलेन विना लोकायांति यत्र प्रवासिनः।।

तस्मिन्नेवं विधेदेषे पुरी स्वर्णगरीसमा।।

राजते द्वारिकानामा प्रसिद्धाक्षितिमंडले।।

आपणानांततिर्यत्र रत्नराषिविराजित।

प्रत्यहं शक्रचापस्य का शेषंकां करोति या।।

सत्यभामायाः वर्णनम् –

तस्यास्तिचाग्रमहिषीसत्यभामा मनोहरा।

सतीनामगणीभूतां गुणानाम नद्यालया।।

लावण्यलक्षणोपेता हावभाव समन्विता।

तर्जितः स्वर्वधूरूपा निजरूपस्यसंपदा। ।।

लक्ष्मीचलानराधीष नचाहं चपलाकदा।

करोषि हि कथं नूनं ममत्वं कमलासभा।।

विनयादिगुणाधारा भर्तृछंदानुवर्त्तिनी।

कुलोभय विषुद्धाच विद्याधरषरीरजा।।

सिरीष सुकुमारांगी मातंग गति गामिनी।

सर्वषास्त्रार्थनिपुणा चतुरावाग्वधू यथा।।

शंपेवकालमेघस्य षिखेवषिखिनः परा।

वेलेवचसमुद्रस्य तथैवास्य बभूव सा।।

तृतीयसर्गः– अत्र एकनवत्युत्तरद्विषतम् (291) श्लोकाः विद्यन्ते। अस्मिन् सर्गे कृष्णबलरामयोः प्रमदोद्यानगमस्य वर्णनम् अस्ति। तथा च नारदागमनस्य वर्णनम्–

अथैकदा सभामध्ये कृष्णोराज्यश्रियायः तः।

पूरयित्वा सभां सर्वां निविष्टोवधुभिर्वरां।।

राज्यदेषमयी वार्तां कुर्वन् लोकान्प्रमोदयन्।

यावत् तत्र स्थितो राजा तावदन्यत्कथान्तरं।।

आकाषां तेजसां पुंजमागछन्तं विलोकितं

यदा तदा सभास्थानां लोकानां विस्मयोभवत्।।

किंवासूर्यमयं तेजः किं वा वह्निमयं भवेत्।

सूर्यस्यगमनं तिर्यक्वह्नेर्नज्वलमूर्द्धगं।।

आधोवतरतेनूनं तेजः पुंजमिदं वरं।

किं भवत् किमिदं चित्तेलोकानां विस्मयो भवेत्। ।।

आसन्नेचततः प्राप्ते मनुष्योयर्मितस्फुटं।

अत्यासन्नेपुनः प्राप्ते पुरुषोयमिति निष्चितं।।

समीपं हि समायाते नारदोवैः विचिंतितः।

इतिक्रमेण निर्णीतो लोकैस्तु नारदोमुनिः ।।

मृगाजिनो धरो धीरो जटाधारी वृषाकारः।

कौतुकाकुल चित्तेऽसौ नारदः कलहः प्रियः।।

जिनमार्गेसदारक्तोभिमानैकधनो नद्यः।

हास्येपि सततं रक्तो जिनवंदनतत्परः।।

नारदेन अन्तः पुरे सत्यभामावलोकनस्य वर्णनम्–

जगाम सत्याभवनं कौतूहलसमन्वितः।

पश्यामि सत्यभामांहि प्रथमं कृष्णवल्लभां।।

यावत् गत्वा मुनिः शीघ्रं तां पश्यति सुलोचनां।

तावत्सा मज्जनं कृत्वा निविष्टा हरि विष्टरे।।

अग्रतो दर्पणं धृत्वां पश्यन्ती रूपसम्पदां।

विभूषणानि देहे सा कुर्वन्तीह निजे तदा।।

पुनः पुनः स्तु पश्यन्ती निजं रूपं विभूषितं।

वहन्ती परमं हर्षं राजसन्मान संभवं।।

सत्यभामया नारद तिरस्कारस्य वर्णनम्–

तदापृष्ठे समायातो नारदः कलहः प्रियः।

दर्पणेस्थितया दृष्ट्या न दृष्टोव्यग्र चित्तया।।

प्रतिबिम्ब च तं रूपं दर्पणे तस्य सन्मुनेः।

भस्मनो धूलितं वक्रं जटाभीरौद्रतां गतं।।

निजमुखस्य समीपे दृष्टं रोद्रं मुखं तया।

मुखंवक्रीकृतं सत्या गर्वपूरितचित्तया।।

चन्द्रवद्वदनं मेहि तस्य पार्श्वे किमीदृषं।

वदनं कस्य दुष्टस्य यदिदं प्रतिबिंबितं।।

पृष्ठि स्थिते न मुनिना नारदेन विलोकितं।

तच्चवक्रंचवक्रचयकृतं सत्यभामया।।

चलितस्तत्रक्षणादेव नारदः क्रोधपूरितः।

सर्वत्र मानिनीयोऽसौ सत्यभामापमानितः।।

चलित्वा सोतिदुःखेन चिन्तयष्च पुनः पुनः।

कस्मान्मेमंद भाग्यस्य मतिरेवं समुदठगता।।

अन्तः पुरे साम्राज्ञीनां कृते आर्शीवाद प्रदानम् रुक्मिणी दर्शनस्य वर्णनम् च–

प्रणुतास्तायुवत्यो सादाषीर्वादेन तोषयत्।

कुर्वन् पुण्यमयीं वार्त्तां स्थितो यावत्ऋषीष्वरः।।

तावत्तेनाग्रतो दृष्टा स्थिता सा रुक्मिणी।

च सा तेन भीष्मानुजापृष्टा केयं बाला मनोहरा। ।।

ततो भीष्मानुजा वोचत् श्रृणुनाथ निगद्यते।

एषा भीष्मनृपस्यैव पुत्री श्री रुक्मिणी वरा।।

एवममुक्त्वा तयासंहि नमिता मुनिपादयोः।

तदाहिमुनिना तस्य दत्ताषीः सर्वमुत्कटा।।

वत्से भवाग्रमहिषी नूनं कृष्ण महीभृतः

मुनिवाक्यं हितंश्रुत्वा रुक्मिणी चकिता ह्रदि।।

श्रीकृष्णेन रुक्मिण्याः चित्रं दृष्ट्वा विचारस्य वर्णनम्–

किञ्चिंतकालं तथा स्थित्वा चिंतयामास चेतसि।

किमेतद्धि समानीतं नारदेनन्वरायता।।

वेधसा वा कथं सृष्टा रूपलावण्यषालिनी।

नेदृषी भुवनेनारी व भूता न भविष्यति।।

वेण्याजितं मयूराणां वृन्दं वाचानयाध्रुवं।

ललाटेनाष्टमी चन्द्रं मुख्येन रजनीकरं।।

कीरचुञ्चुर्ज्जिता नूनं निजघ्राणेनचानया।

नयनाभ्यां मृगीनेत्रे भ्रूभ्यांमन्मथकार्मुकं।।

कम्बु कंठेन सा जिग्ये पर पुष्टास्वरेणवै।

स्तनाभ्यां श्रीफलानीह बाहुभ्यां पुष्पमालके।।

इन्द्रायुधंजितं कट्या जठरेन मनोहरा।

नाभि कूपमहं जाने लावण्य जलदीर्घिका।।

नितंबाभ्यां परं प्रोढा रंभास्तम्भसमोरुका।

जानुभ्यां वर्त्तुलाकारा चरणाभ्यां मनोहरा। ।।

पाणिपादतलाभ्यां किं जितं पद्मसमूहकं।

सन्तप्तकनकाकारा कान्त्याजित निषाकरः।।

तेजसा जितदीप्तांषु स्थैर्यच्चै नैव सागरः।

सर्वलक्षण संपूर्णा सर्वावयव सुन्दरा।।

केयं चात्र क्व चा याता पटे वा निहिता कथं।

नारदेन कथं दृष्टा ज्ञाता वा लिखिता कथं।।

नाकनाथस्य किं जाया किं वा कुसुमधन्विनः।

किमु वा रात्रिनाथस्य दिननाथस्य किं वधूः।।

कीर्त्तिमूर्तियुता वा कि वाग्वधूसरीरिका।

यक्षी वा किंन्नरी वा किंस्यारूपं भवेदिदं।।

इति विस्मयमापन्नो विष्णुरेवं विचिन्तयन्।

इतिध्यात्वा चिरंचित्तेपुनरेव विमृष्ययत्।।

पृच्छामिनारदं नत्वा पटस्थं कारणं स्फुटं।

करस्थेकंकणे नूनं मादर्षको विलोकयेत्।।

विमृस्यैवं चिरं कृष्णो नत्वा तं नारदं मुनिं।

प्रपछविनयात् सर्वं चित्तसंदेहकारणं।।

श्रीकृष्णबलभद्रयोः कुण्डनपुरस्य प्रमदवनं आगमनस्य वर्णनम्—

द्वावेव भ्रातरो वेगद्रथमारुह्य चेलतुः।

निशायाः परिचमेयामे प्रछन्नौकवचान्वितौ।।

आयुधैर्विविद्यै युक्तो धीर्यमात्र सहायकौ।

रुक्मिण्यां दत्तचित्तौहि कलागुण विषारदौ।।

मनोजवरथारुढ़ौ धारयन्तौ मनोरथौ।

श्री कुंडनपुरोद्यानं प्रापतुस्तौ मनोहरं।।

दूरतोपि यदा दृष्टं तत्कुंडनपुरं परं।

श्रीधरेण तदाध्यातं कथं चात्र भविष्यति।।

चतुर्थसर्गः— अत्र त्रयोदषधिकत्रिषतम् (313) श्लोकाः सन्ति। अत्र राज्ञः षिषुपालस्य वधस्य कथा, श्रीकृष्णरुक्मिण्योः विवाहस्य वर्णनं, सत्यभामायाः विडम्बना गर्भस्थसन्तानसम्बन्धस्य च वर्णनमस्ति। तथा च प्रमदवनस्य सुन्दरतायाः वर्णनम्—

कौतुकेन पुरं दृष्टुमायातं तद्वनं भुवि।

इन्द्रो देषवषात् नूनं दृष्यते तद्वदाकतिः।।

पादपैर्विविधैर्युक्तं पुष्पराजि विराजितं।

इन्द्रोपेन्द्र समानौ तो यादवौ विषतुर्वनं।।

संप्रविष्य वने दृष्टोषोकोसौ शोकनाषनः।

तस्या परिस्थिता दृष्टा वैजयन्ती मनोहरा।।

शिशुपालस्य चिन्तनस्य तथा कुण्डनपुरं सेनया परिवृत्तस्य वर्णनम्—

मेलयित्वा महत्सैन्यं चेदिराट् शंकयान्वितः।

जगाम कुंडनपुरं महासाधन संगतः।।

तत्र कुंडनपुरं तेन सर्वं सैत्येन वेष्टितं।

तारकाणां समूहो वा यथा मेरुमहागिरिं ।।

कृष्णेन प्रमदवने रुक्मिणीमवलोक्य रूपलावण्यस्य वर्णनम्—

मनोभव समीपे सा समायाता मनोहरा।

गुल्ममध्य स्थितेनापि कृष्णेनोसौ विलोकेते।।

मनोज्ञां लक्षणैर्युक्वां भंगुरालकप🡻कां।

कामस्य वानवत् नेत्रां चन्द्र बिम्ब समाननां।।

कम्बुकण्ठेधरां तन्वीं पीनोन्नत पयोधरां।

कलस्वनां हि वेणी व मालती दामवाहुकां।।

दार्घोत्तीर्ण सुवर्णाभां वज्रमध्यां तनूदरीं।

दिक्वरींद्रसमाकारां नितम्बस्थल मंडलां।।

मेखलायाः पदे नूनं ऊषकेतनमन्दिरां।

रम्भास्तम्भासमाकार विभ्रतीयीभ्ररोरुकां।।

चरणयोः कमलवद्वारयन्तीं मनोज्ञतां।

रणन्नू पुर संयुक्तां गत्याहंसवधू समां।।

रुक्मिण्या कृष्णस्य आवाहनं तथा कृष्णस्य उपस्थितेः रुक्मिण्याः हरणस्य वर्णनम्—

एवं विध च तां दृष्ट्वा केषवोगुल्ममध्यतः।

यावद्विनिर्गतस्तावत्रयोक्तं हि वने वचः।।

मत्पुण्याद्वासमायातो भवेत् च द्वारिकायति।

निर्गत्य वचनं मद्यंपहे वदीयतां तव।।

एवं व्रतीति सा बालायावत्तावद्विलोकितः।

अग्ने स्थितः सुरूपायो वासुदेवो बलान्वितः।।

अग्रतः स्वामिनं दृष्ट्वा जाता चाऽधोमुखी च सा।

लिखन्ती वर्त्तते नूनं अंगुष्टेन भुवस्तलं।।

जगादकृष्णराजोपि रुक्मिणीं वचनं वरं।

तववाक्यात्समायातो द्वारिकाया अधीष्वरः।।

तस्मात्प्रसीद हे देवि मां विलोकय सुन्दरि।

कृष्णवाक्यं समाकर्ण्य जाता लज्जानताननना।।

धारयंतीहि सानूनं मुखं चलितं क्रुंधरं।

शिषुपाल भयेनैव विभ्रती कंपितर्वपुः।।

सज्जीकृत्वा रथं तावत् बलदेवो जगाविति।

स्त्रीणां स्वभावतो लज्जा कन्यकानां विषेषतः।।

स्वयं नीत्वा कराभ्यां तं रथमरोपय द्रुतं।

स्त्री चरित्रं न जानासि सत्यगोपाल को भवत्।।

बलदेववचः श्रुत्वा कृष्णः प्रेमभरालसः।

स्वरथेरोपयन्बालादालिंगेथ रुक्मिणीं।।

चलितं हि रथं तावद् बलेनोरुह्यवेगतः।

चालितेथरथे तस्मिन् कृष्णो वाक्यं वरं जगौ।।

पा×चजन्यं निजं शंख पूरयित्वा मनोहरं।

सर्वं निरुपयामास वृत्तान्तं केषवस्तदा।।

षिषुपाल दलस्यापि ये च कुडनवासिनः।

ते Üाृणं तु मदीयं वै वाक्यं वीरजनार्चितं।।

मयाकृष्णेन शूरेण रुक्मिणी हि हृता हठात्।

कस्यकस्यास्तिवः शक्तिर्मोचनीयाचतेन सा।।

चिन्ताग्रस्तायाः रुक्मिण्याः तथा कृष्णेन चिन्ता निवारणस्य वर्णनम्—

इत्युक्तेपि प्रतीतिष्च जाता तस्या नमानसे।

तथा च तादृषी दृष्ट्वा कृष्णौचेतामिदं पुनः।।

पश्य पश्य महाभागे ममषक्तिं जनातिगां।

दर्षयामि यथाप्येतां सत्यं प्रत्यय कारणं।।

पविसं चूर्ण कृष्णेन नीत्वा तस्यां गुलीयकान्।

स्वस्तिकं तु करे तस्या लिखितं तेन तत्क्षणात्।।

भिन्नाएकक्षणेनैव सप्रतालाः पुरः स्थिताः।

दर्षितास्तेपि रुक्मिण्या एकेनापि शरेण च।।

अत्यद्भुतां ततो दृष्ट्वा शक्ति कृष्णस्यरुक्मिणी।

पुनष्चिंतापुरा जाता तथैव विषवादिनी।।

कृष्णोथरुक्मिणीं प्राह बालचन्द्रानने Üाृणु।

अद्यापि दुःखिनी कस्मादृष्यसेतन्निवेदय।।

लज्जां संह्रव्य सा बाला संकोच्यकरकु ह्मलं।

जगादप्राणनाथं हि विनयानतमस्तका।।

Üाृणुनाथ महाभाग जानातित्वपराक्रमं।

ममोपरिकृपां कृत्वा विज्ञाप्यमवधार्यतां।।

पिताभ्राता च मे नाथ मौच्यौद्वौतुर रणांगणे।

लोकापवाद दुःखंस्यादन्यथा क्षितिमंडले।।

एतएव कृपां कृत्वा मौच्यौजनक सोदरौ।
श्रुत्वामुरद्विषः प्राहस्मितं कृत्वा च तां प्रति।।
न कर्त्तव्या त्वया देवि चिंता चेतसि दुःखदा।
विमु×चामिरणे नूनं तव तात सहोदरौ।।
माधवोक्तं वचः श्रुत्वा सहर्षा रुक्मिणीजगौ।
जयोस्तु सर्वदा नाथ रणोरिपुममाकुले।।

श्रीकृष्णशिशुपालयोर्मध्ये युद्धस्य शत्रुविनाशस्य वर्णनम् च–

तावत्कृष्णोरणं चक्रेसमं चादिमही भृता।
शस्त्रैर्नाना विधैः कृत्वा सर्वेषां भयकारणं।।
पूर्वं लोहमयैः शस्त्रैष्चक्राते तौ रणं चिरं।
दिव्यायुधैः परं युद्धं चक्रतुस्तौ परस्परं।।
वर्त्तमानेरणेघोरे नारदः कलहः प्रियः।
नभस्थोनर्त्तनं चक्रे तुष्टचित्तः पुनः पुनः।।
संयुध्यर्विविधैः र्युद्धैः षिषुपाल समंहरि।
निःप्रभंगतषौर्यं च शत्रुं कृत्वा जनार्दन।।
दानिनं गुणिनं शूरं संपूजित धनाधिपं।
भीषणं तु कुलीनं च रौद्रं हि कुपितं रणे।।
जद्यानसंस्थितं चाग्रे राजराजं यथा हरिः।
पुण्यक्षयेक्षयोनूनं सर्वेषां प्राणधारिणां।।
खड्गखंडित पादौ वैहयाना दृष्यते रणं।
वीभत्सं चापि रौद्र च कबंधानां हि वर्त्तनैः।
गजकुम्भ स्थलास्थस्त रुधिराज्जात कर्दमं।
भग्नेनापि रथौघेन करुद्धर्दमेरुद्वदिग्मुखं।।

एवं विधं धरं कृत्वा हत्वा शत्रुंवलोत्कटं।

रुक्मिणी सन्निधिं यातौ बलनारायणौ मुदा।।

कृष्णबलरामयोः रुक्मिण्या सह द्वारिकां प्रति प्रवेशस्य वर्णनम्–

रुक्मिणी बलदेवेन यावकृष्णो वने स्थितः।

तावछुद्विष्च संजाता स्वजनानां हि मन्दिरे।।

तावद्वारावती लोकः प्रमोद परिपूरितः।

श्रुत्वा कृष्ण समायात शत्रुं जित्वा वधू युतं।।

श्रृंगारिता पुरीतैष्च तोरणैः केतुभिस्तथा।

पुष्पैस्तु पूरिताः पंथा छंटिताष्चन्दना भसा।।

श्रृंगारियेवं पुरीं तां लोकाः स्वजन संयुताः।

सन्मुखं तु समायाता वेषैर्नानाविधैर्युताः।।

वाजित्राणां सहस्त्रेष्च वंदिनां निवहस्तथा।

महोत्सवेन मिलिता कृष्णदेवं बलान्वितं।।

कृष्णः सन्मानदानैष्च संतोष्यैबंद्याज्जनान् ।

चकारस्वजनैर्युक्त द्वारिकायाः प्रवेषनं।।

रुक्मिण्या कृष्णं सत्यभामाया विषये चर्चायाः रुक्मिण्याः उदारताया च वर्णनम्–

एकदातत्य वासाने रुक्मिणी स्वामिनं जगौ।

कृष्णराज कृपाधार श्रृणुवाक्यं मदीयकं।।

मयापूर्वं श्रुतातेहि सत्यभामाभिधाप्रिया।

तस्यास्तु मन्दिरे नाथ गम्यतेन कथंत्वया।।

ततो नारायणः प्रोचे श्रृणु देवि वचो मम।

येनवाकारणेनापि तस्या गेहं नागम्यते।।

सहंकारांतु सा देविममतच्चनरोचते।

खंडितेयैस्तु कर्णो चै किं साध्यं स्वर्ण भूषणैः ।।

रुक्मिणी वचनं प्राह कृष्णं तु विनयान्विता।
श्रृणुनाथ कृपां कृत्वा कथयामि तवाग्रतः।।
योयस्यापि करेलग्नः सकथं तेन मुच्यते।
स्वर्णः खंडतिकर्णं चेत् स्वर्णं केनापि त्यज्यते।।
तस्या वाक्येन संतुष्टः प्रोचे तत्र सनातनः।
तव वाक्यात् गमिष्यामि तस्या गेहं तु रुक्मिणी।।
पत्रं पूगीफलं चैव चूर्णं खदिरसारकं।
युक्तं कर्पूर खंडैष्च रुक्मिण्याष्चर्चितं यदा।।
क्षिपन्ती तत् च तां कूलं भूमौ दृष्टा यदा तदा।
नीत्वा करेण कृष्णेन स्वयं बंधनिजाचले।।
तत्र स्थित्वा क्षणं कृष्णस्तस्तत्र सत्यालयं ययौ
वंचितुं तां प्रियां नूनं मनेकाद्भुत संकुलं।।

सत्यभामया उपवने श्रृंङक्षरयुतां रुक्मिण्यामवलोक्य चिन्तनस्य वर्णनम्–

गते कृष्णेपि सा देवि सत्यभामा वनेगता।
रुपयौवन संपूर्णा विविधैः भूषणैष्चता।।
वन मध्ये तु सादृष्टा स्थिताषोक तरोरधः।
एयंतु वन देवी हि ज्ञातं वै सत्यभामया।।
किंवासिद्धस्य कन्या वा किन्नरी वा सुरांगणा।
नागलोकात्समायाता किं वा नागवधूरियं।।
रोहिणीचन्द्रभार्या वा किंवामन्मथवल्लभा।
ब्राह्मी वा कमला वापिकेयं बाला भविष्यति।।
ज्ञातं सत्यं मया नूनं येयं बाला मनोहराम्।
मत्पुण्यत्प्रकटा जाता वनस्यैव हि देवता।।
देवताः प्रकटत्वं हि जायन्ते पुण्ययोगतः।

न तु पुण्य विहीनानां देवता दृष्टिगोचरम्।

देवताराधनं लोके नूनं इष्टवर प्रदम्।

आराधयामि भक्त्याहं निजकार्य समीहया।।

पंचिमसर्गः– सर्गेऽस्मिन् त्र्याधिकाद्विषतम् (203) श्लोकाः विद्यन्ते। अत्र प्रद्युम्नकुमारस्य हरणसम्बन्धिनीकथा वर्णिता अस्ति। तथा च मदनस्य उत्पत्तिः सूचक षण्णां स्वप्नानां वर्णनम्

भीष्मराजस्य पुत्रीहि निषाया विरमेन्यदा।

सुखं सुप्ताषयं नीयेमृदो पुष्पमये वरे।।

स्वप्नान्विलोकयामास मदनोद्भव सूचकान्।

पूज्यांष्च सर्वलोकानां प्रमान सुखकारिणः।।

स्वयं नभसि गच्छन्ति विमानेतस्थिता वरे।

विचरामि यथा कामं राज्य लीला समन्विता।।

इन्द्रस्य कु×जरं रम्यमैरावत समाद्वुयम्।

द्वितीयं तु स्वप्ने दृष्टं गंर्ज्जतं हि स्थितं पुरम्।।

उदयाचलमूर्द्धस्थः सविता सन्मुखस्थितः।

प्रकाषयंष्च पÁानां दृष्टः स्वप्ने तृतीयके।।

निर्द्धूमोज्वलनस्तुर्येततः कुमुदवांधवः।

अपांपतिस्तु षष्टे हि गर्ज्जन् दृष्टस्तयापुरः।।

रुक्मिण्या सन्तानोत्पन्नस्य वर्णनम्–

सम्पूर्णं समये साथसुषवे रुक्मिणी सुतं।

तिथिनक्षत्रयोगेण शुभे च करणे तथा ।।

रुक्मिणी प्रमुदं प्राप्ता तनवे पुत्र जन्मना।

पुत्रं सूर्यसमं दृष्ट्वा लक्षणैर्विविधौष्चितम्।।

बान्धवै सह सन्तुष्टं कृष्णां ते प्रेषयत् नरान्।
वर्द्धापनाय कृष्णस्य मांगल्यौष्च विभूषितान्।।

पुत्रहरणस्य वर्णनम्–

रात्रौ तु रुक्मिणी सुप्ता गेह मध्ये सपुत्रकाः।
युक्ता नारी कदंवेन गीत नृत्य विधायिना।।
सुभटानां सहस्त्रं तु मुक्त्वा वैर क्षणाय च।
रुक्मिण्याग्रेह परितो विविधायुध धारिणाम्।।
कृष्णो गत्वा निजं स्थानं सुखं चिंता विवर्ज्जितः।
लग्नः कर्त्तुं तु निद्रांष रक्ष माणोङ्गरक्षकै।।
सहस्त्रैर्युवतीनां च युक्ता तत्रैव रुक्मिणी।
पश्यन्ती पुत्रवदनं हर्ष पूरित मानसा।।
यावत् तत्र स्थिता रात्रौ नाना विध महोत्सवैः।
तावदन्यविचारोभूत् रुक्मिण्या दुःखदायिकाः।।
यो सौ हेमरथोराजा जायातस्यहृतापुरा।
मोहात् च मधुराजेन पापा च दृव्ध चेतसा।।
जायाया हरणं ज्ञात्वा राजापि विरहातुराः।
मुक्त्वाराज्यं तु तत्सर्वं वभ्रामविजने जने।।
गर्गोभूतत् चाति मोहैनमोहोवैः दुःखकारकः।
नगरं च वनं भ्राम्यन् प्राप्तौ सौ पंचतां तदा।।
भ्रमित्वा विविधां योनिं पूर्वकर्मानुसारतः।
ब्राह्मणस्य कुलौत्पन्नो यातोऽसौ तापसा श्रमम्।।
तापसैर्वाधितः सोपि प×चाग्निं साधय हठात्।
तेनकष्ट प्रभावेन मृत्वा प्राप्तो हि दैत्यताम्।।

एकदातु विमानस्थोविचरं निज लीलया।

रात्रौपथ समायातो रुक्मिण्या भवनोपरि।।

दैत्यस्यात्र समायाते विमाने बालकोपरि।

स्खलंनात्रस्य स×जाता वायुवेगेन गच्छतः।।

विमानं स्खलितं ज्ञात्वा चिंचितं वा सुरेण हि।

केनमे स्खलितं नूनं विमान दुष्ट बुद्धिना।।

जैनें वा प्रतिमाचाधो वर्त्तते किं पुरातनी।

शत्रुर्वावर्त्तते चात्र मित्रं वा कष्ट संयुतम्।।

किं वात्रांत्यषरीरोहि वर्त्तते दुःखपूरितः।

अन्यथामद्विमानस्य गतिनैनावरुध्यते।।

स कोस्ति भूतले नूनं येन मे गति रोधनम्।

क्रियते जीव्यते तेन कथं वा भुवनत्रये।।

प्रेषयामि दुराचारं नियतं यम मन्दिरे।

विमानं येन स्खलितं गच्छन्तं वाममांवरेः।।

एवं विमृष्यमाजस्य तस्य कुमति सम्भवम्।

वर्त्तते चावधिज्ञानं तेन ज्ञातं तदाखिलम्।।

मधुभूप चरेणात्र पापेन पूर्वजन्मनि।

कलत्रंतुमदीयं हि हृतं मोहातुरेण च।।

तया सह कृतं राज्यं तेन शंकाविवर्ज्जितम्।

ततः स्वर्गसुखं भुक्त्वा विविधं नाकसम्भवम्।।

विमिष्यैवं चिरं दैत्योर्नत्वातं गगनांगणे ।

तर्ज्जयन्चि विधैर्वाक्यै क्रोधारुण् निरीक्षणम्।।

कर्त्तव्ये निष्चयं कृत्वादत्योथ बालकं प्रति।

नीत्वाबालोत तो जातो गिरौ तक्षक नामनिः।।

नानानोकुह संकीर्णाः कंटका कुलभूतलाः।

कर्करैष्चचितातीक्ष्यौस्तथा गोक्षुर कंटकै।।

इगुटैः खदिरैर्विल्वैर्द्धवैः पलासकेस्तथा।

विषवृक्षैः समाकीर्णा तत्रास्ति खदिराटवी।।

नकुला हि समाकीर्णाः सिंह व्याघ्रादिभिर्युता।

यमस्यापि भयंकारी तस्यारौद्रं किमुच्यते।।

तत्रनीत्वा च तं बालं मुमोचासौ षिलातले।

द्विप×चाषत् गजानां हि षिलाचक्रे तथोपरि।।

बालकस्य सौन्दर्यस्य वर्णनम्—

तस्याधोपिस्थितं दृष्ट्वा बालं चात्यंतसुन्दरम्।

कुर्वन हास्य मनाकूतत्र चपलं वक्रकुंतलम्।।

चपलौपाणिपादौ च बद्धमुष्टि युतौकरौ।

उत्पुलपÁावत् नेत्रं प्रतप्तकनकत् विषम्।।

निजवक्र समृध्या हि जितपर्वनिषाकरम्।

नवमृणालवत् भुजं सर्वलक्षण लक्षितम्।।

सुन्दरं सबलं धीरं सर्वावयवभासुरम् ।

सर्वेषां प्राणिना नेत्र मनोहरणकारणम्।।

निज पुण्यं प्रकाषतं पुराजन्म निज कृतम्।

निजेनांऽत्यषरीरेण जितदैत्य महारिपुम्।।

एवं विधं च तं दृष्ट्वा बालसर्वगुणान्वितम्।

कराभ्यां नृपतिर्निन्येतं च भूमितलात् तदा।।

नीत्वा बालं च भूपोपि चिंतां कर्त्तुं समुद्यतः।

कोऽप्ययं भाग्यवान् जीवोऽत्यन्तं प्रौढकुलोद्भवम् ।।

विमृष्यैवं क्षणं चित्ते जगाद दयितां प्रति।

गृहण बालकं देवि सर्व सुन्दर विग्रहम्।।

षष्ठसर्गः— अत्र अष्टदषाधिकप×चषतम् (518) श्लोकाः सन्ति। सर्गेऽस्मिन् नारदमुनेः महाविदेहगमनम् श्रीसीमंधरस्वामिनः समवषरणे प्राप्ति, चक्रवर्तिनः प्रष्नानुसारं दिव्यध्वनिद्वारा प्रद्युम्नस्य पूर्वभव सम्बन्धिनीकथा तथा च अग्निभूतिवायुभूत्योः स्वर्गप्राप्तेरित्यादिकस्य वर्णनम् अत्र अस्ति। तथा च रुक्मिण्याः विलाप वर्णनम्—

हतेथरिपुना बाले राज्यपत्न्या विचोष्टितं।

कथयामि समासेन जन्तूनां च दयाकरम्।।

बालेहृतेथरिपुना विबुधा रुक्मिणी तदा।

विलोकयति सर्वत्र बालं सर्व गुणाकरम्।।

तल्यंतनूज रहितं तया दृष्टं यदा तदा।

परिवारं तया प्रोचे परं चकित मानसा।।

भो भो परिजना यूयं कथयत्वतियोगतः।

ममापहाययातोहि क्वासौबालो गुणाधिकः।।

इत्युक्त्वा सा पुनष्चिंतां कर्त्तुं लग्ना विचक्षण।

किं वा सुर कृता माया चेन्द्रजालं भवेदिदम्।।

स्वप्नोथवा किमथवा दृषो मे तिमिरं ननु।

चित्ते वा शून्यता जाता ममकिंवात सम्भवा।।

हृतोसुरेण में बालः केनापि पूर्वा वेरिणा।

चेटिकाया करे किं वा रमनाय स्थितोर्भकः।।

धात्रिकाया समीपेस्ति पयः पानार्थमेव किं ।

किं वा परिजनैः नीतोरमणायाति प्रेमतः।।

इति विकल्य जालं हि कृत्वा नाना विधं तु सा।

मूर्छामवाप्य निष्चेष्टा जाता प्रेम भरालसा।।

देवेनदारुणे नासौ हतो बालोतिवेगतः।

भूमौपयात सहसा मुक्तके साथ तेन किं।।

ततः परिजनैर्वोधं नीता सा तु विचकक्षणा।

कृत्वाषीतोपचारं हि हरिचन्दन सम्भवं।।

वक्षौजघान हस्ताभ्यां मुक्त कंठरुरोदसा।

कुर्वती करुणासक्तो परिवारजनं तदा।।

हार्बल क्व गतोसि त्वं हा हा कुटिलकुन्तला।

हा सुनासिकलायुक्तः पूर्णचन्द्र निभानन।।

हा हा कमलनेत्रोसि भू विकार युतोसिहा।

कामपाष समो नूनं कर्णयाषोसिहासुत।।

हा हा कम्बुसमः कंठोवर्त्तात तव सुन्दरः।

हा हा करिकराकारौ दृढौ बाहूतवै वहि।।

इति नाना विधैर्वाक्यै रुदितारुक्मिणी यदा।

अन्तः पुरं च कृष्णस्य रुदितं तु तदाखिलं।।

तदायौरजनाः सर्वे ज्ञात्वा वृत्तं तथैव तं।

विलापं परमं चक्रु ल्लोकानां दुःखकारणम्।।

तद्विलापं समाकर्ण्य रुदितं यादवायपि।

तारहार समाकारैस्तत्र तैर्वाष्पबिन्दुभिः।।

आकस्मिकं च तं नादं श्रुतांनेव कदाचन।

विबुद्धः सहसाकृष्णः श्रुत्वा तत् चातिदुःखदं।।

सात्विकी मुनिना कथितं व्रतादिनाम् वर्णनम्–

मुनिर्जगाद हे वत्सौ श्रूणुतां धर्म कारणं।

पापं वृक्षकुठारं यद् बीजं धर्म महातरो।।

सम्यक्त्वां मलनिर्मुक्तं निःषंकादिगुणैयुतं।

पंचधाणुव्रतं प्रोक्तमहिंसापूर्णकं हि यत्।।
षिक्षाव्रत चतुर्द्धेति त्रिविधं तु गुणव्रतं।
एवं द्वादषभेदैष्च श्राद्धानां तु व्रतं मतं।।
रात्रौतु भोजनं त्याज्यं त्याज्यं वासर मैथुनं।
जिनपूजादि षट्कर्म कर्त्तव्यं चतुरै नरैः।।
मद्यमांसादिकं त्याज्यं सर्वातीचारवर्जितं।
आस्थानादिकमेवात्र कंदमूलादिकं तथा।।
पुष्पादि सकलं त्याज्यं शासनेयच्च दूषितं।
पुष्पितं विदलं धान्यं निंद्यं पापकरंपरं।।
परोपकारणं यत् च कर्त्तव्यता सदापरनिंदा।
संसारात् तारणेतं त्रिधाज्यत्पजेत्।।
धर्ममेवं विधं प्रोक्तं दषधाजिनषासने।
तदेव भव्यजीवानां संसारात् तारणेक्षमं।।
इत्थं ज्ञात्वा निजेचित्ते भवद्भ्यां धर्मकारणं।
सर्वपाप विनाषाया कर्त्तव्यो धर्म संग्रहः।
विप्रौमुनेर्वचः श्रुत्वा पितृभ्यां सहितौ तदा।
चक्राते संग्रहं तस्य जैनधर्मस्य भक्तितः।।
सम्यक्त्वा परमं प्राप्य निर्मलं जिन भाषितं।
पितृ मातृ युतौ तौहि तुष्ट चित्तौव भूवतः।।
धर्मरत्नं समासाद्य कस्य तुष्टिर्नजायते।
अमृतेतु तथापीते संतोषः सर्वजन्तुषुः।।
निंद्यमानौ जनैः कष्चित् कैष्चित् संस्रूयमानकौ।
मुनिं नत्वा पुरंयाता युक्तबन्धुसमाकुलं।।

सप्तमसर्गः— सर्गेऽस्मिन् द्विषतम् (200) श्लोकाः सन्ति। अत्र प्रद्युम्नकुमारस्य तृतीय भव सम्बन्धिनीकथा, मणिभद्रपूर्णभद्रयोः धर्मस्वरुपश्रवणं, तयोः स्वर्गलोकगमनं मित्यादिकम् वर्णितम् अस्ति। तथा च कौषल नाम्नः प्रदेषस्य वर्णनम्—

अस्त्यत्र भारते क्षेत्रे विषयः कौषलाभिधः।
स्वच्छासरः समाकीर्णः स्वर्गलोक इवापरः।।
चम्पकाषोकपुन्नागनारिगवकुलाः कुलाः।
वाटिका यत्र राजन्ते पुष्पप्रकरशोभिताः।।
वापिका यत्रसन्नीरैः पूरिताः पंकजावृताः।
स्वर्णसोपानराजीभिः वर्त्तते श्री विभासुराः।।
श्रियंमानसकासारसन्निभां धारयंति याः।
सरांषि यत्र राजन्ते ससारसनिः Üवनैः।।
सरितः प्रसरन्नीरं पूरपूरित विग्रहाः।
गम्भीरावर्त्त संयुक्ताः शोभन्ते बुद्धिवल्लभाः।।
मेद्यवद्गुहिरैणीरणादैः संपुरितांतराः।
दानलब्धपाराष्ध विभ्राजन्ते महोज्ज्वला।।
पुंड्नक्षुवाट संकीर्णा राजन्ते यत्र भूमयः।
स्थाने स्थाने सदानल्य शोभाभरविभासुराः।।
कुक्कुटोत्पात संलक्षा यत्र ग्रामामनोरमा।
धनधान्य समाकीर्णः परोपद्रव वर्ज्जिता।।
यत्र स्वप्नेपि दुष्काला श्रूयतेन हि जातुचित्।
सप्ते तयो न लोकेषु न चौरापद्रवस्तथा।।
पराभवोथकस्यापि कोपि कर्त्तुं क्षमो नहि।
नातं को व्याधिजो यत्र श्रूयतेकर्णगोचरः।।
धनदैवधनाकीर्णः संकीर्णः पुण्य कर्मभिः।
न्यायनिष्टो गुणैर्ज्येष्टा यत्र वासीजनो भृषं।।

श्रीमहेन्द्रसूरि मुनिना निर्देशित मोक्षप्राप्तेः उपायानां वर्णनम्—

मुनिः जगाद हे भूप श्रूणु सर्वं समासतः।
येन जीवस्यबन्धः स्यात् येन वा मोक्षसम्भवः।।
मिथ्या त्वा विरती योगात्प्रमादो बन्ध कारणं।

कषायास्क्त जिनैः प्रोक्ताः प×चविंषति संख्यका।

अश्रद्धानां तु तत्वानां पदार्थानां तथैवच।
मिथ्यात्वायोगतो नूनं कारणं बन्धसम्भवं।।
तन्मिथ्यात्वं द्विधाप्रोक्तं जिनेन्द्रै ज्ञानलोचनैः।
स्वभावात् च तथैका तातदेव बन्धकारणं।।
संशयादिक भेदेन मिथ्यात्वकर्मयोगतः।
पापश्रवस्य सम्बन्धात् बन्धः प्रोक्तोजिनोत्तमैः।।
तथा प्रकृति युक्तानां अष्टानामपि कर्मणां।
बन्धयोगेन बन्धः स्याद् शुभाश्रवयोगतः।।

1. बन्धकारणं– मिथ्यात्व, अविरत, प्रमाद, कषाय, योग

2. मिथ्यात्व– निसर्गज (अगृहीतमिथ्यात्व) गृहीतमिथ्यात्व

गृहीतमित्थात्व– एकान्त, विपरीत, संषय, विनय, अज्ञान मिथ्यात्व।

संक्षेयतोपि बोधव्या मिथ्यात्वस्य महीपते।
परिणाम कृतासंख्या विकल्प त्रिषु धीमता।।
तथा विरतयष्चात्र द्वादषैव नराधिप।

योगाः प×चदषाः ख्याता प्रमादाष्चापिततप्रमा।।

बन्धस्य कारणं सर्वे त्वं जाना हि महीपते।
अधुना कथ्यते ते हि कारण मोक्ष सम्भव।।
विष्णेषः क्रियतेयच्च जीवस्यापथकर्मणः।
दर्षनज्ञानचारित्र त्रयं तस्यापि कारणं।।
जीवादिसप्ततत्वानां श्रद्धानं दर्षनं मतं
दर्षनेन विना मोक्षो न भूतो न भविष्यति।।

पुण्य संचयस्य महत्वस्य वर्णनम्–

सुकृतस्य प्रभावेन जायन्ते त्रिदषालये।
चैत्यालये जिनेन्द्रानां कुर्वन्तो महिमावरां।।
सुरांगणामुखां भोज मधुपाना समानतां।
भजन्ति सर्वदा तेहि सौख्य सागर मध्यगाः।।
नव यौवन संपूर्णा वलीपलित वर्ज्जिताः।

धातुभिः सप्ताभि हीनाः तृप्तदेहाः सुधाषनैः।।

एवं नाना विधैः सौख्यैर्भोगैः नाना वधैः तथा।

न जानन्ति गतं कालं पूर्व पुण्य प्रभावतः।।

पुण्यात् स्वर्गे तथा मुक्तौ नृलोके भूभुजादिजं।

प्राणी सौख्यमवाप्नोति नूनं सम्यक्तव संयुतः।।

पुण्यात्प्राणी भवति नितरां कामरुपेण तुल्यः

प्राज्यराज्यं निरुपमगुणं प्राज्ञतास्वल्यता च।

कीर्न्तिः कोतिर्विपुल विलसतू शौर्यता भाग्यराषेः

किं किं तेषां भुवनतलयेः पदार्थो सर्वमेव।।

अष्टमसर्गः— अत्र षोडषाधिकचतुः शतम् (416) श्लोकाः विद्यन्ते। अत्र प्रद्युम्नकुमारस्य पूर्वभवस्य कथा तथा नारदेन कृष्णपुत्रस्य वृतान्तं श्रुत्वा रुक्मिण्या प्रसन्नतायाः वर्णनं कृतम् विद्यते। तथा च राज्ञः पद्मनाभस्य राज्ञी धारिण्याः वर्णनं मधुकैटभस्य जन्मनः च वर्णनम्—

पÁनाथ इति ख्यातो भूपः तत्र मनोहरः।

प्रतापतिर्ज्जितारातिः कीर्त्तिव्याप्त दिगंतरः।।

यथा स्वर्गेनराधीषः पातालेन्नगाधिपः।।

प्राज्यं राज्यं करोत्यत्र न्यायपालित भूतलः।।

तस्यासीत्सुन्दराकारा श्यामामंथरगामिनी।

नवयौवनसम्पन्ना सर्वावयवसुन्दरा।।

शचीवसुरराजस्य यथेषस्यपनगात्मजा।

प्रिया हि धारिणीनाम चेत्र श्चोरण तत्पराः।।

तसार्द्धं नराधीषष्चक्रे राज्यं मनोहरं।

यथा भागं भाथा सौख्यं पूर्वपुण्यप्रभावतः।।

कुर्वाणे तु तथा राज्यं भूपाले हि तया समं

मुतयुग्मं परं जातं च्युत्वा च त्रिदषालयात्।।

तस्याः कुक्षि समुद्भुतं सर्वलक्षण संयुतं।

पूर्वपुण्यभावेन लभ्यते चिन्तितं खलु।।

अद्योमधुरिति ख्यातो द्वितीयाः कैटभाभिधः।

महोत्सवोनरेन्द्रेण कृतः पुत्र समुद्भवे।।

रुपयौवन सम्पूर्णो सर्वलक्षण लक्षतौजातौ।

तौ यौवनारम्भे सर्वावयम सुन्दरौ।।

भूपतिर्योग्य सम्बन्धैः कुलरूपगुणोचितैः।

विलोक्यकन्यके रम्ये चक्रे पाणिग्रहं तयोः।।

नवमसर्गः– अत्र अष्टनवत्याधिकप×चषतम् (598) श्लोकाः विद्यन्ते। अत्र षोडषलाभानाम् विद्यानाम् च प्राप्तिः पितृभात्रोर्विरोधः, नारदस्य आगमनम् इत्यादिकस्य वृतान्तस्य वृहद्रूपेण निरूपणं कृतम्। तथा च कालसंवरकनकमालयोः अतिरिक्तं प×चषतम् साम्राज्ञीनां प×चषतम् विद्याविषारदपुत्राणां वर्णनम्–

वर्तन्ते तस्य भूपस्य नारीणां शतपंचकम्।

जातास्ताभ्यस्तु प्रत्येकां पुत्रा विद्याविषारदाः।।

कनकमालया षोडशलाभं लब्ध्वा स्वश्रेष्ठ पुत्रं आशीर्वाद प्रदानस्य वर्णनम्–

पुत्रं विलोकयामास लाभैः षोड्षभिर्युतं।।

सर्वलक्षण सम्पूर्णं नवयौवन भूषितं।

स्वकीय यषसा व्याप्तं विष्वं सर्वगुणास्पदं।।

स कोमलैः सुनीलैष्च भंगुरैरायतैस्तथा।

एवं विधैष्चितं केषै षिरस्तस्याति सुंदरं।।

कृष्ण श्वेतसु रक्तादि त्रिविधायत लोचनं।

चन्द्रवद्वदनं सौम्यं कम्बुकंठ मनोहरं।।

मेरुभित्ति समाकार वक्षस्थल विराजितं।

मृगराजासमं मध्यर्मिभनाथ गतिषुभं।।

तप्तकांचन संकाष शरीरं गुण मन्दिरं।

उपमानां समूहेन युक्तां तस्य शरीरकं।।

नारदेन प्रद्युम्नाय कथनं यत् श्रीकृष्णनारायणः भवतः पिता इत्यस्य वर्णनम्–

जगाद वचनं रम्यं श्रृणु वत्स ममोदितं।।

माकृथा त्वं वृथा दुःखं यदहं बंधु वर्ज्जितः।

बांधवा बहवः सन्ति तद् वृत्तान्तं निरूप्यते।।

द्वारिकायाः पति नूनं केषवोनामचक्रभृत्।

हरिवंषाभिधेवंषेयादवानां षिरोमणिः।।

भर्त्तुः प्राण समाना हि जननी रूक्मिणी तव।

रूपलावण्य संयुक्ता गुणानामनघालया।।

दशम सर्गः— सर्गेऽस्मिन् प×चप×चादषदधिककैकसहस्त्रम् (1055) श्लोकाः सन्ति। अत्र प्रद्युम्नस्य मातृदर्षनम् तथा च सेनानाम् सज्जीकरणस्य वर्णनं वृहद्रूपेण कृतम् वर्तते। तथा च हस्तिनापुरे कुरुवंषीनां राज्ञां साम्राज्ञीना×च वर्णनम्—

हस्तिनापुरे राजा दुर्योधन समाहुयः।

कुरुवंष समुद्भूतो वर्त्तते गुण सागरः।।

आदिनाथस्य तीर्थेयो दानतीर्थ प्रवर्त्तकः।

श्रेयान्र्निति विख्याताय यथार्थो जनता प्रियः।।

तद्वंष भूषणमनिः कुरूनाम भवन्नृपः।

यस्य नाम्नाति विख्यातः कुरूवंषो भुवस्तले।।

क्रमा च तत्र वंषे भून्नृपाणां तु सहस्रकं।।

बहुषु भूमिनाथेषु व्यतीतेषु पुरे वरे।।

धृतोनामनराधीषो विख्यातक्षिति मंडले।

तिस्रस्तस्यैव संजाता रामा विख्यातमूर्त्तयः।।

प्रथमान् गुणरूपाढ्ययाहिवांबाभिधानका।

द्वितीया त्वं अम्बिका नामा तृतीयाम्बालिकाख्यया ।।

अजनिष्ठ सुतास्तासु नृपतिर्धृतनामकः।

आद्योपि धृतराष्ट्राख्यः पांडस्तु विदुरास्तथा।।

क्रमेणापि त्रयस्तासु सुता विख्यात कीर्त्तयः।

धृतराष्ट्राभिधः प्राप गांधारीनामिकां प्रियां।।

दुर्योधनस्य तनयायाः उदधिकुमार्याः वर्णनम्–

विदधात्यधुना राज्यं दुर्योधन महीपतिः।

तस्यास्ति देहजा नूनं विख्यातोदधिनामकः।।

रूपं सच्चरितं चैव गुणान् लावण्यमेव हि।

वचो मधुरताचैवं विद्या च विनयं तथा।।

शरीरं च तथा नेत्रे भातिभामंडलं परं।

लोकाबोधित वृतं च चरित्रं चापि चारूता।।

लीलया ललितं चैव कलानां निवहस्तथा।

तस्याः कोगदितुं शक्तो बृहस्पति समोपिहि।।

भाग्यफलस्य वर्णनम्–

साधन्या खेटभूपस्य पत्नीकनकमालिका।

यया बाल्यं तु ते दृष्टं वर्द्धितस्त्वं सुपुण्यतः।।

धृतोदरे मया नूनं नवमासां च क्लेषतः।

प्रसूतश्चाति दुःखेन नियतं पुण्य हीनया।।

अथवा कस्य दोषोयं दोषोवै निजकर्मनः।

भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्।।

धर्मोपदेशस्य वर्णनम्—

मातुः कार्यमनेकधासु विहितं कामेन ते नामुना।

तत्सर्वं जिनधर्मतः शुभतमं ध्येयं सदाप्राणिभिः।।

धर्मतः सकल मंगलावली धर्मतः स्वजन बंधुसंगम।

सोमसौम्यममलं मनोहरं धर्म एव तदहो विधीयतां।।

एकादशसर्गः—अस्मिन् सर्गे चतुविंषत्यधिकद्विषतम् (224) श्लोकाः विद्यन्ते। अत्र प्रद्युम्नस्य युद्ध वर्णनं स्वजनानां दर्षनं, विवाहोत्सवस्य वर्णनं कृतमस्ति। तथा च श्रीकृष्णप्रद्युम्नयोर्मध्ये संग्रामस्य वर्णनम्—

आकाशे च तथा भूमिं दिक्कं च जनार्दनः।

वाणौघैः स्छादयामास कोपसंछन्न विग्रहः।।

छादयंतं समालोक्य वाणैर्विष्वं ततोहरेः।

अर्द्धचन्द्रैण चिछेद धनुरस्य मनोभव।।

पातयामासछत्रं च ध्वजं च सारथिं तथा। — युग्मं

तुरंगांष्चापरिजनं कामदेवस्य केषवः।

तावदन्यं समारुह्यं रथं वेगान्मनोभवः।

गुरुमात्मसमं चक्रे मायया किं न साध्यते।।

दिव्यं स्पंदनमारुह्य हरिर्वाहयदुत्तमः।

क्रोधादाहूय सद्विद्यां मुमोचहुद्भुकं शर।।

स गत्वाथ शरोदिव्यं प्रलयानलसन्निभः।

दहियमान्मथं सैन्यं परिवेष्ट्वा समं ततः।।

सछीत्कारं क्वचिद्वर्िः करोत्याश्रश्य शक्तितः।

ष्भत्कारं च क्व चिद्भीमं स्फुलिंगाणुनिरुद्धदिक्।।

कटकांतं स्फुटोद्दीप्तेह गद्वाटक भूषणः।

प्रपद्यमानमालोक्य पावकं मजमस्तदा।।

सस्मारवारुणं बाणं वाणासन परिग्रहः।

शरासनगतं वेगात् चिक्षेप च रिपुं प्रति।।

युग्मं– सोपिगत्वा महामेद्यः शक्तचाप विभूषितः।

गर्ज्जन् सो दामिनी युक्तो विमुंचणभतोषनि।।

मुसलाकारधारेभिः प्रवर्षणभता जलं।

नाषयन्मास वेगेन कृषानुमकृषत्विषं।।

अग्नि बाणमथात्मीयमव लोक्यापसारितं। – युग्मं

वायव्यस्त्रं महावेगं मुमोच मधुसूदनः।

तेनक्षिप्ता नरेभाष्वरथाष्चापि विदूरतः।।

छात्रकेतु ध्वजै सार्द्धं पत्र संघाइव क्षणात्।।

रतिप्रद्युम्नयोर्विवाहः उदधिकुमार्याः सहितस्य अष्टाधिकं पंचिशतं कुमारीणांविवाह वर्णनम्–

कालसंवर खेटेन कृष्णेन सबलेन च।

उत्सवैर्विविधैर्युक्तो जगामासौ वनं मुदा।।

कामरत्योर्विवाहो भूत् तत्रैव सुंदरं वनं।

आनन्दः स्वजनानां च जात्येत्यं तं सुखां वहं।।

पंचषत्यष्ठ संख्याष्च सुररामासमास्तुयाः।

प्राप्तास्तेनैव कामेन कन्या उदधिपूर्वकाः।।

परीणीय महाभूत्या विवेष नगरीं स्मरः।

खेचरै रेव विहितो विवाहो विष्णु वाक्यतः।।

द्वादश सर्गः– अस्मिन् सर्गे सप्तषट्युत्तरम् द्विषतानित (267) श्लोकानि सन्ति। अत्र प्रद्युम्नस्य पुण्यफलस्य वर्णनं। तथा च श्रीकृष्णस्य सारथी पद्मनाभेः सुधारकस्य, वीर नाम्न महामन्त्रिण बुद्धिसेनस्य गरुड़तोः सेनापतेः जयसेन नाम्नः पुत्रस्य जाम्बुवत्या शम्बुकुमारस्य तथा सत्यभामायाः जितभानोः नाम्नः पुत्रस्य जन्मनः वर्णनम्–

सुमुहुर्त्ते शुभेयोगे सुलग्नेच शुभे दिने।

असूततनयं तन्वी रम्यं जाम्बवती शुभं।।

स्फुरन्मणि समाकारं नीलरोचिं मनोहरं।

सर्वलक्षण संपूर्णा सर्वावयसुंदरं।।

समयेथतास्मिन्नेव कृष्णभूपस्य सारथेः।

पद्मनाभेष्च पुत्रो भूत्सुधारक समाद्वयः।।

वीराभिधो महामन्त्री तस्यैव कृष्णभूपतेः।

तत्रैव समये तस्य पुत्रो भूत् बुद्धिसेनकः।।

गरुडकेतुरितिख्यातः तस्यैवच चमूपतिः।

जयसेनाभिधः पुत्र संजातः समये वरे।।

त्रिभिरेकदिनोद्भूतैः र्ववृधे मदनानुजः।

महोत्सवः परं जातो दान पूजा पुरस्सरः।।

वंदिनां वंदिमोक्षो भूत् तस्मिन् जाते सुतोत्तमः।

शम्बुस्तु स्वजनैः सर्वैः स्ततो नाम प्रतिष्ठितं।।

सत्यभामा सुतं रम्यमसूत शुभ लक्षणं।

जितभानुं शुभानुं च तस्य नाम प्रतिष्ठितं।।

सर्वलोक प्रियौरम्यौ शुभ वेष धरौ परौ।

संपूर्णं चन्द्रवदनो पद्म नेत्रौ मनोहरौ।।

सर्वासां यदुनारीणां करपंकज वासिनौ।

नेत्रचित्त हरौबालौ दृष्यतेषद्यदौयद्य।।

कराच्चकरसंचारं लालितौ लक्षणान्वितौ।

भूषणैर्विविधैयुक्तौ कामभानु समर्पितैः।।

रणन्नूपुर संयुक्तौ किंकिणीभिः विराजितौ।

ललितानि पदानीह दातुं तत्र समुद्यतौ।।

कामभान्वनुजौवीरौ क्रमात् वृद्धिंमुपागतौ।

कामः शम्बुकुमारं च पाठयामास प्रत्यहं।।

भानुः सुभानुतोमानमनुजं वर लक्षणं ।

पाठयामास सिद्विद्यां कला कौषलमात्मनः।।

कलागुण विदग्धौ तौ जातौ द्वोच कुमार कौ।

ललितं बाल्यवेषं हि व्यतिलंध्यगुणोद्वलौ।।

त्रयोदश सर्गः—अस्मिन सर्गे एकनवत्युत्तरम् एकषतम् (191) श्लोकानि सन्ति। अत्र श्री नेमिनाथस्य विवाहवर्णनं, वैराग्यवर्णनं, दीक्षावर्णनं, ज्ञानसमवषरणं, देषनादिवर्णनं, विहारादिवर्णन, पूर्णरूपेण दृष्यते तथा च संसारस्य भ्रमणं तथा च संसारस्य भ्रमणं नाषी धर्मस्य विवेचनतम्

गम्भीरां मधुरां वाणीं सप्तभंरी समन्वितां।

जगाद जलदाकारो जिनेन्द्रो भव्य नायकात्।।

चतुर्नियोगसारां तु द्वादषागमयावरं।

रत्नत्रयेन संयुक्तां सप्ततत्व प्रमानिकां।।

द्विविधं तु जिनः प्राह धर्मं संसार नाषनं

परं तपस्विनामाद्यं ततोन्यद्गृहमेधिनां ।।

त्रयदंष विधं तत्र चारित्रं व्योमवाससां

महाव्रतानि पंचैव पंचैव समितीं स्तथा।।

तथा च गुप्तयस्तिस्रो भाषिता श्री जिनेष्वरैः।

अष्टाविंषति संख्याता नूनं मूल गुणाः स्मृताः ।।

तथोत्तर गुणास्तत्वन्ये संतितास्तत्र सहस्रसः।

प्रत्यहं पालनीयानि तथैवावष्यकानि षट्।।

एवं विधं जिनेद्रोक्तं चारित्रं निर्मलं मुनिः।

पालयित्वा तु प्राप्नोति मोक्षसौक्षं हि शाष्वतं।।

पंचैवाणुव्रतानिस्यु स्त्रिविधं च गुणव्रतं।

षिक्षाव्रतानि चत्वारि श्रावकानां व्रतान्यमी।।

सम्यक्त्वा ज्ञान चारित्रं त्रितयं रत्नं परं तु।

पालनीयं सदा भव्यैः श्रावकाचारमुत्तमं।।

मद्य मांस मधुत्याग पंचोदुम्बर वर्ज्जनं।

अष्ठौ मूल गुणा प्रोक्ताः गृहस्थानं मुनीष्वरैः।।

अज्ञात भाजने भोज्यं कुपुष्प कुफलानि च।

हदृचूर्णं सदाहेयम पक्व लवनादिकं।।

नवनीतं स सदा त्याज्यं कंदमूलादिकं तथा।

पुष्पितं बिदलं चैव धान्यमनंत कायकं।।

आरणालं च तक्रंच शाकपाकादिकं तथा।

दिनद्वयगतं त्याज्यं सर्वातीचारकारकं।।

चर्मभांड स्थितं यच्च घृतं तैलं जलं तथा।

मांसदोषकरं तत् नग्राह्यं श्राद्धै विवेकिभिः।।

पानीयं तत्क्षणेगाल्यं प्राश्रुकं दोषवर्ज्जितं।

तथाज्ञात फलं त्याज्यं ग्राह्यं श्रीजिनभाषितं।।

मिथ्यात्वं दूरतः त्याज्यं सप्तैव व्यसनानि च।

रात्रौ तु भोजनं हेयं तथा वासर मैथुनं।।

कुदेवांष्च कुषास्त्राणि कुगुरुन् कुधर्मं तथा।

मनसापिन चिंतव्यमेतत् संसार वर्द्धनं।

देवपूजादि षट्कर्म कर्त्तव्यं प्रत्यहं बुधैः।

दुर्लभं त्रिषु लोकेषु धर्मं श्रीजिन भाषितं।।

इति श्रुत्वा जिनेन्द्रोक्तं धर्मं सर्व नरामरा।

सन्तोष परमं प्राप्यनमताः श्रीजिनेष्वरं।।

भगवतः पावन चरित्रश्रवणस्य महत्वस्य वर्णनम्—

ये ये भव्य जना जिनेन्द्र चरितं शृण्वंति चित्तादरात्।

विवाहादि महोत्सवैः परियुतं वैराग्यमेवामलं ।।

दीक्षा ध्यान विषेषतोषि विमलं ज्ञानं च सद्देषनां।

सौम्यत्वं गुणगेहता चतुरता तेषां गृहे सर्वदा।।

चतुर्दश सर्गः—अत्र एकनवति (91) श्लोकाः सन्ति। अस्मिन् सर्गे बलभद्रप्रष्नं, जिनेन्द्र देवं च कृत भविष्य निरूपणस्य वर्णनं विद्यते। तथा च ध्यानस्य चत्वारः प्रकाराः तथा त्रिषष्ठी शलाका पुरुषाणां चरित्र वर्णनम्—

तथा चत्वारि ध्यानानि कथितानि जिनेष्वरः।

आर्त्तरौद्रं तु संत्यज्य धर्मे शुक्लं तु गृह्यते।।

गुणास्थानानि प्रोक्तानि चतुर्दष जिनेष्वरैः।

तथाच्चैव समुदिष्टा मार्गणाष्च चतुर्दष।।

दषलाक्षिणि को धर्मो जिनेन्द्रैः प्रतिपादितः।

तपो द्वादष भेदं तु बाह्याभ्यंतर योगतः ।।

इति जैनं वचः श्रुत्वा त्रिषष्टि पुरुषोद्भवं।

प्रपछ चारितं कृष्णः कृत्वा करपुटं निजं।।

जिनेन्द्रेण तदा प्रोक्तं प×चकल्याणं संयुतं।

गुरवोपि पुराणीह नाम स्वर्ग पुरातनं।।

नगराणि पितामाता नक्षत्राणि तथैव च।

उत्सेधं वर्णभेदंतु वंषो राज्यं तथैव च।।

तपो ज्ञानं तु निर्वाणं स्थानं भूपतिभिः समं।

प्रत्येकं षट्चत्वारिंषत् भेदा प्रोक्ता जिनेषिनां।।

षट् खण्ड भूमिपतयष्चक्र नाथास्तु द्वादष।

वदेवास्तु हरयस्तथैव प्रतिषत्रवः।।

तेषां पुराण वंषोपि पिता माता तथैव च।

यस्यतीर्थे समुत्पन्नास्तत् सर्वं प्रतिपादितः।।

उत्पत्तिं च प्रबुद्धिं च मरणं च तथैवहि।

इति श्रुत्वा सभा जाता वैराग्येन विभूषिता।।

श्रीकृष्णस्य मृत्यु कदा कथचि भविष्यति ? प्रश्नमिदं बलदेवेन जिनेन्द्रं प्रति पृष्ठस्य जिनेन्द्रस्य उत्तरदानस्य वर्णनम्–

कर्णांजलिपुटैः पीत्वा तज्जिनेन्द्र वचोमृतं।

हृष्टः सर्वेहली चैवं प्रपछ निज वांछितं।।

अनाद्यं कृत कं नाथ जातस्य ध्रवुं मतिः।

अतोद्वारावतीनाषो मरणं च हरे कुतः।।

इति पृष्टो जगौ नेमिः पुरीमद्येन हेतुना।

साधोः द्वीपायनादस्माद्य वषावे च विनस्यति।।

मृगया व्यसन स्थाच्च कौषांब वनमाश्रितात्।

जरत्कुमार तो विष्णुः मृतिस्यादिषुघाततः।।

श्रुत्वै तज्जिन वाक्यं हि सर्वे जाता भयकुलाः।

यथा संपदि सौख्यं स्यात् तथा विपदि दुःखतः।।

पचिदशसर्गः अस्मिन्, सर्गे सप्तदषोत्तरमेकषतम् (117) श्लोकाः सन्ति। अत्र प्रद्युम्नकुमारस्य भानुकुमारस्य तथा च अष्ट महिष्यः च दीक्षाया वर्णनं कृतमस्ति। तथा च प्रद्युम्नकुमारस्य राजसभायां आगमनं –भगवतः जिनस्य दीक्षाप्राप्तेः ज्ञान प्रदानं यदुवंषीनां च सन्ताप वर्णनम्–

अथैकदा सभामध्ये निविष्टो मधुसूदनः।

सेव्यमानो जनौद्यैस्तु पाकषासन सन्निभः।।

पूरयित्वा सभां दिव्यां यादवोधैः समंततः।

किंचित् च शंकया युक्तो दिव्ये सिंहासनेमुदा।।

सामन्तैः सचिवैः सर्धैस्तथा विद्याधरैरपि।

बलभद्रादि भूपैस्तु परीतो रवि सन्निभः।।

गंगातरंग संकाषैः वीज्यमानसुचामरैः।

षोडषाभरणोपेतो कौस्तुभालं कृतोहृदि।।

पुष्पत्पयोजव वनष्चात्र शोभित मस्तकः।

नानाकलाविनोदैष्च लोकै रंजित मानसः।।

कुलकं अत्रांतरे समागत्य राजपुत्रैः समन्वितः।

शांतोगुण षतैः पूर्णः सर्वविद्या समन्वितः।।

विषयेभ्योविरक्तात्मा कृष्णस्या स्थान मंडपं।

नत्वा हरिं निविष्टोसौ मदनो विष्टरे वरे।।

क्षणमेकं ततः स्थित्वा लब्धा कथावसानकं।

स्नेहं सुदुस्त्यहंत्यक्त्वा वैराग्याहत चेतसा।।

ललाटे स्वांजलिं कृत्वा विनयान मस्तकः।

याचयित्वा भयं कामो जगाद मधुसूदनं।।

स्वामिंस्तव प्रसादेन जातिरूपकुलादिकं।

सर्वेभोगोपभोगास्तु लब्धा सौख्य करामया।।

भुक्त्वा विलोकिता सर्वे दृष्यतेत न शाष्वताः।

नित्यतारहिता तात साः वा सांसारिकी स्थिति।।

कुरु प्रसाद मधुनादेहि त्वाज्ञां मम प्रभो।

मोक्षसौख्याय यद्यन्नं करोमि कृपया तव।।

दीक्षांजैनेष्वरीं तात गृहणामि भवनाषिनीं।

असारं सर्व संसार वर्त्तते दुःख कारकं।।

तस्योदितं समाकर्ण्य वसुदेव पुरस्सराः।

कृष्णाद्यायादवाः सर्वे शोकात् निष्चलतांगता।।

भानुकुमार–सत्यभामा–रुक्मिणीं –जाम्बुवती प्रभृतीनां दीक्षाप्राप्तस्य वर्णनम्–

ततो भानुकुमारोपि वैराग्य रंगलालसः।

मातापित्रादिकं सर्वं पृष्ट्वा बंधुजनं निजं।।

मुक्त्वा राज्यस्य चिंता च राजपुत्रैः समन्वितः।

विलोक्य सर्वलोकौघै दीक्षां जग्राह निर्मलां।।

गृहीते सति चारित्रै भानुनामकुमरेणहि।

दुःखितास्तत्र संजाता लोकाहरि समन्विता।।

सत्यभामा तथा भीष्म तनया गुण पूरिता।

जांबुवत्यादयोदेव्यो गत्वा जिनसभांतरे।।

तत्रगत्वा जिनं देवं राजीमत्या समीपके।

धूतरागाः स्त्रियाः सर्वादधुदीक्षां मनोहरां।।

नीत्वा दीक्षा च ताः सर्वाः सितवस्त्र समन्विताः।

समुद्यतास्तयो घोरं तप्तुं वैराग्य संयुताः।।

षोडश सर्गः

चतुर्सप्तत्युत्तरमेकषतम् (174) श्लोकाः सन्ति। श्री नेमिनाथस्य, प्रद्युम्नस्य, शाम्बस्य, अनुरुद्धस्य निर्वाणस्य वर्णन प्रमुख रूपेण वर्ण्यते। तथा च आर्तरौद्रादि ध्यानानां सर्वथा परित्याग करणं धर्मध्यानं शुक्लध्यानं सादरं करणे वर्णनं विद्यते।

आर्त्तिरौद्रादि कुध्यानं त्रिघातत्याजसन्मुनिः।

धर्म शुक्लादिभेदेन चक्रे ध्यानं महादरः।

आवष्यकं चकारासौ मनोभव मुनीष्वरः।

कायोत्सर्गेण रात्रौतु ध्यानी मौनी हि तिष्ठति।।

लोकाक्रोसकै रुद्रैष्च तथैव ताडनैरपि।

आदरेणनिर्मुक्तै भाषणैर्भर्त्सनैस्तथा।।

अचालितांतःकरणो विवेकीहि क्षमायुतः।

निष्चलोमेरुणातुल्यः कामदेवोमुनीष्वरः।।

प्रस्थाने शयने स्थाने भोजने तु विलोकने।

विमर्षने तु सच्चेष्टे पठने पाठने तथा।।

प्रषांत ह्रदये योगी शुभ चेष्टा समन्वितः।

मार्दवं परमं विभ्रद्रराज शुभ चेष्टया।।

प्रद्युम्नचरित्रस्य सम्पादनम् संस्कृतजगतः जैनसमाजस्य च कृते कल्याणाय अलौकिकपरलौकिकाभ्युदाय च भविष्यति।

(iii) लेखकस्य परिचयः

भट्टारकसोमकीर्तिः संस्कृतभाषाया प्रसिद्धो विद्वानासीत्। अयं श्रमणसंस्कृतेः, साहित्यस्य, शिक्षादीञ्च महान् प्रचारक आसीत्। लक्ष्मीसेनस्य द्वौ शिष्यौ आस्ताम्। प्रथमः भीमसेनः द्वितीयश्च धर्मसेनः। उभाEयामपि पृथक्-पृथक् स्वभट्टारकस्थानं संस्थापितम्। भीमसेनस्यैव शिष्यः सोमकीर्ति- रासीत्। अयं भीमसेनस्य समीपे कुतः, कदा, समायात इति विषये ज्ञानं न प्राप्यते। एतदतिरिक्तं अस्य पित्रोः, जन्मस्थानस्य, शिक्षादिक्षयोर्विषये किञ्चित् ज्ञानं न सEप्राप्यते। एतदेव ज्ञायते यत् विक्रमाCदे 1518 तमे वर्षे काष्ठासंघनदीतटगच्छस्य भट्टारकपदे अभिषिकतोऽभवत्। तस्मिन् दिवसे आषाढ़मासस्य शुDलपक्षस्य अष्टमी तिथिरासीत्। अयं 87 तमः भट्टारक आसीत्। अस्य पटाभिषेकः गुर्जरप्रान्तस्य सोजित्रानगरस्य शान्तिनाथस्य मन्दिरे अभवत्।

भट्टारकपदे समलङ्कृतानेन गुर्जरराजस्थानप्रान्तयो विभिन्न भागेषु व्यहरत्। जनसEपर्कं विधाय अहिंसाधर्मपालनार्थमुपादिशत्। अस्य प्रसिद्धिः विक्रमाCदस्य 1518 तमे वर्षे सञ्जाता किन्तु यावज्जीवं प्रकाशमाननक्षत्रमिव प्रकाशत। श्रीमता जोहरापुरकरेण स्वभट्टारकसEप्रदाये अस्य समयः विक्रमाCदस्य

1526 तमात् वर्षात् आरHय 1540 तमं वर्षं यावत् सEमुलिखितः यश्च प्राप्तपट्टावल्या न मिलति।

ब्रह्मश्रीकृष्णदासेन विलिखितम् यत् यवनशासकाः अपि अस्य सEमानं कुर्वन्तिस्म।[4]

प्रद्युEनचरिते अस्य परिचयविषये लिखितोऽस्ति यत् लक्ष्मणसेनस्यशिष्य भीमसेनः, भीमसेनस्य शिष्यः सोमकीर्तिरासीत्। अयमत्यधिकः प्रभावशाली आसीत्। सEप्रतिप्राप्तग्रन्थाः अनेन स्वयमेवविरचिताः, समाजाय प्रतिष्ठाव्रतविधानयोरुपदेशं चकार।[5]

(iv) ग्रन्थकारस्यकृतित्वं–

अयं राजस्थानीसंस्कृतभाषयो: उद्‌भटो विद्वान् आसीत् उभयोरपि भाषयो: अस्य लेखनी अबाधरूपेण चलति स्म। अयं करRिव्यपरायण आसीत्। अस्य निEनलिखिता: संस्कृत रचना: सन्ति–

(i) प्रद्युEनचरित्रम्

(ii) सप्तव्यसनकथासमुच्चय:[6]

(iii) यशोधरचरित्रम्[7]

(iv) अष्टाह्निकाव्रतम्

(v) समवसरणपूजा।

एतदतिरिक्तं राजस्थानीभाषायां अधोलिखिता: ग्रन्था: विलिखिता: ते च इमे:–

(i) यशोधररास:

(ii) गुरूनामावली

(iii) ऋषभनाथस्य धूलि: (रिषभनाथ की धूल)

(iv) त्रेपनक्रिया गीतं

(v) आदिनाथप्रार्थना (आदिनाथ विनती)

(vi) मल्लिजिनगीतम् (मल्लिजिन गीत)

(vii) लघुचिन्तामणि पार्श्वनाथ जयमालः।

एषां ग्रन्थानाम् स्वरूपविषये संक्षेपेण विवेचनं क्रियते।[8] प्रद्युEनचरित्रं शोधप्रबन्धस्य प्रमुखविषयत्वात् अस्य विषये अग्रे विवेचनं करिष्यते सEप्रति अन्येषां ग्रन्थानाम् स्वरूपविषये समासेन निरूपणं क्रियते।

(v) समस्याः

विष्वस्य प्राचीनतमा भाषा संस्कृतं वर्तते। ऋग्वेदो वदति देवी वाचमजनयन्त देवास्तां विष्वरूपाः पशवो वदन्ति। सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुण्टुतैति। भाषायाः प्रादुर्भावः लिपिज्ञानात् प्रागेव जायते। भाषायाः समुपलब्धिः लोके वाक्य ज्ञान पूर्वं भवति। भाषा ज्ञानं विना कस्यापि समाजस्य विकासः कदाचिदपि न सम्भवति तस्मादुक्तं हरिणा–

'' इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्।

यदि शब्दाींयं ज्योतिरासंसारं न भासते।।''

अस्य समग्रस्य ज्ञानं बुद्धि विना न जायते।

लिपेःसमस्याः– प्रस्तुतस्य प्रबन्धस्य या पाण्डुलिपिः वर्तते पठने अतिक्लिष्टा प्रतिभाति। अस्य क्लेषस्य निवारणं पाण्डुलिपि विषिष्टानां पण्डितानां पं. श्री उदय शंकर शास्त्री महोदयानां चार्ट फलकेन जातम् ग्रन्थेऽस्मिन् शास्त्रिवर्येण लेखनकर्मणि कियत् वैषिष्ट्यं जायते प्राचीन समये कस्य वर्णस्य लेखनं किमासीत् कथं तत्र हासोवृद्धिष्चाभवत् एतत् सर्वं विचारितम्। शास्त्रि महोदयस्य समीक्षात्मकं ग्रन्थमधीत्य यथा ज्ञानं कार्यं मया साधितम्। गुर्जर प्रान्तस्य ग्रन्थागारे एतादृषो ग्रन्थोमया लब्धः यत्र अक्षरसंघानां, वर्ण समाम्नायानां विष्लेषण पूर्वकं कार्यं कृतं वृर्त्तते। तद्ग्रन्थाच्च सहयोगः प्राप्तः।

अनन्तरं सम्पादनकार्यस्यापरा समस्या पाठालोचनस्य भवति। ग्रन्थस्य मूलो लेखकः यत्किमपि लिखति तत् प्रकृति पाठः भवति। मूल पाठस्य रक्षणं सर्वेरालोचकैः कर्त्तव्यम्। मूल पाठः लेखकस्य स्वहस्त निर्मितो भवति। पाठालोचने बहुत्र अस्यष्टोवर्णः लुप्तःपाठः सन्दिग्धपाठः द्वित्वपाठष्च प्राप्यते अस्यकृत्स्नस्य निराकरणं

पाठालोचन प्रक्रियया सम्पद्यते। पाठालोचन विषये अनेकेषां विदुषां प्रामाणिकाः गन्थाः निबन्धाः शोध प्रबन्धाष्च प्राप्यन्ते प्रायेण एतेषां बहुनां ग्रन्थानां सदुपयोगः मया प्रबन्धस्य सम्पादने कृतः। तथापि काचित् समस्या शब्दार्थयोः समाधाने अवषिष्टा आसीत् यथा मात्रा विकृतः, अक्षर विकृतः, विभक्तअक्षरविकृतियुक्तः युक्ताक्षरविकृतियुक्तः, अलंकरणयुक्तःविकृतियुक्तष्च, नवरूपाक्षर युक्त शब्दः, लुप्ताक्षरी शब्दः, आगमाक्षरीः, विपर्याक्षरी शब्दः, संकेताक्षरी शब्दः,श्संख्यावाचक शब्दः वर्त्तनीच्युत शब्दः भ्रमात् स्थानापन्न शब्दः, अपरिचितः शब्दः, आसां सर्वासां सम्पूर्णानां[9] समस्यानां धैर्य पूर्वकेण समाधानेन परमेष्वरस्य कृपया प्रबन्धोऽयं सफलोऽभवत् यतोहि दोषाणामपाकरणं कृत्यैव किमपि लेखनं कर्त्तव्यम् प्रबन्धः सदा नवीनानां पाठकानां गवेषकाणां मार्ग दर्षनाय भवति तस्मात् सावधानेन यथाज्ञानं कार्य सम्पादितम्। कार्यं भगवतः कृपया सम्पन्नम्।

(vi) शोधप्रबन्धस्योद्देश्यम् :–

मम शोध प्रबन्धस्य ''आचार्य सोमकीर्त्तिकृत प्रद्युम्नचरित्रस्य सम्पादनं समीक्षण×च'' इत्याख्यस्य मुख्योद्देष्यं अस्ति असत्याचरण–कपटाचारव्यवहारं न्यायोपार्जनं– अत्याचार–दुराचार विष्वासघात–अषिष्टता इत्यादि दोषाणां दमनं कृत्वा अस्य प्रद्युम्नचरित्रस्य माध्यमेन सच्चरित्रता–सुखसमृद्धि–सत्यता–प्रेमोदारता सहनषीलता–विनम्रता–षिष्टता–सहानुभूति प्रभृतीनां गुणानां सृजनं विधाय प्राणीमात्रस्य कल्याणमेव मुख्य ध्येयं अस्ति।

चरित्रस्य निर्माणं विधाय समस्त सद्गुणानां प्रसारं परिवारस्–समाजस्य –देषस्य तथा संस्कृत साहित्यस्य कृते वरदानं सिध्यति। तथोहि सच्चरित्रतया मानवस्य कृते सुन्दरं स्वास्थ्यं परिष्कृताष्च बुद्धिः प्राप्यते। सदाचारस्य सच्चरित्रस्य च अभावे मानवः पशुवत् जीवनं याप्यते। सम्पूर्ण जीवने च आत्मग्लानि असन्तोषस्य च ज्वालायां दग्धो भवति। अनेन शोध ग्रन्थेन मानवस्य मनसि नैतिकतायाः दायित्वस्य च ज्ञानं प्राप्यते। यो जनः स्वकीय जीवने आनन्दोल्लासस्य उन्नतेः समृद्धेः पुण्यानामर्जनं स्वर्गे च स्थानं अन्ये जन्मनि च श्रेष्ठ योनिं प्राप्तुमिच्छति। स आजीवनं धार्मिक प्रवृत्तिनामनुभवम् करोति। आत्मिकषान्त्याः सन्तोषस्य च प्राप्त्यर्थं स आसां मान्यतानां अनुसरणं करोति। धार्मिक मान्यताः न तु अवैज्ञानिकाः सन्ति न च काल्पनिकाः। कस्यापि वस्तुनः लाभं महत्वं रहस्यं च ज्ञातुं विना तस्योपरि श्रद्धाः आस्था तथा प्रीत्याभावो स्वाभाविकं अस्ति। यतोहि धर्मस्य आधारः विष्वासश्रद्धयोरूपरि स्थितोऽसि तथा तस्य प्रवृन्ति ह्रदयेन भवति। अनेन अप्रत्ययेसन्देहे भयेसतिरपि केनापि वस्तुना सम्पूर्ण लाभो न प्राप्यते।

अनेनोद्देष्येन मया प्रद्युम्नचरित्रस्य पाण्डुलिपिं पुस्तरूपे सम्पादनार्थं गृहीतं यस्मिन् धर्मस्य सम्बन्धे वैज्ञानिक आधुनिक दृष्टिकोणयुता ज्ञानं संगृहीतम् आस्ति। अनेन न केवलं विचारणार्थं नूतनं दृष्टिपूर्णं प्राप्स्यते अपितु

प्रद्युम्नचरित्र सम्बन्धि जिज्ञासानां समाधानं अपि भविष्यति। मदीयाभिलाषा वर्त्तते यत् भारतीयाः संस्कृति संस्कत प्रेमिणष्च अस्य प्रद्युम्नचरित्रस्य स्वकीय जीवने आत्मसातं कृत्वा स्वलोक परलोकं सम्यक् साधयिष्यन्ति।

(vii) क्षेत्रम्

भारतवर्षीय संस्कृत ग्रन्थ समुदाय सम्बन्धी चरित्रकालं प्राधान्येन द्विधा विभज्यते। तत्राद्यो वैदिककालः। द्वितीयस्तु लौकिक संस्कृतकालः। साहित्यषास्त्रस्य चत्वारि महदङ्गानि मन्यते–प्रथमम्–शब्दार्थ भाषा विज्ञानस्य अतिरिक्त शब्दतः अर्थं यावत् गन्तुं शब्द शक्तयः सन्ति। अस्यैव एकं पक्षं साहित्यषास्त्रे ध्वनिः अस्ति द्वितीयं अङ्गरसोऽस्ति। साहित्य शास्त्रिणः काव्ये नवरसानां प्रविष्ठा कृताः अस्ति। तृतीये अंङ्गछन्दः चतुर्थञ्च अलंकारःअस्ति।

रसस्य ज्ञान साहित्यिक पाण्डुलेखस्य कृते सर्वोपरि अस्ति। प्राचीन काले ग्रन्थ लेखने पद्य एव सर्व प्रचलितं तथा लोकप्रियं माध्यम् आसीत्। यतोहि पद्यस्य रचना विधानं छन्दोपरि निर्भरं भवति तथा तस्य स्मरणं गद्यस्यापेक्षा सरलं भवति। अनया दृष्ट्या छन्दो ज्ञानं प्राचीन हस्तलेखानां पाण्डुलिपीनां कृते च सामान्यतः आवष्यकं मन्यते। अलंकारः अपि साहित्यषास्त्रस्य महत्वपूर्णं अंङ्गअस्ति।

अस्य प्रयोगः हस्तलेखेषु पाण्डुलिपिषु च प्राप्यते अस्य चरित्रकाव्यस्य तुलना विभिन्न धर्माणां चरित्रैः कृत्वा अस्योपयोगिता सिद्धं कर्त्तुं शक्यते। साहित्य शास्त्रस्य सिद्धान्ता–भाषाषैली व्युत्पत्तिरपि महत्वपूर्णास्ति।

एता सर्वाः पाण्डुलिपिनां विषेषताः आवष्यकताः च सन्ति, येन पाण्डुलिपेः विषयवस्तुना आत्मसात कर्त्तुं शक्यते।

—प्रथमसर्गः—

श्रीमन्तं सन्मतिं नत्वा नेमिनाथं जिनेष्वरम्।

विश्वजेतायि मदनो वाधितुं नो शषाकयम्।। 01 ।।

वर्धमानं निजं नत्वा वर्द्धमानं सतामिह।

यद्रूपदर्षनाज्जातः सहस्त्र नयनो हरिः।। 02 ।।

प्रणम्य भारतीं देवीं जिनेन्द्र वदनोदϑताम्।

कृष्णपुत्रस्य चरितं वक्षे सूत्रानुसारतः ।। 03।।

यदुक्तं चात्र विद्वद्भिर्महसेनादि सूरिभिः।

तत्कथं शक्यते नूनं मया वालेन भाषितुम्।। 04 ।।

तथापि तत्क्रमां भोज प्रणामार्ज्जित पुण्यतः।

श्रीप्रद्युम्नाभिधं ग्रन्थं प्रवक्तुं मे श्रमोनदि।। 05 ।।

सज्जनानां नमो नित्यं सदा निर्मलचेतसाम्।

परोपवादमूकानां सर्वसत्वोपकारिणम् ।। 06 ।।

दुर्ज्जना अपि नंदंतु छिद्रानवेषणे तत्पराः।

येषां प्रसादमासाद्य नैपुण्यं जायते नृणाम्।। 07 ।।

क्व चरित्रं हरे सूनो क्वा चाल्पविषयामतिः।

बाहुभ्यां सागरं घोरं तरितुं केन शक्यते।। 08 ।।

मन्दः कवित्वकामोहं यस्यां इत्युपहास्यताम्।

उच्चवृक्षफलाकांक्षी याति कु×जोपि लाघवं।। 09 ।।

व्याकरणं न जानामि छन्दोऽलंकार नाटकं।

पुण्योत्साहवषाःकुर्वे चरित्रं पापनाषनं ।। 10 ।।

सुरेन्द्राजिनपूजायां कुर्वंति कुसुमैः वरैः।

नरास्तां किम् न कुर्वन्ति कÈारिपत्रसंचयैः।। 11 ।।

जिनसेनादिभिः पूज्यैराचार्यै यः निरुपितम्।

करोमि शक्तिहीनो हन्तत्यादां वुजसेवनात्।। 12 ।।

श्रोतव्यं सज्जनैः सर्वैः भव्यजीवैर्विषेषतः ।

वदतां श्रणवतां नूनं चरित्रं पापनाषनम्।। 13 ।।

मयामन्द धियाप्याजनं चरित्रं क्रियते शुभं, ।

पापषत्रुविनाषाय केवलम् पुण्य हेतवे।। 14 ।।

भव्यराषिप्रबोधार्थं पुण्यदृष्टान्तकारणम्।

वालधी वृद्धि सिद्धयर्थं क्रियते सुगमम् मया।। 15 ।।

अस्ति जंबूद्रुमाकारो द्वीपो जंबूद्रुमाभिधाः।

वाहिनीनाथ संसेव्यः सुवृत्तोनृपतिर्यथा।। 16 ।।

तत्रास्ति भारतं नाम क्षेत्रं च क्षिति विश्रुतं।

तीर्थं तीर्थकृतां स्थानैः पवित्रं पाप नाषनम्।। 17 ।।

तत्रवै मगधो नामदेषोऽसौ विदितो भुवि।

वापी कूपतडागादिवनैः नाना विधैः युतः।। 18 ।।

श्रीमद्राजग्रहं तत्र विख्यातं नगरं भुवि।

जिनेन्द्रः भुवनैः भाति भूमौ स्वर्णनगरीसमं।। 19 ।।

तत्रास्ति श्रेणिकोनामभूपालोविदितोभुमि।

शत्रुराषिविजेया योनिर्मलोऽतिविवेकवान्।। 20 ।।

दुष्ट निःक्रन्दको नूनं साधुपालनतत्परः।

श्रावकाचार संयुक्तः सम्यक्यतवे न विभूषितः।। 21 ।।

तस्यास्तिः चेलनानामजायामायाविवर्ज्जिता।

निर्ज्जिता स्वर्वधूरूपा निजरूपस्यसंम्पदा।। 22 ।।

पापभीतागुणैः ख्याता गुणराषिप्रपूरिता।

सम्यकेन च संयुक्ता श्रावकाचारनिर्मला।। 23 ।।

कुलद्वयविषुद्धा या पतिस्नेहभरालसा।

जिनेन्द्रमार्गे कुषलासतीगुणधुरन्धरा।। 24 ।।

तयासहानिषं राजा भुजानो विविधं सुखं।

न जानाति गतं कालं निमग्नसुखसागरे।। 25 ।।

एकदा विपुलोद्याने गिरौ विपुलनामनि।

समायतं जिनेन्द्रस्य शरणं समवादिकं।। 26 ।।

वर्द्धमानं जिनेन्द्रस्य युक्तस्य मुनिनायकैः।

गणेन्द्रः सेव्यपादस्य भूषितस्य त्रपुश्रिया।। 27 ।। युग्मं ।।

जिनेन्द्रस्यप्रभावेन वनं जातं सुषाद्वलां।

वनपालोपिवनं दृष्टवा विषेषविभवान्वितं।

चिन्त्यमानो वने सोपि बभ्रामः प्रविलोकयन्।। 29 ।।

भ्रममात्र वने दृष्टं शरणं समवादिकं।

तस्य दर्षन मात्रेण प्रमोदेन प्रपूरितः।। 30 ।।

नीत्वासौवनजाता निःष्फलानि विविधानि च।

प्रतीहारोपदेषेन ययौ राज सभां तरे।। 31 ।।

भूपालोस्य पुरोमुक्ताफलपुष्पाणि तानि च।

नमस्कारं ततः कृत्वा जगादैवं वचोवरं।। 32 ।।

श्रृणुराजन् महाभाग वनेतव समागतः।

वर्द्धमानजिनेन्द्रोऽसौकेवलज्ञान भूषितः।। 33 ।।

तस्यदेव प्रसादेन चिरंजीवनराधिपः।

भवसर्वगुणाधारो धनधान्ययुतोध्रुवं।। 34 ।।

समागतं जिनं श्रुत्वा श्रेणिकोऽसौ नराधिपः।

सिंहासनात् समुत्थायवेगात्सप्तपदानि च।। 35 ।।

तां दिषं सततो गत्वा प्रणःमाम जिनेष्वरम्।

परोक्षे विनयं कृत्वा सज्जनानां हि लक्षणं ।। 36।।

उपविष्य पुनः सोपि रम्ये सिंहासने तदा।

वनपालस्यप्रददौ षोडषा भरणानि च।। 37 ।।

दापयित्वां नंदभेरीं मेलियित्वा जनंधनं।

वेदनार्थं ययौ भूपः परिवारेण संयुतः।। 38 ।।

दूरतोऽथनृपो दृष्ट्वा शरणं समवादिकं।

राजादुत्तरितो वेगात् जहौ राज्यपरिग्रहः।। 39 ।।

मानस्तंभ प्रभावेन गतमानो बभूवः सः

परयाभावभूत्पासौ भूषितोऽभून्नराधिप।। 40 ।।

त्रिः परीत्यजिनं तत्र संयोज्यकरकुंजलौ।

गद्यपद्यैः स्तुतिं चक्रेपरमाह्लादपूरितः।। 41 ।।

त्वमधीषस्त्रिजगतां त्वं वंद्योसिसतांविभो।

संसार सागरे घोरे नाव तुल्योऽसि हे विभो।। 42 ।।

कामषत्रुविजेतासि मोहमल्लविनाषकः।।

चिंतितार्थपदोनूनं चिन्तामणिरिवापरः।। 43 ।।

ज्ञानमूर्त्तिमयोसि त्वं तेजोमूर्त्तिस्त्वमुत्तमः।

स्वयंभुवः स्वयंबोधा सहजानंदपूरितः।। 44 ।।

निर्जिताषेषदुःखादि जरामरण विवर्ज्जितः।

रत्नत्रयनिधानोऽसि मानमायाविवर्ज्जितः।। 45 ।।

वेदषास्त्रे तथा ध्याने गीते ध्येयस्त्वमेव हि।

सूर्यकोटिसमो दिप्त्या कांत्याकोटिषिं प्रभाः।। 46 ।।

तवदर्षनमात्रेण पापंयाति नृणां ध्रुवं।

शंकरः शकरोलोके विष्णुर्व्याप्तजगत्त्रयः।। 47 ।।

परब्रह्मयुतोऽसित्वं दुरितारिहरोहरः।

संसारवासमुक्तोऽसि तारकस्त्वं त्वदाश्रितान्।। 48 ।।

लक्ष्मीनाथो जगन्नाथो धर्मनाथोदयानिधिः।

वर्द्धितासुखपरम्परानो वर्द्धमानजिनेष्वरः।। 49 ।।

इति स्तुतिः विषेषै सः स्तुत्वादेवं जगत् गुरुं।

प्रणम्यपरया भक्त्या पूजांचक्रेविधानतः।। 50 ।।

जलगंधाक्षतैः पुष्पैनैवेद्यदीपैर्धूयसत्फलैः

पूजामष्टविधानकृत्वा नरकोष्टेन्यवीविषत्।। 51 ।।

धर्मं श्रुश्राव भूपोसौ सागरेतर भेदतः।

ततो त्रयतिनामाद्यं द्वितीयं गृहिणां मतं।। 52 ।।

यतिधर्मां ध्रुवं मोक्षो द्वितीयात् स्वर्ग संभवः।

त्रयोदषविधं नूनं चारित्रं कथितं जिनैः।। 53 ।।

महाव्रतानि पंचैवतत् प्रमास्क्त सामितयः।

गुप्तयष्चत्रयः प्रोक्ताष्चारित्रं यतिनामिदं।। 54 ।।

अष्टाविंषति विख्याता गुणामूल गुणाभिधाः।

तथोत्तरगुणाः प्रोक्ता इदं स्यात् मोक्षसाधनं।। 55 ।।

अतः सागारिणां नूनं कथ्यते व्रतजातयः।

पंचधाणुव्रतं प्रोक्तं त्रिविधंस्याद~xq.kozraAA 56 AA

षिक्षाव्रतं चतुर्भेदमेवं द्वादषधास्मृतं।

अष्टौमूलगुणाः प्रोक्ता गृहिणां मुनिनायकैः।। 57 ।।

गार्हस्थ्याधर्म योगेन स्वर्गेस्यात् प्राणिनां।

गतिः हिताहितं विचार्यादौ कर्त्तव्यं भव्यजंतुना।। 58 ।।

श्रुत्वाद्विविधं धर्मम् प्रमोदेन प्रपूरितः।

धर्मश्रवणमात्रेण भव्यास्तुष्यति निष्चितं।। 59 ।।

ततः प्रस्तावमासाद्य धर्मं श्रुतेरनंतरं।

करयोसंपुटीकृत्यनृपः प्रोवाच श्रेणिकः।। 60 ।।

भगवान् श्रोतुमिछामि चरित्रं मदनस्यवै।

कथं तस्य समुत्पतिः कथं चाहरणंरिपोः।। 61 ।।

किं तेन निर्मितंधर्मं का विभूतिरभूधरा।

का युक्तिःका शक्तिष्च वीर्यं धैर्यं कथं किमु।। 62 ।।

तत्सर्वं श्रोतुमिछामित्वत्प्रसादाधि भो ध्रवुं।

संदेहध्वातं सूर्योसि संदेहमेनिराकुरु।। 63 ।।

तदाजगादभगवान् भव्यपृष्टं नराधिप।

प्रद्युम्नापिचरित्रं तु पापनाषनकारणं।। 64 ।।

पुण्योदयंविनाजीवैः श्रोतुं तं नैवलभ्यते।

भव्याभव्यात्मनां नूनं प्रमाणं लेभ्यते स्फुटं ।। 65 ।।

नृणां श्रवणमात्रेण चातुर्यं हृदि।

भव्यराषि विवोधार्थं चरित्रं प्रतिपाद्यते।। 66 ।।

सावधानतया मतिमान् स्थिरं कृत्वा मनोनिजं।

चरित्रं शृणु राजेन्द्रं कृष्णपुत्रस्य श्रेणिक।। 67 ।।

तदा सर्वा सभाजातो स्थिरचित्तदृढ़ासना।

उत्तमानां चरित्रं हि श्रोतुमिछति सज्जना।। 68 ।।

पृष्टे श्रेणिक भू भुजा सुनिर्मलविषदे दिव्ये चरित्रेवरे।

प्रोचेतं जिननायको मुरुरिपोः सूनोष्चरित्रं शुभं।। 69

*** इति श्री प्रद्युम्नचरित्रेश्रीसोमकीर्ति आचार्यविरचिते श्री श्रेणिक प्रश्नवर्णनो नाम प्रथमःसर्गः।। ***

—द्वितीयसर्गः—

अथास्ति सर्व द्वीपेषुमध्ये जम्बूपलक्षतः।

द्वीपोजम्बूद्रमोनामविख्यातः क्षितिमंडले।। 01 ।।

तत्रैव भारतं नामक्षेत्रं भाति विषेषतः।

दक्षिणस्यां दिषिर्स्थं यं तस्य का वर्णनापरा।। 02 ।।

तीर्थं तीर्थकृतां तीर्थैः पवित्रं पापनाषनं।

यत्रागमनं देवानां जिनकल्याणकारिणं।। 03 ।।

तत्र क्षेत्रपरं ख्यातोदेषः सौराष्ट्रिकाभिधः।

राजते स्वर्गतुल्योयं प्राणिनां पुण्यकर्मणां ।। 04 ।।

यत्रेक्षुसरसावाटावालैराकंपिता अपि।

नायांतिपामराणां हि भूमौ वंधभयादितः।। 05 ।।

सरौवरानि यत्रैव कमलैः पूरितानि च।

राजहंसैः सषब्दानि राजन्ते सर्वदा भुवि।। 06 ।।

सरितो यत्र भांतिस्मजलैः राप्तरिताभंष।

तटद्वयस्थवृक्षाणां वसिताः पुष्पराषिभि।। 07 ।।

राजंतेवापिकानूनं नीरराषि प्रपूरिताः।

कुर्वन्तिः कोकवदनैः स्वागतंताः प्रवाषिणां।। 08 ।।

स्थाने स्थाने प्रयांरम्यादानषालाः पदे पदे।

कुक्कुटोत्यातसंलक्षा यत्र ग्रामामनोहराः।। 09 ।।

उद्यानैर्विविधैर्युक्तः स्वर्गलोकइवापरः।

कृतपुण्यजनानां हि सृष्टो सौवेधसा भुवि।। 10 ।।

शालिवप्रावभुर्यत्रसाकपिंडा पदे पदे।

शालयस्तेषु राजंतेनम्नाः पातुं जलं यथा।। 11 ।।

सर्वधान्याकरायत्र दृष्यते सर्वदा ध्रुवं।

दोर्भिक्षं संभवीवार्त्ता श्रूयते न कदाचन।। 12 ।।

सरसाः शाड्वलादेषा राजन्तेवाह्यभूमिषु।

सर्वायत्र प्रदर्ष्यं ते गोधनैर्ध्वलीकृताः।। 13 ।।

नागवल्लीभिराष्लिष्ठाः पूगवृक्षावने वने।

ताम्बूलार्थं नायत्र चूर्णं नीत्वा व्रजंतिहि।। 14 ।।

मोचचोचमयावृक्षाः स्फुरत् द्राक्षादिमंडपाः।

संवलेन विना लोकायांति यत्र प्रवासिनः।। 15 ।।

तस्मिन्नेवं विधेदेषे पुरी स्वर्णगरीसमा।।

राजते द्वारिकानामा प्रसिद्धाक्षितिमंडले।। 16।।

वापीकूपतडागादि वनवाटीविराजित।।

अमरावतीवलोके समैता लोक पुण्यतः।। 17 ।।

आवासयत्रराजन्ते सप्ताष्टनव भूमिका।

सुवर्णभित्ति संयुक्ता रत्नमालोपषोभिता।। 18 ।।

सुधाधौतेषुहर्म्येषु स्त्रीणांवदनषांतति।

शुक्लपक्षमयां शंकां दृष्ट्वा यत्र वर्धर्जनाः।। 19 ।।

स्थाने स्थाने प्रपायत्र पदे पदे जिनालयाः।

भव्यजीवैकृतावासाः समुत्सवविराजिता।। 20 ।।

तुंगवाप्राःपरं रम्याः समुद्रखातिकान्विताः।

नानादेषागतैर्लोकै राजते सा मनोहरा।। 21 ।।

मदन्ननिसमादायकेयं पुरी प्रयास्यति।

इतिमत्वाविवेष्टासौसमुद्रः खातिकामिषात्।। 22 ।।

चामीकरमयैर्हर्म्यैः परीतासानिरीतरं।

उपरिन्यस्तरत्नैष्च राजते वसुधातले।। 23 ।।

आपणानांततिर्यत्र रत्नराषिविराजित।

प्रत्यहं शक्रचापस्य का शेषंकां करोति या।। 24 ।।

राजमार्गा विराजन्ते यस्यापंका कुलाषदा।

निर्गमागमयुक्तानां गजानां मदयैर्जलैः।। 25 ।।

नित्यंराज कृतावासा राजधानीं परा भुवि।

शोभते नगरीं नूनं चिन्तामणिरिवार्थिनां।। 26 ।।

नारीणां तु परं रूपं दृष्टवायम्याः सुरांगनाः।

तत्यजुस्तानिजं गर्वं रूपलावण्य संभवं।। 27 ।।

किमत्रवहुनोक्तेन सा पुरीं क्षितिमंडले।

लोकत्रयस्य तन्वेनचेधसेव विनिर्मिता।। 28 ।।

तस्यां विराजतेराजा विख्यातः क्षितिमण्डले।

श्रीमन्नारायणो नामप्रसिद्धो भुवनत्रये।। 29 ।।

तदाताभोक्ता विवेकी च ज्ञान विज्ञान भूषितः।

नपरोविद्यते लोके प्रजानां हि पितेव् सा।। 30 ।।

बाल्येपि येन निहताः कंसाद्यारिपुवोवहूनू।

गोवर्द्धनैनगोदध्रेवत्सानां रक्षणायवैः।। 31 ।।

नाथितः कृष्णनागोपियमुनहद मध्यतः।

नागषय्या धनुः शंखं गृहीतं रिपुगोहत।। 32 ।।

अपराजित नामानं जरासंधेष्च भ्रातरं।

हतं रणां गणेयेन तस्य शौर्यं किमुच्यते।। 33 ।।

समुद्राख्यसुरस्तस्मै ददौ भूमिं मनोहरां।

वारिधितुं समुत्सार्य द्वादषयोजनावधिं।। 34 ।।

इन्द्रादेषं समासाद्य धन देवे विनिर्मिता।

नगरीद्वारिकानाम कृष्णभूपस्य शक्तितः।। 35 ।।

बन्धुलोकस्ययो नूनं सेवकेवबभूव च।

किं कराणां सखेवात्र प्रक्षिकपाता शरणार्थिनां।। 36 ।।

कल्पवृक्षसमोभूमौ सेवकानां सदाभुवि।

वैरिकान्तामुखेन्दूनां राहुतुल्यो विराजते।। 37 ।।

यादवानाकुलां भोधेष्चन्द्रोतित्योदयोहियः।

नास्त्यन्यो भूपतिर्भूमौयः समोलक्षणैर्गुणैः।। 38 ।।

उदयस्य कोटिषीलां यस्य वीक्ष्यपराक्रमं।

नारेन्द्रामुमुचर्मानं पराक्रममयं निजं।। 39 ।।

मनोर्थानांमप्यधिकं त्यागं यस्य विलोक्यवै।

अद्यापिनसमायाति कल्पवृक्षोस्तथा गताः।। 40 ।।

गुणानामादसेनाथ क्रियते हि त्वया कथं।

इत्युक्त्वातुगता दोषा दूरं क्रोध समन्विताः।। 41 ।।

निर्म्मलत्वं सुवृत्तत्वमाह्लादत्वं ममैव हि।

त्वयापनीतमित्युक्त्वा धत्ते चन्द्रः कलंकतां।। 42 ।।

यस्यराजः प्रयाणेभूदाकाषेचपरामही।

विश्रामकारणं चित्ते चिंतित्वारजसस्थलात्।। 43 ।।

इन्द्रोपिप्रभुतां दृष्ट्वा यस्य भूपस्य निर्मलां।

निर्जं गर्वं निराचक्रे यत्कृतं प्रभुतामयं।। 44 ।।

साधूनां पालने दक्षो दुष्टानां निग्रहेक्षमः।

गंभीरोऽसौ समुद्रेव धीरः पर्वतराजवत्।। 45 ।।

परस्त्रीणां निजंवक्षः शत्रूणां पृष्टि संयुगे।

याचकानां नकारत्वं नदत्तं तेन भूभुजा।। 46 ।।

ईहगुणगणाधारो राजाराजेव सुन्दरः।

हरिवंषीनरेन्द्राणां श्रृंगारो राजते हरिः।। 47 ।।

तस्यास्तिचाग्रमहिषीसत्यभामा मनोहरा।

सतीनामगणीभूतां गुणानाम नद्यालया।। 48 ।।

लावण्यलक्षणोपेता हावभाव समन्विता।

तर्ज्जितः स्वर्वधूरूपा निजरूपस्यसंपदा। ।। 49 ।।

लक्ष्मीचलानराधीष नचाहं चपलाकदा।

करोषि हि कथं नूनं ममत्वं कमलासभा।। 50 ।।

विनयादिगुणाधारा भर्तृछंदानुवर्त्तिनी।

कुलोभय विषुद्धाच विद्याधरषरीरजा।। 51 ।।

चन्द्रः कलंक संयुक्त प्रेक्षान्तेथक्षयावहः।

तस्यावदनसादृष्यं चन्द्रेवादीयतेकथं।। 52 ।।

वेनीदण्डकलापेन मयूरं तु जिगायसा।

ललाटेनाष्टमीचन्द्रं कीरं नासिकया तथा।। 53 ।।

नयनाभ्यां जिता नूनं तयातुमृगयोषितः।

अतएवगतामन्ये लज्जयाकुलितावने।। 54 ।।

द्विजैः कुन्दस्यकलिकामोष्टाभ्यां बिम्बिकाफलं।

कंठेन कंबुरेखां च स्तनाभ्यां श्रीफलानि च।। 55 ।।

बाहुभ्यां सुन्दराकारा मालतीमालकोपमा।

रम्यासापानिपÁाभ्यां युक्ताभ्यां शुभरेखया।। 56 ।।

उदरेणापि सिंहोद्यानू श्रोणीभ्यां गिरिभित्तयः।

उरूभ्यां कदलीस्तम्भान् जितान् मन्ये तया ध्रुवं।। 57 ।।

रक्तौसकोमलौ यस्या पादपÁो मनोहरौ।

शुभरेखा समायुक्तो राजते राज लक्षणैः।। 58 ।।

सिरीष सुकुमारांगी मातंग गति गामिनी।

सर्वषास्त्रार्थनिपुणा चतुरावाग्वधू यथा।। 59 ।।

तयाससहितौ राजा चक्रे राज्यं निरन्तरं।

कंटकैष्च विनिर्मुक्तं युक्तं वैराज्य पÁया।। 60 ।।

यथाषंभोश्चगिरिजायर्थं दृष्य पराषची।

तथा कृष्णस्य जाया सा सत्यभामाभिधाभवत्।। 61 ।।

शंपेवकालमेघस्य षिखेवषिखिनः परा।

वेलेवचसमुद्रस्य तथैवास्य बभूव सा।। 62 ।।

जिनधर्मे सदारक्तो जिनपूजापुरन्दरः।

जैनपात्रे परं त्यागीभोगीपरिजनैः सह।। 63 ।।

प्रत्यहं पालयन् राज्यं श्रृण्वन् शास्त्रं जिनोदितं।

नमन् गुरुजनं प्रीत्या कलत्रैः सहक्रीडयन्।। 64 ।।

बन्धून मानयन् शष्वत् सम्यक्त्व पालयनदृढं।

संसारं गणयन् चित्तेरंभास्तम्भ समं परं।। 65 ।।

अनेन विधिना कालं निज्येमग्नः सुखार्णवे।

यस्य भ्राता भुविख्यातो बलभद्रोतिविश्रतः।। 66 ।।

यादवानां सहस्त्रैष्च सदामानितषासनः।

विविधोद्यानेषु कृष्णो रमते सत्यभामया।। 67 ।।

गजानां मदमत्तानां वाजिनां वातरंहसां।

रथानां च सेवकानां तस्य संख्या न विद्यते।। 68 ।।

सप्तांगराज्य भूत्यासौ चक्रे राज्यं सनातनः।

गतं कालं न जानाति निगग्नः सुखसागरे।। 69 ।।

ईतिभिष्च विनिर्मुक्तं लोकानां हितकारणं।

प्राज्यंराज्यं सदाचक्रे नारायणनरेष्वरः।। 70 ।।

इति विविधविनोदैः पालयन् राज्यलक्ष्मीं गतभवकृतपुण्याल्लभ्यते किं न पुंसा।

जिनकुलवसुधांयो मु×चयित्वा विदेषेधनकनक गुणानांवारिधौ सोमतुल्यः।। 71 ।।

***इति श्री प्रद्युम्नचरित्रे श्रीसोमकीर्त्याचार्य विरचिते श्रीकृष्णविभूति वर्णनो नाम द्वितीयः सर्गः ***

—तृतीयसर्गः—

अथैकदा सभामध्ये कृष्णोराज्यश्रियायः तः।

पूरयित्वा सभां सर्वां निविष्टोवधुभिर्वरां।। 1 ।।

राज्यदेषमयी वार्तां कुर्वन् लोकान्प्रमोदयन्।

यावत् तत्र स्थितो राजा तावदन्यत्कथान्तरं।। 2 ।।

आकाषां तेजसां पुंजमागछन्तं विलोकितं

यदा तदा सभास्थानां लोकानां विस्मयोभवत्।। 3 ।।

किंवासूर्यमयं तेजः किं वा वÉमयं भवेत्।

सूर्यस्यगमनं तिर्यक्वÉर्नज्वलमूर्द्धगं।।। 04 ।।

आधोवतरतेनूनं तेजः पुंजमिदं वरं।

किं भवत् किमिदं चित्तेलोकानां विस्मयो भवेत्। ।। 05 ।।

आसन्नेचततः प्राप्ते मनुष्योयर्मितस्फुटं।

अत्यासन्नेपुनः प्राप्ते पुरुषोयमिति निष्चितं।। 06 ।।

समीपं हि समायाते नारदोवैः विचिंतितः।

इतिक्रमेण निर्णीतो लोकैस्तु नारदोमुनिः ।। 07 ।।

मृगाजिनो धरो धीरो जटाधारी वृषाकारः।

कौतुकाकुल चित्तेऽसौ नारदः कलहः प्रियः।। 08 ।।

जिनमार्गेसदारक्तोभिमानैकधनो नद्यः।

हास्येपि सततं रक्तो जिनवंदनतत्परः।। 09 ।।

समायात समीपेथतं नारद महामुनि।

समुत्थितो मुदाकृष्णः सभाया सहितस्तदा।। 10 ।।

सहसासन्मुखं गत्वा नमामविनयान्तितः।

अर्घपाद्यादिकं चक्रे कृष्णौ सौ नारदाय वै ः।। 11 ।।

निजेसिंहासनेतं हि निवेष्यनारदंमुदा।

भक्त्यासक्ततिं चकारासौ कृष्णमेतद् गृहांगतः।। 12 ।।

नारदत्वं महाभाग्यस्तपसा त्वं पवित्रितः।

समभाग्यवषानूनं मम गृहे समागतः।। 13 ।।

पवित्रंमद्गृहं नूनं कृतम् भाग्यवतात्वया।

नन्वभाग्यवतां गेहे समागच्छाति सज्जनाः।। 14 ।।

पुराकृतं मयापुण्यं शुभहेतोष्चकारणं।

साम्प्रतं मम सर्वं हि याति पापं न संषयः।। 15 ।।

त्वयाकालत्रये नाथ कृतोयोग्योत्रभूतले।

अन्यथा हि कथस्यात्रे मम गेहे समागमं।। 16 ।।

ते धन्यास्ते विवेकं ज्ञास्तेषंस्या इह भूतले।

आगच्छन्ति गृहे येषां नूनं नारदत्वादृषाः।। 17 ।।

नारदादेषमासाद्य द्वितीयेहरिविष्टरे।

निविष्टो हरि राजोपि विनयानतमस्तकः।। 18 ।।

नारदोपिजगादैव श्रृणु कृष्णवचोमम।

भवतां मिलनायात्र समायातो न संषयः।। 19 ।।

मादृषामवतारौवै केन वा कारणेन हि।

यदा भवादृषां गेहे गमनेन विवर्ज्जितः।। 20 ।।

जिनेन्द्राबलदेवाद्याः कृष्णाद्यापुरुषोत्तमाः।

विलोक्यानियतं राजन् अन्यथामादृषैः किंमु।। 21 ।।

अषेषदेषमभूतां वार्त्तां चक्रे मुनिर्वरः।

सर्वतीर्थसमानीताम् आषिषां हरये ददौ।। 22 ।।

एवं यावत्समालापो वर्त्तते मुनिकृष्णयोः।

तावत्तत्रसमायातो नेमिनाथो जिनेष्वरः।। 23 ।।

समागतं जिनदृष्ट्वा सभासर्वासमुत्थिता।

सकृष्णोनारदोप्याषुजिनदृष्ट्वा समुत्थितः।। 24 ।।

अपरे सिंहासने हि निवेष्य जिननायकं।

नारदोसौस्तुतिं चक्रे नेमिनाथस्य भावतः।। 25 ।।

जयनाथ जिनाधीष जयत्वं पापनाषन।

जरामरणदुःखानां अन्तकारो भवानषि।। 26 ।।

भुवनस्य परं चक्षुर्भव्यांभोसहभास्करः।

नूनं त्वमपरष्चन्द्रः कलांवाष्चसदोदयः।। 27 ।।

नमस्ते देव देवाय देव सेव्यायते नमः

नमस्ते जिननाथाय सर्वा कल्याणकारिणे।। 28 ।।

कामगजमृगेन्द्राय मोहाहिगरुडात्मने।

जन्ममृत्यु विनाषाय नेमिनाथाय ते नमः।। 29 ।।

स्त्रोत्रैर्नानाविधैः स्तुतित्वां निविष्टोहरि विष्टरे।

ेनेमिरादेषमासाद्य नारदो विनयान्वितः।। 30 ।।

कुशलप्रष्न पूर्वं च चक्रिरेवै परस्परं।

परमानन्दमापन्ना जिनकृष्णबलादयः।। 31 ।।

सर्वलौकैस्तदादृष्टो नारदोमुनिसत्तमः।

प्रमोदं परमं प्राप्ता लोकानारद दर्षनात्।। 32 ।।

क्षणमेकं ततः स्थित्वा नारदोवचनं जगौ।

श्रृणुकृष्ण महाभाग यन्मयात्र निगद्यते।। 33 ।।

गच्छामि विविधं देषं करोमि जिनवंदनां।

स्मर्त्तव्याप्रत्यहं राजन् त्वं वैधर्म्मस्य स्थापकः।। 34 ।।

ममेछावर्त्तते चित्ते तव सौख्य विलोकन।

सुखेन तेहं तुष्टोस्मि तव दुःखेन दुःखितः।। 35 ।।

तवांतःपुरनारीणां करोमिचावलोकनं।

त्वदृषाः सतिनार्योवानोसंतीत्यति विस्मयः।। 36 ।।

कृष्णादेषं ततः प्राप्य नारदो विस्मयाकुलः।

यातस्त्वतः पुरोवेगान्तं निरीक्षणलालसः।। 37 ।।

जगाम सत्याभवनं कौतूहलसमन्वितः।

पश्यामि सत्यभामांहि प्रथमं कृष्णवल्लभां।। 38 ।।

यावत् गत्वा मुनिः शीघ्रं तां पश्यति सुलोचनां।

तावत्सा मज्जनं कृत्वा निविष्टा हरि विष्टरे।। 39 ।।

अग्रतो दर्पणं धृत्वां पश्यन्ती रूपसम्पदां।

विभूषणानि देहे सा कुर्वन्तीह निजे तदा।। 40 ।।

पुनः पुनः स्तु पश्यन्ती निजं रूपं विभूषितं।

वहन्ती परमं हर्षं राजसन्मान संभवं।। 41 ।।

तदापृष्ठे समायातो नारदः कलहः प्रियः।

दर्पणेस्थितया दृष्ट्या न दृष्टोव्यग्र चित्तया।। 42 ।।

प्रतिबिम्ब च तं रूपं दर्पणे तस्य सन्मुनेः।

भस्मनो धूलितं वक्रं जटाभीरौद्रतां गतं।। 43 ।।

निजमुखस्य समीपे दृष्टं रोद्रं मुखं तया।

मुखंवक्रीकृतं सत्या गर्वपूरितचित्तया।। 44 ।।

चन्द्रवद्वदनं मेहि तस्य पार्ष्वे किमीदृषं।
वदनं कस्य दुष्टस्य यदिदं प्रतिबिंबितं।। 45 ।।
पृष्ठि स्थिते न मुनिना नारदेन विलोकितं।
तच्चवक्रंचवक्रचयकृतं सत्यभामया।। 46 ।।
चलितस्तत्रक्षणादेव नारदः क्रोधपूरितः।
सर्वत्र मानिनीयोऽसौ सत्यभामापमानितः।। 47 ।।
चलित्वा सोतिदुःखेन चिन्तयष्च पुनः पुनः।
कस्मान्मेमंद भाग्यस्य मतिरेवं समुदठ्गता।। 48 ।।
सत्यभामागृहेयातः कृतंयुक्तं न तन्मया।
अज्ञातकुलषीलस्य गृहे गन्तुं न युज्यते।। 49 ।।
चिन्तयन् विविधं चित्ते विचारं सोगमन्मुनिः।
विमृष्टं कारणं यच्चकैलाष षिखरं चरं।। 50 ।।
गत्वा तत्र निविष्टोऽसौ मुनिष्चिंता परायणः।
किं करोमि क्व गच्छामि कस्या दुःख शातिता।। 51 ।।
अवाद्यतेप्रनृत्यं हि करोति नारदोमुनि।
शुतेवै वाद्यनाद्वे हि किंचात्र भण्यतेस्यहि।। 52 ।।
यो माम् मानयति शक्त्या च यामिक्रोधंमप्यहं।
यो मां द्वेषति मूढात्मा तस्य किं भण्यते ध्रुवं।। 53 ।।
विचरामि महीं सर्वां सर्वलोका नमन्ति माम्।
अपमानितोस्म्यहं मेनयातु पाप चित्तया।। 54 ।।
किमस्यां तु करोमीति दुःखंस्यात्कथमुत्कटं।
पराभवोभवेदस्याः कथं पश्यामि दुःखिनां।। 55 ।।
कस्याप्यग्रे निरूप्यास्या रूपस्य वर्णनां परं।

हरामि पापचित्तां तां तदास्यादुःखताघना।। 56 ।।

चिन्तयित्वा पुनष्चित्ते चिंतयामास नारदः ।

अनया रहितो विष्णुः दुःखीस्याच्चध्रुवंह्रदिः।। 57 ।।

तस्य दुःखेनमदुःख कृष्णोमित्रं ममोत्तमं।

उपायेदं न कुर्वेहं मन्योपायं विचिंतये।। 58 ।।

परपुरुषेण युक्तां दर्षयामी हविष्णवे।

मायाविद्याविषेषेण छिप्टां तां हि करोम्यहं।। 59 ।।

क्षणात् त्यजति रामां तां प्राणेभ्योपि गरीयसीं।

परपुरुषसमाषक्त्यामुपायोनापारो भुवि।। 60 ।।

विमृष्यदं दृढं चित्ते कृतं तेन यदा तदा।

उत्पन्नं कारणं चान्यं मनोविस्मयकारणं।। 61 ।।

सतीनामग्रणी नूनं सत्यभामा गुणोज्जवला।

पतीजं परमं कृत्वास्याद्विषुद्धाति वल्लभा।। 62 ।।

तदा कृष्णो पितां दृष्ट्वा विषुद्धां गुणभूषितां।

करिष्यति कृपां नूनं स्यात् विरक्तोमयि ध्रुवं।। 63 ।।

तदा प्रभृति मे वाक्यं मानयिष्यति नो कदा।

असत्यवादिनं नूनं स त्यजन्ति विचक्षणाः।। 64 ।।

तदायास्यति मे सत्यं दुःखं स्थास्यति मानसे।

उभाभ्यां हि परिभ्रष्टो भविष्यामि कथं ध्रुवं।। 65 ।।

विमृष्येदंदृढं चित्तेतां चिन्तां च निवारयत्।

अन्यचिन्तारतो भूत्वा स्थितो नारदसन्मुनिः।। 66 ।।

विमृष्यमाणेहि चिरं बुद्धिरेखा समुद्गता।

मनोदुःख विनाषाय सत्यं ज्ञातं स्वचेतसि।। 67 ।।

नारीणां परमं दुःख सपत्नी सम्भवं भुवि।

तत्समं हि परं किंचिन्नभूतं न भविष्यति।। 68 ।।

तत्समान न वैधव्यं न दारिद्रमयं कदा।

न चापुत्रमयं लोके यत्सपत्नाभवं पदं।। 69 ।।

एवं विमृष्यमाणे हि नारदो तु पुनः पुनः।

सैव बुद्धिः समुद्भूतो निःष्चला निजमानमे।। 70 ।।

बहुधापि विमृष्यैवं दृढं कृत्वा मनोनिजं।

विलोकाणायस ूमिं सार्धद्वीपद्वयोद्भवां।। 71 ।।

समुत्थाय ततः सोपिनारदोमुनिनायकः।

कार्यं चेतसिसंधाय विलोकयितुमुद्यतः।। 72 ।।

विजयार्धनगं गत्वा राजधान्यो विलोकिताः।

प्रत्येकं भूपतीनां हि मिलित्वा परमादरात्।। 73 ।।

विद्याधराधिपा दृष्ट्वा संवेष्यभवनान्तरम्।

अन्तः पुरः समालोक्य पुनरन्यत्र गच्छति।। 74 ।।

न काव्यूढाप्यरूढा वा दृष्ट्वा खेचर मन्दिरे।

सत्यभामा पदांगुष्ठा समानं या हि गच्छति।। 75 ।।

श्रेणीद्वयं समालोक्य विषन्नो नारदोऽभवत्।

किं करोमि क्व गच्छामि विलोक्येहं क्व चेदृषी।। 76 ।।

सत्यभामा मनोदर्प्यं यावैनाषयितुं क्षमा।

विद्याधरागण, गेहेयानास्ति सा भूतले कथं।। 77 ।।

इति धृत्वा विषादं हि कृता चिन्तापराहृदि।

विलोकयामि भूलोकं मनष्चिन्तां निवारये।। 78 ।।

विमृष्यैवं तदा चित्ते भूलोकं हि समागतः।

सर्वेषां भू भुजां तत्र राजधान्यो विलोकिता।। 79 ।।

न तत्र क्वापि सादृष्टा या तुल्या सत्यभामया।
सचिन्तो नारदोनूनं वभ्राम वसुधातले।। 80 ।।
एकस्मिन् दिवसे सोपि सर्वत्रापि विलोकयन्।
भ्रमन्नाकाष मार्गेण ययोमार्गवषान्मुनिः।। 81 ।।
श्रीकुंडनपुरं रम्यं श्री निवास समुज्जवलं।
आगरंतत् च नारीणां विद्यारूपगुणात्मनां।। 82 ।।
तत्रास्ति भूपतिर्मान्यो विख्यातः क्षितिमंडले।
शत्रुपक्ष विजेतायः प्रपाताषरणार्थिनां।। 83 ।।
रूपसौन्दर्यसंयुक्तो गुणैर्मण्डित विग्रहः।
सश्रीभीष्माभिधानोहि् राजचिÊरलंकृतः।। 84 ।।
तस्यास्ति गुण संयुक्ता जाया माया विवर्ज्जिता।
श्रीमती संज्ञिता लोके प्रसिद्धा रूप सम्पदा।। 85 ।।
नरदं हि समायातं समालोक्य सभान्तरे।
सहसा समुत्थितोऽसौ विनयात् नारदंप्रति।। 86 ।।
अर्घपाद्यादिकं कृत्वा सन्निवेष्य निजासने।
विनयात्प्रणतिं कृत्वा निविष्टोन्यासनेनृपः।। 87 ।।
नारदोपिततस्तस्य कुषल प्रष्नपूर्वकं।
चकार विनयोपेतं दृष्ट्वा भीष्मानराधिपं।। 88 ।।
स्नेहालापादिकं कुर्वन् स्थितौमुनि नृपौ यदा।
तदा तत्र स्थितं दृष्टं मुनिना नृप पुंगवं।। 89 ।।
तं भूपति सुतं दृष्ट्वामुनिष्चिंतामुपागतः।
अस्य चेत् भगिनी नूनं भविष्यति गुणान्विता।। 90 ।।
तदा मे सफलाः सर्वे भविष्यन्ति मनोरथाः।

इति कृत्वा तदा चित्ते भूपतिः पृष्टवान् यतिः।। 91 ।।

कस्यायंभूपते पुत्रो यः स्थितष्चावयोः पुरः।

ततो जगाद भूपोपि कृत्वाचाधोमुखं निजं।। 92 ।।

ममायंहियते पुत्रस्तवपाद प्रसादतः।

तदाहि मुनिनाप्रोक्तं भव्यं भव्यं नराधिपः।। 93 ।।

ऊढानूढेति सा कन्या पृष्टोसौमुनिनायदा।

ततोपि च नरेन्द्रेण प्रोक्तं श्रृणु महायते।। 94 ।।

दत्तेयं वर्त्तते कन्या षिषुपालाय भूः भुजे।

इतिश्रुत्वा मुनिः प्राप्तोहर्षंपारविवर्ज्जितं।

किंचित्कालं स्थितं तत्र कुर्वन् गोष्ठीं मनोहरीं।

विलंव्य कियतीं वेलां उत्थितो मुनिपुंगवः।। 96 ।।

जगाद भूपतिं स्नेहाद्विनया नतमस्तकं।

तवसौधं जगामीति राजंस्तवदक्षया।। 97 ।।

ततोभूपतिना प्रोक्तंहर्षपूरितचेतसा।

पवित्रं क्रियतां नाथ सौधं मम मनोहरं।। 98 ।।

इत्युक्तेनारदः सोपिगतः श्चांतःपुरेवरे।

तत्रास्ति भूपतेर्भग्नी विधवाबालतो हिया।। 99 ।।

तयासमागतो दृष्टो नारदो मुनिनायकः।

उपलक्ष्यमुनिं तं हि ज्ञात्वा नारदसंज्ञिकं।। 100 ।।

अभ्युत्थानादिकं कृत्वा दत्वासन्मानमुत्तमं।

मुक्त्वा सिंहसनंचाग्रे प्रणुतामुनिमब्रवीत्।। 101 ।।

उपविष्यतां विभोचात्र दिव्ये सिंहासने नधे।

तस्यावचनमासाद्य निविष्टो विष्टरे वरे।। 102 ।।

उपविष्टेहि मुनौ तत्र जगौ भीष्मानुजातदा।

भव्यं कृतं विभोनूनं यत्वमत्र समागतः।। 103 ।।

त्वयाहि पद पÁाभ्यां पवित्रं मन्दिरं कृतं।

न तु पुण्य विहीनानां मिलयन्ति त्वादृषानराः।। 104 ।।

एवमुक्त्वा तयाताहि युवत्यो भीष्म भूपतेः।

नारदस्य मुनेः पादौ प्रणामं कारितावरं।। 105 ।।

प्रणुतास्तायुवत्यो सादाषीर्वादेन तोषयत्।

कुर्वन् पुण्यमयीं वार्त्तां स्थितो यावत्ऋषीष्वरः।। 106 ।।

तावत्तेनाग्रतो दृष्टा स्थिता सा रुक्मिणी।

च सा तेन भीष्मानुजापृष्टा केयं बाला मनोहरा। ।। 107 ।।

ततो भीष्मानुजा वोचत् श्रृणुनाथ निगद्यते।

एषा भीष्मनृपस्यैव पुत्री श्री रुक्मिणी वरा।। 108 ।।

एवममुक्त्वा तयासंहि नमिता मुनिपादयोः।

तदाहिमुनिना तस्य दत्ताषीः सर्वमुत्कटा।। 109 ।।

वत्से भवाग्रमहिषी नूनं कृष्ण महीभृतः

मुनिवाक्यं हितंश्रुत्वा रुक्मिणी चकिता हृदि।। 110 ।।

पितृप्वसामुखं तत्र विलोक्य विस्मयाकुला।

समस्ययाहि सापृष्टां किमुक्तं मुनिनामुना।। 111 ।।

मुनिं जगाद सा तत्र किमुक्तं मुनिनायकः।

त्वपासकः समाख्यातो नारायण समाह्वयः।। 112 ।।

क्व निवासोस्य कृष्णस्य किं कुलं हिवयं तुकिं।

किं रूपं कीदृषी रिद्धिः कुटुम्बं वद कीदृषं।। 113 ।।

नारदोपि ततो वोच श्रृणु वत्से निगद्यते।

यादृषं कृष्णभूपस्य कथ्यते स्वजनादिकं।। 114 ।।

देशोसौराष्ट्रकेरम्ये पुरी श्रीद्वारिकाभिधा।

हरिवंषस्य श्रृंगारो यदूनां कुलभूषणः।। 115 ।।

नवयौवनमंपन्नो रूपेन मदनोयमः।

रिद्धिवृद्धिसमायुक्तो धनधान्यसमाकुलः।। 116 ।।

यादवानां सहस्त्राणि कुटुम्बं तस्य विद्यते।

रिपुवंशनिहंतायौ भूपैर्मानित शासनः।। 117 ।।

येनबाल्ये समुत्क्षिप्तो गोवर्द्धन महीधरः।

पूतना दुष्टचित्तायास्तत्क्षणात्तेजणाषीता।। 118 ।।

यमुनाया ह्रदेगाधे कृष्णाहिर्येन मर्दितः।

कंसोपि निहितो येन मुष्ठिचाणूर संयुतः।। 119 ।।

समुद्रतीरमासाद्य वषीकृत्यार्णवासुरं।

द्वारिकां वासयामास कृष्णराजोवलान्वितः।। 120 ।।

नेमिनाथो जिनाधीषो यस्य भ्राता प्रवर्त्तते।

तस्य किं वर्ण्यते शौर्यंचातिषयन्वितं।। 121 ।।

एकया जिह्वयावत्से वर्णयतुं धैर्य सम्पदं।

शक्यते गुरुणानैव तस्य किं वर्ण्यते मया।। 122 ।।

नारदोक्तं वचः श्रुत्वा जगौपितृस्वसावचः।

सत्यं रुक्मिणी सद्वाक्यं नारदस्य जगाद्वितं।। 123 ।।

कथमेतन्मुनेर्वाक्यं सत्यं वदस्य कौषले।

अहमन्यत्र दत्तास्मि वदत्यन्यत्र नारदः।। 124 ।।

त्वमप्यैतत् मुनेर्वाक्यंजल्पसे जनकानुजे।

इति पृष्टाहि रुक्मिण्यां जगौ सा जनकानुजा।। 125 ।।

एकदास्मद्गृहे योगीचर्यार्थं च समागत्तः।

अतिमुक्तक नामासौ ज्ञानवान् श्रुतपारगः।। 126 ।।

तवपित्राति भक्त्या सौचर्यां कारिता सामुनिः।

दत्तासने मुनिः श्रेष्टष्चर्यां ते सौन्यवी विषत्।। 127 ।।

उपविष्याग्रतो राजा भक्तिं कर्तुं समुद्यतः।

तावत्तेनाग्रतो दृष्टा स्थिता त्वं रुपषालिनी।। 128 ।।

अनोपमं ततो दृष्ट्वा तच्चरूपं मुनीष्वरः।

प्रपछभूपतिं भक्त्या कस्येयं दुहितावरा।। 129 ।।

ततोभूपतिना प्रोक्तं ममेयं दुहिता विभो।

इत्युक्त्वा पुनरप्येवं जगाद नृपतिर्मुनिं।। 130 ।।

स्वामिन्मदुहिताचेयं कस्य स्यात् प्राणवल्लभा।

तत्रदत्वामुखीचाहं भवामिक्षतकार्यकः।। 131 ।।

ततो भूपवचः श्रुत्वा जगौ योगी वचोवरं।

श्रृणु भूप महाभागयस्तु ते दुहितापतिः।। 132 ।।

यादवानां कुलाकाष प्रकाषन प्रभाकर।

उपेन्द्रेति भुविख्यातो विख्यातो गुणसंपदा।। 133 ।।

सस्यात्ते दुहितानाथो दैत्यकन्दनिकन्दकः।

मत्यमेतद्विजानीहि मद्वचनं नरेष्वरः।। 134 ।।

इत्युक्ता स गतो योगी यथा स्थानं तपोवने।

तस्य वाक्यं मयावत्से समीपे स्थितया श्रुतं।। 135 ।।

सत्यं सत्यं मुनेर्वाक्यं तन्नासत्यं कदाचन।

प्रसिद्धं भुवने चैतन्नान्यथा मुनि भाषितं।। 136 ।।

तदाहि रुक्मिणी प्राह कथमेतद्भविष्यति।

दत्तास्मि षिषुपालाय जानासि जनकानुजे।। 137 ।।

तदापितृस्वसा प्राह माकृथा दुःखितं मनः।

श्रृणु वाक्यं ममात्यं तं सुन्दरं तव सुन्दरि।। 138 ।।

शिषुपालाय नोदत्ता पितृभ्यां तव कन्यके।

किं तु तुष्टे न भ्राता ते दत्ता तत्र गतेन हि।। 139 ।।

इत्युक्ते श्रेणिकस्तत्र प्रपछगण नायकं।

षिषुपाल समीपेऽसौ कुमारस्तु गतः कथं।। 140 ।।

गौतमोपि ततः प्रोचेश्रृणु श्रेणिक कथ्यते।

एकदा षिषुपालोऽसौरिपून्नुद्दिष्य प्रस्थितः।। 141 ।।

तदाहि प्रेषितो दूतः समीपे भीष्म भूपतेः।

आगन्तव्यं ससैन्यैनन्वया शीघ्रं ममांतिकं।। 142 ।।

दूतवाक्यं ततः श्रुत्वा राजा गन्तुं समुद्यतः।

मेलियित्वा क्षणात्सौन्यं सुसन्नद्वं सदा युधं।। 143 ।।

गमनावसरेराजा राज्यं दातुं समुद्यतः।

निजं रूप्यकुमाराय स्थितिरेखामनीषिणीं।। 144 ।।

तत्रकार्योद्यतं दृष्ट्वा कुमारः पितरं जगौ।

किमेतत् क्रियते नाथ क्व वागन्तुं समुधतः।। 145 ।।

तदाभीष्मः सुतं प्राह श्रृणु वत्स वचोमम्।

राज्यं त्वंहि क्रमायातं पालयस्व निरंकुषं।। 146 ।।

मया हि गम्यते स्यैन्ये षिषुपाल महीभृतः।

तातोक्तं वचनं श्रुत्वा नत्वा तातं सुतोवदत्।। 147 ।।

कथं चागम्यते स्यैन्ये विद्यमाने सुतेमयि।

एतत्पुत्रस्य पुत्रत्वं पित्रेत्यद्दीयते सुखं।। 148 ।।

किं जातैः प्रचुरैः पुत्रैः शोकसंतापकारकैः।

एकोपिहि पिताभक्तः सुपुत्रोनापरः सुतः।। 149 ।।

राजा तं हि तदा प्राह श्रृणु बालकुमारक।

युद्धकर्मण्यताभ्यासस्तत्र गतुं न युज्यते।। 150 ।।

कुमारोपि तदा प्राह श्रृणु तात वचो मम।

पुरुषस्य प्रमाणं हि सत्वं सर्वत्र शस्यते।। 151 ।।

हस्ती स्थूलो भवेत् नूनं सिंहः कृष शरीरकः।

सिंहनादेन नष्यन्ति शतषोपिगजाः क्षणात्।। 152 ।।

तेजसा साध्यते स्व सर्ववयसा किं प्रयोजनं।

तव पुण्य प्रभावेन जयामि रिपवः क्षणात्।। 153 ।।

पुत्रवाक्येन संतुष्टो राजा पुत्रं प्रमोदयत्।

सैन्य सागर मध्यस्थं शकुनैः प्रेरितं मुदा।। 154 ।।

गत्वा रूप्यकुमारोपि मिलितष्चेदिपतिर्यदा।

तदा तेनापि भूपेन सन्माने नैव मातितः।। 155 ।।

तेनान्वितो ययौ राजा युद्धार्थं चेदिभूपतिः।

रिपून् हत्वाकरं नीत्वा समायातो गृहेनृपः।। 156 ।।

रूप्यकुमार सानिध्यं प्राप्य चेदि महीभृता।

रिपवोपिजिता युद्धे तस्मात् सोवल्लभोजनि।। 157 ।।

अभिसन्मान दानेन मानितोऽसौ पुनः पुनः।

तदा सोपिकुमारोपि तुष्टोमानेन भूपतेः।। 158 ।।

संतुष्टेन कुमारेण दत्तास्मै रुक्मिणी स्वसा।

रुक्मिणी दान मात्रेन तुष्टो भूपोति चेतसि।। 159 ।।

सन्मान्यः प्रेषयामास वस्त्रदानादिभिःस्वयं।

संतुष्टो गृहमागत्य पितृभ्यां च निषेदितं।। 160 ।।

तेन वाक्येन ते सर्वबान्धवास्तोषमागताः।

एतते गदितं भूपकुमार गमनादिकं।। 161 ।।

रुक्मिणीं च तदा प्रोक्तं तयापितृस्वसा वचः।

पितृभ्यां नैवदत्ता त्वां कुमारेण प्ररूपिता।। 162 ।।

पितोदत्ता प्रयात्येवं पुत्री सर्वत्र पिष्टये।

अतस्त्वं माकृथा दुःखं भव्यं चात्र भविष्यति।। 163 ।।

तथायत्नं करिष्यामि यथां कृष्णनरेष्वरः।

अवष्यं ते पतिर्वत्से भविष्यति न संसयः।। 164 ।।

इत्युक्तं वचनं श्रुत्वा रुक्मिणी नमनौह्वदि।

प्रमोदेन परं पूर्णा कृष्ण संगमजन्मना।। 165 ।।

प्रषस्य विविधैर्वाक्यैः कृष्णराजं पुनः पुनः।

रुक्मिण्याहि मनोनीत्वा ततो नारद निर्ययौ।। 166 ।।

गत्वाकैलाष कूटेऽसौ निविष्टो मुनिसत्तमः।

लिखितं रुक्मिणी रूपं तेन तत्र पटेचरे।। 167 ।।

संकोच्य च पटं रम्यः प्रमोदेन प्रपूरितः।

द्वारिकां हि समायातो वेगवान् प्रमुदान्वितः।। 168 ।।

सभांगणे निविष्टे विष्णु महीभुजा।

आकाषेन समायातो नारदो मुनि नायकः।। 169 ।।

समायातं मुनिं दृष्ट्वा तदा कृष्णमहीपतिः।

अभ्युत्थानादिकं कृत्वा दत्तं सिंहासनं निजं।। 170 ।।

आषीर्वादेन संतोष्य कृष्णराजं हि नारदः।

सिंहासने निविष्टोऽसौकृतसधर्मसंकथः।। 171 ।।

परस्परं समालाप चक्राते कृष्णनारदौ।

स्नेहेनपूरितौ चित्ते प्रीति युक्तौ विचक्षणौ।। 172 ।।

अवसरं तु समासाद्य प्रोवाचैवं सनातनः।

श्रृणुनारद किंचत्ते प्रछाम्यहं मनोगतं।। 173 ।।

सार्द्धद्वीपद्वयेनाथ वर्त्ततेहि गतिस्तवः।

अपूर्णं हि विनोदं तु त्वया दृष्टं क्वचित् क्षितौ।। 174 ।।

मत्सदृषा समानीता काचिद्वा सुखभक्षिका।

त्वमेव परमं मित्रं वर्त्तते मम नापरः।। 175 ।।

इत्युक्ते परमं गत्वा तोषं नारद सन्मुनिः।

न किंचिदूचे वचसा प्रसार्य च पटं ददौ।। 176 ।।

पटं विलोकयामास प्रमोदेनान्वितो व्युतः।

पटे स्थितं तदा दृष्टतेन रूपं मनोहरं।। 177 ।।

तन्व्यारूपं समालोक्य कृष्णयो भूद्विस्मयाकुलः।

मुषिता वा तया नूनं लिखितो वा पटे स च।। 178 ।।

कि×चिंतकालं तथा स्थित्वा चिंतयामास चेतसि।

किमेतद्वि समानीतं नारदेनन्वरायता।। 179 ।।

वेधसा वा कथं सृष्टा रूपलावण्यषालिनी।

नेदृषी भुवनेनारी व भूता न भविष्यति।। 180 ।।

वेण्याजितं मयूराणां वृन्दं वाचानयाध्रुवं।

ललाटेनाष्टमी चन्द्रं मुख्येन रजनीकरं।। 181 ।।

कीरचु×चुर्जिता नूनं निजघ्राणेनचानया।

नयनाभ्यां मृगीनेत्रे भ्रूभ्यांमन्मथकार्मुकं।। 182 ।।

कम्बु कंठेन सा जिग्ये पर पुष्टास्वरेणवै।

स्तनाभ्यां श्रीफलानीह बाहुभ्यां पुष्पमालके।। 183 ।।

इन्द्रायुधंजितं कट्या जठरेन मनोहरा।

नाभि कूपमहं जाने लावण्य जलदीर्घिका।। 184 ।।

नितंबाभ्यां परं प्रोढा रंभास्तम्भसमोरुका।

जानुभ्यां वर्त्तुलाकारा चरणाभ्यां मनोहरा। ।। 185 ।।

पाणिपादतलाभ्यां किं जितं पद्मसमूहकं।

सन्तप्तकनकाकारा कान्त्याजित निषाकरः।। 186 ।।

तेजसा जितदीप्तांषु स्थैर्यच्चै नैव सागरः।

सर्वलक्षण संपूर्णा सर्वावयव सुन्दरा।। 187 ।।

केयं चात्र क्व चा याता पटे वा निहिता कथं।

नारदेन कथं दृष्टा ज्ञाता वा लिखिता कथं।। 188 ।।

नाकनाथस्य किं जाया किं वा कुसुमधन्विनः।

किमु वा रात्रिनाथस्य दिननाथस्य किं वधूः।। 189 ।।

कीर्त्तिमूर्तियुता वा कि वाग्वधूसरीरिका।

यक्षी वा किंन्नरी वा किंस्यारूपं भवेदिदं।। 190 ।।

इति विस्मयमापन्नो विष्णुरेवं विचिन्तयन्।

इतिध्यात्वा चिरंचित्तेपुनरेव विमृष्ययत्।। 191 ।।

पृच्छामिनारदं नत्वा पटस्थं कारणं स्फुटं।

करस्थेकंकणे नूनं मादर्षको विलोकयेत्।। 192 ।।

विमृस्यैवं चिरं कृष्णो नत्वा तं नारदं मुनिं।

प्रपछविनयात् सर्वं चित्तसंदेहकारणं।। 193 ।।

विभोकुतः समानीय लिखितं रूपमुत्तमं।

तत्सर्वं त्वं कृपां कृत्वा निवेदय ममैवहि।। 194 ।।

कीलितं स्तम्भितं वा किं मोहितं हि मनोमम।

पटस्थेनापि रूपेण चंचलं चाभवत्क्षणात्।। 195 ।।

इति पृष्टे जगादोऽसौ प्रमोदं परमं वहन्।

श्रृणुकृष्ण महाभागमाकृथा दुःखितं मनः।। 196 ।।

न देवं न तु गंधर्वं नो विद्याधरनारिजं।

मानुष्यारूपमेतद्विविद्विचित्ते सनातना।। 197 ।।

श्रीकुंडलपुरे रम्ये श्रीभीष्मोनाम भूपतिः।

तस्यास्ति भुवने ख्याता श्रीमतीति प्रियाप्रिया।। 198 ।।

तस्येयं दुहिता भाति रुक्मिणी नामतो भुवि।

लक्षणानां हि गुणानां हि निधि रेखा समुदϖता।। 199 ।।

मयाविलोकितं सर्वं सागरान्तं धरातलं।

विद्याधराणां गेहानि भूभुजां निलयानिच।। 200 ।।

रुक्मिण्याष्चरणांगुष्ठ समानैव विलोकिता।

रुपेण सदृषा काचित् नास्ति नारी महीतले।। 201 ।।

न श्रुताहि त्वया किं सा रूपयौवन भूषिता।

विख्याता विष्टपे नूनं लावण्यजल दार्घिका।। 202 ।।

तां निर्माप्य विधातासौ कृतार्थत्वममानयत्।

प्राप्यतां सुन्दरीं नूनं कृतार्थ स्वं न चान्यथा।। 203 ।।

यावर्न्नायाति गेहे सा बाला गुणविभूषिता।

परिणीत इदं वाक्यं नो वाच्य कस्यचित् कदा।। 204 ।।

संसारेष्लाध्य मेतद्धितवावतरणं तदा।

यदां के रमते रम्या रुक्मिणी लोक विश्रुता।। 205 ।।

इतिनाना विधैर्वाक्यैः कृष्णं संमोहयन् मुनि।

प्रत्युत्तरं तदा प्राह मुनिं नारायणो नघं।। 206 ।।

ऊढानूढेति सा बाला तत्सर्वं कथ्यतां मम।।

इत्युक्ते नारदः प्राह सानोढा सुन्दरीवरा।। 207 ।।

चेदिभूपाय दत्तावै षिषुपालाय सा ध्रुवं।

वधूनां स्वजनानां चापृष्ट्वा दत्ता तु कन्यका।। 208 ।।

भ्रात्रौवषिषुपालाय दत्ता बाला प्रमोदतः।

गतेन सदने तस्य तोषितेन पुनः पुनः।। 209 ।।

रणेचेदिपतिंहत्वा प्राप्यते सानचान्यथा।

षिषुपालो हि बलवान् जीवमानेन षक्यते।। 210 ।।

कृष्णंकृष्ण मुखं दृष्ट्वा किंचिन्नारदसन्मुनि।

माकृथा कातरं चित्तं प्राप्यते सुखतो हि सा।। 211 ।।

सरैः सम्यप्यते सर्वं का तरैर्नकदाचन।

कातरस्त्वं विहायाषु धैर्ये संधार्यतां मनः।। 212 ।।

त्वयि संमोहिनी बाला मया दृष्टापितुगृहे।

निश्चियात्तेगृतं प्राप्ता विद्विचित्ते सनातन।। 213 ।।

माकृथा हि वृथा दुःखं कार्ये संधार्यते मनः।

उद्यमी लभ्यते सौख्यमालस्यान्ताप्यते हि तत्।। 214 ।।

स्पृहास्ति यदि ते चित्ते नारीणां रति विभ्रमे।

वृष्णीस्वतां भुवने ख्यातां सुन्दरी लोक सुन्दरीं।। 215 ।।

कलावतष्च चन्द्रस्य द्विजौषधि पतेरपि।

पूर्णिमामपिहायैकां नाना शोभाय शर्वरी।। 216 ।।

तवजायाषतं व्यर्थं सहस्त्रंललक्ष मेवच।

यावत् न आयाति ते गेहे बालासाति विचक्षणा।। 217 ।।

स तु नाना विधैर्वाक्येः सम्मोह्यैवमधोक्षजं।

जगामं स्वोचितं स्थानं नारदः प्रमुदान्वितः।। 218 ।।

गते हि नारदे कृष्णः क्षणान्मूर्छामुपागते।

पुनरून्मूर्छितो बन्धु लोपचारतः।। 219 ।।

संज्ञामवाप्यकृष्णोपि चिन्तां कर्त्तुं समुद्यतः।। 220 ।।

चित्तेधृत्वाहि तत्कार्यं स्थितो गेहे विचक्षणः।

न दिवापि च नोरात्रौ क्षुधां निन्द्रां निषेवते।। 221 ।।

इति चिंतासमायुक्तः स्थितः कृष्णो यदा तदा।

अन्यत्कथान्तरं जातं रुक्मिण्यातत्व कथ्यते।। 222 ।।

लग्नं नीतं हि रुक्मिण्याः षिषुपालेन धीमता।

तत् श्रृत्वा रुक्मिणी चाभत् शोकग्रस्त शरीरिका।। 223 ।।

मनोगतं तदा दुःखं जगाद जनकानुजां।

यास्यामि मरणं नूनं वियोगकृष्ण भूपतेः।। 224 ।।

इति तस्या वचः श्रुत्वा जगाद जनकानुजा।

किं कृथा हि वृथा दुःखं करोमि चिन्तितं तव।। 225 ।।

एवं विमृष्य ताभ्यां हि दूतो वै कुषलाभिधः।

कुशलः सर्व भाषासुकलासुसकलासुच।। 226 ।।

समीपे कृष्णभूपस्य प्रेषितोऽसौयुवाकृती।

सस्नेहैर्वचनैर्युक्तं लिखित्वा पत्रमुत्तमं। ।। 227 ।।

शकुनैः प्रेर्यमाणो सोदूतोपि प्रमुदान्वितः।

उत्सकः कृष्णमुद्दिष्य ययौ स द्वारिकांपुरीं।। 228 ।।

विलोक्य द्वारिकां दिव्यां दूतो विस्मयमागतः।

स्वर्णनाथ नगरी वेषा कुतो भूमौ समागत।। 229 ।।

इति विस्मयमापन्नो विलोकयन् इतस्ततः।

जगाम राजमार्गेण दूतां सौहर्ष पूरितः।। 230 ।।

गत्वाराजप्रतोलीं स प्रतिहारं निवेदयत्।

कथयस्व महाभाग कृष्णस्यागमनं मम।। 231 ।।

कुतोवात्रसमायातः कस्त्वंवाकेन प्रेषितः।

प्रतीहारेण पृष्टेथ दूतो वाक्यं जगौवरं।। 232 ।।

विदेषाच्च समायातो दूतो वैदेषिको विभो।

मनोज्ञकार्यमुदिष्य तवप्रेमनिबन्धनं।। 233 ।।

तत्र गत्वा विभो पार्ष्वे मद्वाक्यं त्वं निवेदयं।

इति दूतोदितं श्रुत्वा प्रतीहारो गतस्ततः।। 234 ।।

नारायणं नमस्कृत्य वृत्तान्तं दूतं सम्भवं।

सर्वं निवेदितं तेन प्रतीहारेण भक्तितः।। 235 ।।

प्रतीहार वचः श्रुत्वा कृष्णोप्येवमभाषत।

आनीयतां द्रुतं दूतो मत्समीपेति मानतः।। 236 ।।

प्रतीहारेण दूतोपि समानीतः सभान्तरे।

दूतो विष्णु सभां दृष्ट्वा प्रमोदेन प्रपूरितः।। 237 ।।

दामोदरं प्रणभ्यासु दत्ते स्थानेन्यवीविषत्।

दूतोपिसंज्ञय किंचित् कृष्णराजं निवेदयत्।। 238 ।।

कृष्णोपि हि प्रतीहारं यदा दृष्ट्वा विलोकयन्।

तदासोपि प्रतीहारः सभां सर्वं व्यसर्ज्जयत्।। 239 ।।

कृणेनापि च पृष्टोऽसौदूतोप्यागम कारणं।

विनयेन तत् सोपिजगादेवं विचक्षणः।। 240 ।।

मिथोस्ति कथनीयं ते तत्सर्वं श्रुयतां विभो।

येन श्रवणमात्रेण प्रमोदोजायते हृदि।। 241 ।।

कृष्णोपि तद्वचः श्रुत्वा तोषदालोचमन्दिरं।

बलदेवयुतो गत्वा दूतेनामान्यवीविषत्।। 242 ।।

योग्ये सिंहासने तौ हि निविष्टो प्रेम संयुतौ।

दूतोपिहि यथा योग्यमासनं प्राप्य संस्थितः।। 243 ।।

पृष्टेजनार्दन दूतो जगाद वचनं वरं।

श्रुणुनाथ सतां मान्यं मद्वच प्रेम कारणं।। 244 ।।

नदीयंवचनं विद्धि सारसंग्रह संयतं।

श्रोतुत्वमसि योग्योसिमानीनयं त्वया विभो।। 245 ।।

श्री कुंडनपुरे रम्ये भूप भूपा निषेवितः।

विख्यातो भीष्मनासौजित शत्रुकदंबकः।। 246 ।।

तस्यास्तिभ्यमिनी रम्या श्रीमती विश्रुता भुवि।

तया पुत्रः प्रसूतोस्ति गुणषीलालयो महान्।। 247 ।।

जयन्त स्वरनाथस्य शवस्यापिहि षन्मुखः।

सूरोधीरस्तथा मानी श्रीरूप्यकुमारो महान्।। 248 ।।

अपरास्यैव संजाता पुत्रीरुप गुणालया।

नवयौवन सम्पन्ना पूर्णेंदुसदृषानना।। 249 ।।

यथोदधेः समुत्पन्ना विख्याताकमलाभिधा।

नगाधिराजात् संजाता यथावैषंभुवल्लभा।। 250 ।।

हिरण्यगर्भतो जाता भारती विदिता भुवि।

यथा भीष्माच्चसंजाता प्रसिद्धा रुक्मिणीसुता।। 251 ।।

दत्ता स षिषुपालाय भ्राता तस्या विवेकिन।

रणोद्भूतेन दर्प्येण मानितेन महीभुजा।। 252 ।।

बान्धवाष्च गुरुन् सर्वान् ननारीपृछाति दर्प्यतः।

दत्ता सा रुक्मिणी कन्या षिषुपाल महीपते।। 253 ।।

स्वजनैरपि तद्वाक्यं मानितं चाति भक्तितः।

शिषुपालस्य योग्यत्वात् योग्यः कस्य न रोचते।। 254 ।।

तया समं ध्रुवं नाभं लग्नं चेदि महीपतेः।

समस्तैः स्वजनैस्तत्र मिलित्वा गणकेन च।। 255 ।।

माघमासस्य शुक्लायामष्टम्यांतु दिने शुभे।

तयो र्विवाह लग्नं हि वर्त्तते दोषवर्ज्जितं ।। 256 ।।

एतस्मिन्नंतरे प्राप्तो नारदो मुनि नायकः।

मिलित्वा भूपतेः पूर्वं ततः सौद्धांतमाविषत्।। 257 ।।

तत्रास्ति भूपतेर्भग्नी विधवा चतुरापरा।

अन्तःपुरेहि सा श्रेष्ठा मानिता भूभुजा सदा।। 258 ।।

तयाहि प्रणुता भक्त्या नारदो नृप पूजितः।

नारदस्य ततः पादौ प्रणुता भूपते स्त्रियः।। 259 ।।

सुखासने निविष्टेन पुष्टास्ता कुषलादिकं।

ततोहि रुक्मिणी दृष्टा नारदेन स्थिताग्रतः।। 260 ।।

नारदेन ततः पृष्टा भीष्मस्यैव सहोदरा।

केयं पुरः स्थिता बालाकस्यचास्ति शरीरजा।। 261 ।।

भीष्मानुजा ततो वोचत् श्रृणुनाथ निगद्यते।

पुत्री श्रीभीष्मभूपस्य रूपसैवानुजाह्यथा।। 262 ।।

इत्युत्वा हि तया नीत्वा पातिता मुनिपादयो।

मुनिनापि ततो दत्वा तस्या आषीरियंवरा।। 263 ।।

जितशत्रुकंदवोस्ति मुरारिति संज्ञितः।

द्वारिकायाः पतिर्नूनं हरिवंष विभूषणः।। 264 ।।

तस्याग्रमहिषी वत्से भवत्वं पुण्यनोदिता।

इतिरियं वचः श्रुत्वा जाता सा विस्मयाकुला।। 265 ।।

गतेथनारदे क्वापितयापि कि सुचेष्टितं।

तव स्नेह वषात् नूनं तत्सर्वं श्रूयतां विभो।। 266 ।।

अन्नं न रोचते तस्या जलस्यापिस्पृहा नहि।

न रात्रौ लभते निन्द्रा चिन्तया परिपूरिता।। 267 ।।

नतल्पे लभते सौख्यं रम्भापत्रमयेपि च।

न सखीनां समालापारोचं तेस्या वियोगतः। । 268 ।।

चन्द्रज्योत्स्नाहि विषवत्चंदनं ज्वलनोपमं।

मुहुर्मंचतिनिष्वासं ज्वासारोपित मानसा।। 269 ।।

तवैवनामग्रहणात् सा जीवति न संषय।

इति मत्वा त्वया कार्यं यत् च मौख्यकरं परं।। 270 ।।

अस्मादृषां विभोवाचो युक्ति सारा न संषयं।

कर्त्तव्यं हि त्वदायत्तं कृत्ये चित्तं निधीयतां।। 271 ।।

कृष्णोपि तद्वचः श्रुत्वा बलदेव समन्वित।

जगाद वचनं वाग्मी प्रेम्लाहितु वषीकृतः।। 272 ।।

गत्वा च स्थीयते कुत्र कथमागम्यते मया।

मिलिष्यति कथं सामेतत्सर्वं त्वं निवेदय।। 273 ।।

दूतोपि हि तदा प्राह श्रृणु नाथ वचो मम।

गन्तव्यं कुंडनं नाम पुरं वेगवता त्वया।। 274 ।।

तत्रास्ति प्रमदोद्यानं नानो कुहसमंकुलं।

मनोभवयवी मूर्त्तिः तत्राषोकतरोरधः।। 275 ।।

तया हि स्थापिता तत्र तवार्थेवन मध्यतः।

अषोक परिवद्वास्ति वैजयन्ती मनोहरा।। 276 ।।

तत्रागत्य त्वयानाथ स्थातव्यं गुल्ममध्यतः।

आगमिष्यति सा तत्र पूजितुं वै मनोभवं।। 277 ।।

बन्धून प्रतार्य सा सर्वान् पूजायाः छलतो ध्रुवं।

समेष्यति वनेबाला मिलिष्यति तवैवहि।। 278 ।।

अतोविमृष्य स्वहितं कर्त्तव्यं हि त्वया विभो।

त्वां विना न च सा बाला पतिं नैव निषेचते।। 279 ।।

सिंहिनीकुरुते किं हि रतिगोमायु शावके।

तथा त्वामपहायैकमन्यस्य नियमो ध्रुवं।। 280 ।।

तवार्थं हि समागत्य विलोक्यत्वामितस्ततः।

तत्रानालोक्य सावामरणं प्रापयिष्यति।। 281 ।।

तवरामामयीहत्या नूनं नाथ भविष्यति।

अतस्त्वं स्वहिते कृते देहि देहि मनोजिता।। 282 ।।

इत्युक्त्वा माधवं नत्वा दूतो गन्तुं समुद्यतः।

कृष्णेन वस्त्रदानैष्च संप्रतोष्य विसर्ज्जितः।। 283 ।।

दूतो विसर्ज्य कृष्णोपि बलदेव समन्वितः।

मन्त्रं विचिन्तयामास रुक्मिणी मत मानसः।। 284 ।।

सत्यभामा न जानाति कर्त्तव्यं हि तथा स्फुटं ।

विद्याधरा सुता दुष्टा किंचिद्विध्नं करिष्यति।। 285 ।।

एवं विमृष्य कृष्णोपि समंत्र्यबल संयुतः।
गमनाय मनष्चक्रे श्री कुंडनपुरं प्रति।। 286 ।।

द्वावेव भ्रातरो वेगद्रथमारुह्ये चेलतुः।

निशायाः परिचमेयामे प्रछन्नौकवचान्वितौ।। 287 ।।

आयुधैर्विविद्यै युक्तो धीर्यमात्र सहायकौ।

रुक्मिण्यां दत्तचित्तौहि कलागुण विषारदौ।। 288 ।।

मनोजवरथारुढ़ौ धारयन्तौ मनोरथौ।

श्री कुंडनपुरोद्यानं प्रापतुस्तौ मनोहरं।। 289 ।।

दूरतोपि यदा दृष्टं तत्कुंडनपुरं परं।

श्रीधरेण तदाध्यातं कथं चात्र भविष्यति।। 290 ।।

एकाकिनावुपगतौ बलकेषवौ तौ चित्तेनिधायकरिणी गजषेषमेव।

सौम्याननौ विहितधर्मवतेन युक्तौ श्रीकुडनस्यहिपुरस्य वनं क्षणेन।। 291 ।।

***इति श्रीप्रद्युम्नचरिते श्रीसोमकीर्त्याचार्यविरचिते बलभद्रकृष्णवनागमनो . नाम**

तृतीयसर्गः *

चतुर्थसर्गः

कौतुकेन पुरं दृष्टुमायातं तद्वनं भुवि।

इन्द्रो देषवषात् नूनं दृष्यते तद्वदाकतिः।। 1।।

पादपैर्विविधैर्युक्तं पुष्पराजि विराजितं।

इन्द्रोपेन्द्र समानौ तो यादवौ विषतुर्वनं।। 2 ।।

संप्रविष्य वने दृष्टोषोकोसौ शोकनाषनः।

तस्या परिस्थिता दृष्टा वैजयन्ती मनोहरा।। 3 ।।

मनोभवमयी मूर्त्तिस्तस्याधस्ताद्विराजिते।

दृष्ट्वामूर्त्तिमनोजस्य कृष्णस्तोषमुपागतः।। 4 ।।

छोटयित्वा रथं तत्र हयावन्यत्रमुंचितौ।

तत्समीपस्थ गहने प्रविष्टौबलकेषवौ।। 5 ।।

स्थितौ प्रछन्नतां प्राप्य रुक्मिणी मुक्तमानसौ।

तावदन्यत् च संजातं वृत्तान्तं लोक हर्षणं।। 6 ।।

द्वारिकायास्ततो गत्वा नारदोचेदिसन्निधं।

मानितस्तेन स प्रोचे वचनं कलिकारणं।। 7 ।।

षिषुपाल महीपाल विवाहस्ते मया श्रुता।

मिलितः कुंडनपुरे सत्यार्थं तं च मेवद।। 8 ।।

नारदोस्तं वचः श्रुत्वा स्मित्वा चेदि महीपतिः।

तत्सत्यं यच्छतं नूनं भगवन्स्त्वत्प्रसादतः।। 9 ।।

नारदोपि ततः प्रहधृत्वा स्नेह मनुत्तमं।

लग्नं विलोकयामीति दृर्ष्यतां हि पयं मम।। 10।।

इत्युक्ते षिषुपालेन लग्नं तस्मै प्रदर्षितं।

लग्नं विलोकयामास नारदोपि कलिप्रियः।। 11 ।।

विलोक्य सुचिरं तावत् मस्तकं सोप्यधूनयन।

धूनितं हि षिरोदृष्ट्वा प्रपछचेदिभूपति।। 12

शिरोविधूनितं कस्मात् कथयस्व विभोमम।

नारदोपि च तं प्राह श्रृणुभूप विचक्षणः।। 13 ।।

लग्ने विलोक्यते किंचित् शरीरे कष्ट कारणं।

अतः त्वयाति यत्नेन गन्तव्य कुंडनेपुरे।। 14 ।।

तत्र किंचित् महत् कष्टं शरीरस्यापि दृष्यते।

अतस्त्वयापि गन्तव्यं साधनेन घनेन च।। 15 ।।

इत्युक्तवा कलिमुत्याद्यनारक्षेपि गतस्ततः।

चिन्ताषक्तो नृपोजातो गते नारद सन्मुनौ।। 16 ।।

मेलयित्वा महत्सैन्यं चेदिराट् शंकयान्वितः।

जगाम कुंडनपुरं महासाधन संगतः।। 17 ।।

तत्र कुंडनपुरं तेन सर्वं सैत्येन वेष्टितं।

तारकाणां समूहो वा यथा मेरुमहागिरिं ।। 18 ।।

समवेष्ट्य पुरमेतद्धि स्थिते चेदिमहीपतौ।

तावत् तत्र समायातो वने कृष्णोबलान्वितः।। 19 ।।

रुक्मिणी दुःखिताजाता दृष्ट्वा तं वेष्टितं पुरं।

कथंवागम्यते नूनं वने कृष्ण विभूषितं।। 20 ।।

चिन्तापुरां हि तां दृष्ट्वा जगाद जनकानुजा।

कथं म्लानमुखाजाता दृष्यसेवलुकन्यके।। 21 ।।

जगाद रुक्मिणी चैवं पुरंचेदिमहीभृता।

वेष्टितं बहुसैन्येन कथं वा गम्यते मया। 22 ।।

दीनं तस्या वचः श्रुुत्वा भीष्माराजसहोदरी।

स्मित्वाकु तु रुक्मिणीं प्रोचेमाकृथादुःखितं मनः।। 23 ।।

तथा यत्नं करिष्यामि यथाते गमनम् वने।

भविष्यति न सन्देह एतेषां पश्यतामपि।। 24 ।।

इत्युक्त्वा मधुरैः वाक्यैः शान्तयित्वा मुहुर्मुहुः।

उपायस्तु समुद्भूतः स्त्रीणां तात्कलिकामतिः।। 25 ।।

पूजापहारसंयुक्ता रुक्मिणीच तया सहा।

गीतनादादि कुर्वाणा मन्दं मन्दं तु निःसृताः।। 26 ।।

निसृतां हि पुरा दृष्टवा षिषुपालचरैस्तदा।

स्थापयित्वाहि तां तत्र भूपाय विनिवेदितं।। 27 ।।

शृणु चेदिमहीपाल रुक्मिणी क्वापि विसृता।

परिवारयुताया याति वने पादप संकुले।। 28 ।।

षिषुपालस्ततः प्रोचेवचनं नयपेषलं।

निवार्यतांद्रुतंगत्वा रुक्मिण्यागमनं वने।। 29 ।।

ततस्तैष्च चरैर्गत्वा निषिद्धा सा च कन्यका।

न गन्तव्यं वने दुष्टे प्रभोराज्ञा प्रमाणतः।। 30 ।।

ततः पितृस्वसा प्रोचे श्रूयतां वचनं वरं।

रुक्मिण्या मानिता यात्रा मनोभवमयी वने।। 31 ।।

एकदाहिगतारंन्तु सखीजन समावृता।

मनोभवमयीमूर्तिः दृष्टा तत्र मनोहरा।। 32 ।।

प्राणिपत्य च तां मूर्तिं जगाद रुक्मिणीवचः।

स्वामिन् स्यात् यदि मे नाथः षिषुपाल महीपतिः।। 33।।

आगमिष्यामि लग्नंस्यदिने यात्रां तवैवहि।

इत्यत्र मानितायात्रा रुक्मिण्या हि वेरछया।। 34 ।।

लेभेभाग्यवषात्सोपि षिषुपालं पतिं शुभं।

मनोभवस्य यात्रायामतो नो गम्यते कथं।। 35 ।।

वांछते कुषलं चाग्रे षिषुपालमहीपतेः।

विलोक्यते हि नारीणां पतिपुत्रादिकं न तु।। 36 ।।

इति तस्यावचः श्रृत्वा गत्वा भूपाल सन्निधिं।

तत्सर्वं हि मयारख्यातं वृतान्तं तु तयोदितं।। 37 ।।

तद्वृतान्तं नृपः श्रुत्वा हर्ष पूरित मानसः।

वांछतीत्यतिस्नेहेन रुक्मिणी गुणपूरिता।। 38 ।।

इत्यानन्दवषात्सोपि जगाद वचनं चरान्।

दीयतां गमनं तस्या यात्रार्थं हि वनेचरे।। 39 ।।

इत्युक्त्वं वचनं श्रुत्वा ययौ परिजनावृता।

पितृस्वसा समायुक्ता समीपेस्य–वनस्यसा।। 40 ।।

परिवार समायुक्ता स्थित्वा पितृस्वसातदा।

श्रृणु रुक्मिणिमद्वाक्यं कथयामि च ते शुभे।। 41 ।।

तवास्ति देवताह्मत्र वनमध्ये विचक्षणे।

एकाकिनीहि गत्वा त्वं तमुपासय भक्तितः।। 42 ।।

नीत्वा पूजापहारं सा मन्दंमन्दं ययौ वनं।

पश्चंयाहि दिषा सर्वा यूथ भृष्टा तथा मृगी।। 43 ।।

मनोभव समीपे सा समायाता मनोहरा।

गुल्ममध्य स्थितेनापि कृष्णेनोसौ विलोकेते।। 44 ।।

मनोज्ञां लक्षणैर्युक्वां भंगुरालकप🡻कां।

कामस्य वानवत् नेत्रां चन्द्र बिम्ब समाननां।। 45 ।।

कम्बुकण्ठेधरां तन्वीं पीनोन्नत पयोधरां।

कलस्वनां हि वेणी व मालती दामवाहुकां।। 46 ।।

दार्घोत्तीर्ण सुवर्णाभां वज्रमध्यां तनूदरीं।

दिक्वरींद्रसमाकारां नितम्बस्थल मंडलां।। 47 ।।

मेखलायाः पदे नूनं ऊषकेतनमन्दिरां।

रम्भास्तम्भासमाकार विभ्रतीयीभ्ररोरुकां।। 48 ।।

चरणयोः कमलवद्वारयन्तीं मनोज्ञतां।

रणन्नू पुर संयुक्तां गत्याहंसवधू समां।। 49 ।।

एवं विध च तां दृष्ट्वा केषवोगुल्ममध्यतः।

यावद्विनिर्गतस्तावत्रयोक्तं हि वने वचः।। 50 ।।

मत्पुण्याद्वासमायातो भवेत् च द्वारिकायति।

निर्गत्य वचनं मद्यंपहे वदीयतां तव।। 51 ।।

एवं व्रतीति सा बालायावत्तावद्विलोकितः।

अग्ने स्थितः सुरूपायो वासुदेवो बलान्वितः।। 52 ।।

अग्रतः स्वामिनं दृष्ट्वा जाता चाऽधोमुखी च सा।

लिखन्ती वर्त्तते नूनं अंगुष्टेन भुवस्तलं।। 53 ।।

जगादकृष्णराजोपि रुक्मिणीं वचनं वरं।

तववाक्यात्समायातो द्वारिकाया अधीष्वरः।। 54 ।।

तस्मात्प्रसीद हे देवि मां विलोकय सुन्दरि।

कृष्णवाक्यं समाकर्ण्य जाता लज्जानताननां।। 55 ।।

धारयंतीहि सानूनं मुखं चलितं क्रुंधरं।

शिषुपाल भयेनैव विभ्रती कंपितर्वपुः।। 56 ।।

सज्जीकृत्वा रथं तावत् बलदेवो जगाविति।

स्त्रीणां स्वभावतो लज्जा कन्यकानां विषेषतः।। 57 ।।

स्वयं नीत्वा कराभ्यां तं रथमरोपय द्रुतं।

स्त्री चरित्रं न जानासि सत्यगोपाल को भवत्।। 58 ।।

बलदेववचः श्रुत्वा कृष्णः प्रेमभरालसः।

स्वरथेरोपयन्बालादालिंगेथ रुक्मिणीं।। 59 ।।

चलितं हि रथं तावद् बलेनोरुह्यवेगतः।

चालितेथरथे तस्मिन् कृष्णो वाक्यं वरं जगौ।। 60 ।।

पा×चजन्यं निजं शंख पूरयित्वा मनोहरं।

सर्वं निरुपयामास वृत्तान्तं केषवस्तदा।। 61 ।।

षिषुपाल दलस्यापि ये च कुडनवासिनः।

ते Üाृणं तु मदीयं वै वाक्यं वीरजनार्चितं।। 62 ।।

मयाकृष्णेन शूरेण रुक्मिणी हि हृता हठात्।

कस्यकस्यास्तिवः शक्तिर्मोचनीयाचतेन सा।। 63 ।।

सर्वेषां पश्यतां वोचत् ह्रियते यदिरुक्मिणी।

भवदि्भः सेवकैः सर्वैः किं कुर्वन्ति नराधिपाः।। 64 ।।

भो षिषुपाल राजेन्द्र Üाृणुत्वं वचनं मम।

तव किं जीवितव्येन रुक्मिणीचेन्मयाहृता।। 65 ।।

भी भो भीष्ममहाराज तव पुत्री मया हृता।

सूर्येणाप्यथगर्वेण किं धैर्येण प्रयोजनं।। 66 ।।

Üाृणु रुप्यकुमात्वं तव स्वसा मया हृता।

द्वारिकायाथ नाथेन कृष्णेन बलषालिना।। 67 ।।

मोचापयतुमत्याष्चार्द्यदिव शक्तिमानसे।

मुधावोजीवतव्यं हि जातं सत्व विवर्ज्जितं।। 68 ।।

एतेषु विद्यमानेषु रुक्मिणी ह्रियते मया।

तदां किं भवतां शौर्य धैर्यं सत्वं मुधाखलु।। 69 ।।

आकृत्वा हि रणे युद्धं मयासह नराधिपाः।

कृतार्थत्वं कथं सर्वेः प्राप्यते तु नराधिपैः। 70 ।।

इतस्तुवाहयेद्वेगादित्युक्त्वा रथमुत्तमं।

वनवाह्येहि युद्धार्थं सविस्तारे भुवः तले।। 71 ।।

षिषुपालादयः सर्वेक्षुब्धास्ते तत्क्षणादपि।

कृष्णस्यवचनं श्रुत्वा रुक्मिणीहरणं तव।। 72 ।।

विनिर्गतं ततः पुर्यास्तत्सर्वं भीष्म भूपतिः।

सैन्यं रूप कुमारेण भीमेनापि युतं तदा।। 73 ।।

सैन्यं श्रीचेदिभूपस्य क्षुभितं सागरोपमं।

नीयतां नीयतां शीघ्रं शठं चौरं मलिन्मुचं।। 74 ।।

इत्युक्त्वा निर्गतं सर्वं सुमन्नद्धं रथान्वितं।

गजवाजिरथोष्ठैष्चयुक्तं भृत्य गणेन च ।। 75 ।।

वाजित्राणां च निर्घोषैर्गजानां वृंहितैस्तथा।

हेरिवतैष्च हयानां हि वंदिनां तु जया रवौ।। 76 ।।

रथानां चक्र चित्कारैः विस्फारैः च धनुषां तथा।

भ↓नामट्टहासैष्च कर्णाभ्यां श्रूयतेनहि।। 77 ।।

सर्वतो विसृतं सैन्यं धावमानं च पृष्टितः।

वेगतोपि समायातं रुरुधाते बलाच्युतौ।। 78 ।।

उद्धतानां नदीनां च वेगो वा सागरेण हि।

तुद्यतेतु तथारुद्धं ताभ्यां सैन्यं क्षणादपि।। 79 ।।

एकतः सकलं सैन्यं दृष्टं भटशताकुलं।

तावेवैकाकिनौ दृष्ट्वाचेकतस्तु तयायदा।। 80 ।।

तदाहि चिंतितं चित्ते किमेतद्वै भविष्यति।

ममाभाग्यवषाज्जात एतयोष्चायुषक्षयः।। 81 ।।

क्वचैतत् च महासैन्यं क्वैतोरुपगुणान्वितो।

एतयोर्मरणं प्राप्तं मदर्थं किं कृतं मया।। 82।।

विषमादरता जाता रुक्मिणी दुःखिताभृषं।

अश्रुबिन्दून् विमुंचन्तीदृष्टा हलधरेण सा।। 83 ।।

बलोनारायणं प्रोचे पश्येमां सुन्दरीदृषा।

विषवादं हि कुर्वन्ती दृष्ट्वास्यैन्यंघनपुर।। 84 ।।

प्रदर्ष प्रत्ययं किंचिदेतामा स्वासय द्रुतं।

कृष्णोपि दुःखितां दृष्ट्वा करुणा विष्टमानसः।। 85 ।।

प्रोवाच रुक्मिणीं तावत् श्रुणु देवि वचोमम।

मा कृथा हि वृथा दुःखं दृष्ट्वा सैन्यं समागतं।। 86 ।।

प्रेषयामिक्षणादेतान् भटान् सैन्य समन्वितान्।

स्वामिभिष्च समायुक्तान् मृत्यमेयम मन्दिरे।। 87 ।।

इत्युक्तेपि प्रतीतिष्च जाता तस्या नमानसे।

तथा च तादृषी दृष्ट्वा कृष्णौचेतामिदं पुनः।। 88 ।।

पश्य पश्य महाभागे ममषक्तिं जनातिगां।

दर्षयामि यथाप्येतां सत्यं प्रत्यय कारणं।। 89 ।।

पविसं चूर्ण कृष्णेन नीत्वा तस्यां गुलीयकान्।

स्वस्तिकं तु करे तस्या लिखितं तेन तत्क्षणात्।। 90 ।।

भिन्नाएकक्षणेनैव सप्रतालाः पुरः स्थिताः।

दर्षितास्तेपि रुक्मिण्या एकेनापि शरेण च।। 91 ।।

अत्यद्भुतां ततो दृष्ट्वा शक्ति कृष्णस्यरुक्मिणी।

पुनष्चिंतापुरा जाता तथैव विषवादिनी।। 92 ।।

कृष्णोथरुक्मिणीं प्राह बालचन्द्रानने Ÿाृणु।

अद्यापि दुःखिनी कस्मादृष्यसेतन्निवेदय।। 93 ।।

लज्जां संह्रव्य सा बाला संकोच्यकरकु ह्मलं।

जगादप्राणनाथं हि विनयानतमस्तका।। 94 ।।

Ÿाृणुनाथ महाभाग जानातित्वपराक्रमं।

ममोपरिकृपां कृत्वा विज्ञाप्यमवधार्यतां।। 95 ।।

पिताभ्राता च मे नाथ मौच्यौद्वौतुर रणांगणे।

लोकापवाद दुःखंस्यादन्यथा क्षितिमंडले।। 96 ।।

एतएव कृपां कृत्वा मौच्यौजनक सोदरौ।

श्रुत्वामुरद्विषः प्राहस्मितं कृत्वा च तां प्रति।। 97 ।।

न कर्त्तव्या त्वया देवि चिंता चेतसि दुःखदा।

विमु×चामिरणे नूनं तव तात सहोदरौ।। 98 ।।

माधवोक्तं वचः श्रुत्वा सहर्षा रुक्मिणीजगौ।

जयोस्तु सर्वदा नाथ रणोरिपुममाकुले।। 99 ।।

रेवतीरमनः प्रोचे श्रीधरं श्रीसमन्वितं।

षिषुपालोपि दुर्योध्यो मयायोद्धं न शक्यते।। 100 ।।

षिषुपालं विना सैन्यं सर्वमेतद्भटाकुलं।

ज्येष्यामि क्षणमात्रेणकांदिस्यैकं करोम्यहं।। 101 ।।

शिषुपालं महाश्रूरं जयत्वं हि रणांगणे।

इत्युक्ते माधवः प्राह का मात्रा चेदिभूपते।। 102 ।।

जयामिक्षणमात्रेण प्रेषयामि हरेर्गृहं।

इत्युक्त्वा प्रस्थितौ शूरौ सैन्यं सागरसन्निभं।। 103 ।।

रथेत् रुक्मिणीं मुक्त्वा जयावहित मानसौ।

धीरौसाहस संयुक्तौ वीरौ विद्या विषारदौ।। 104 ।।

चेदिराजं ययौ कृष्णः क्रोधः संदीपिता ननः।

यथामत्तगजाधीषं केषरी च भयोद्गित।। 105 ।।

शिषुपालोपि सम्प्राप्तो माधवं क्रोध पूरितः।

चक्राते तौरणं शूरौलोकाष्चर्य करं परं।। 106 ।।

तावत् च बलदेवोपि युद्धचक्रे भयावहं।

सर्वेणापिचसैन्येन समंवेषित सायकैः।। 107 ।।

मातंगान् पातयामास तुंगान् गिरि समानपि।

वेगवन्तोपियेचाष्वाः पातितास्तेरणाजिरे।। 108 ।।

गजैरथैष्व संयुक्तं स्थान् सचूर्णस्तदा।

शूरान् कुलवलोपेतान् घातयामास वेगतः।। 109 ।।

सैन्यं सर्वबलेनामाचक्रे युक्तं भयावहं।

एकतः सकलं सैन्यं मन्यतोपि बलीबलः।। 110।।

दैवाष्चर्यकरं जातं चिरं युद्धं क्षयावहं।

केनापि शक्यते स्थातुं नैव युद्धे बलाग्रतः।। 111 ।।

हतं तु सर्वतः सैन्यं कां दिषीकं कृतं यदा।

तदारूप्यकुमारोपित बलं प्रति समागतः।। 112 ।।

मुमोचनिषितंवानं बलं प्रति भटोत्तमः।

सैन्यं भंगात्यरं क्रुद्धोरोषरक्त मुखांबुजः।। 113 ।।

गत्वाते पिनवानेण तीक्ष्णेणापि बलं प्रति।

जातंकमपिनो विध्नं तस्य वज्रमयस्यहि।। 114 ।।

प्रकटस्तत्र संजातके बलं कोप पावकः।

लोहसंगाद्यथा नूनं पाषाणेग्निः समुद्भवः।। 115 ।।

चिरं युद्धं हि चक्राते बल रुप्यकुमारकौ।

नानायुद्धसमूहेन न विखिन्नौरणागणे।। 116 ।।

विफलं हरिणा कृत्वा कुमारं भीष्म भूपते।

मुमोचनाग पाषाख्यं वाणं संकर्षणोरुषा।। 117 ।।

गत्वा हि नागपाषेण बद्वोसौकुमारस्तदा।

नखंत्तं केष पर्यन्तं वेष्टितो रज्जुवदृढं।। 118 ।।

बंधयित्वा समानीय रुक्मिण्यास्तु समर्प्पितः।

कथितं बलदेवेन मक्षिकोडायनं कुरु।। 119 ।।

तावत्कृष्णोरणं चक्रेसमं चादिमही भृता।

शस्त्रैर्नाना विधैः कृत्वा सर्वेषां भयकारणं।। 120।।

पूर्वं लोहमयैः शस्त्रैष्चक्राते तौ रणं चिरं।

दिव्यायुधैः परं युद्धं चक्रतुस्तौ परस्परं।। 121 ।।

वर्त्तमानेरणेघोरे नारदः कलहः प्रियः।

नभस्थोनर्त्तनं चक्रे तुष्टचित्तः पुनः पुनः।। 122 ।।

संयुध्यर्विविधैः र्युद्धैः षिषुपाल समंहरि।

निःप्रभंगतषौर्यं च शत्रुं कृत्वा जनार्द्दन।। 123 ।।

दानिनं गुणिनं शूरं संपूजित धनाधिपं।

भीषणं तु कुलीनं च रौद्रं हि कुपितं रणे।। 124 ।।

जद्यानसंस्थितं चाग्रे राजराजं यथा हरिः।

पुण्यक्षयेक्षयोनूनं सर्वेषां प्राणधारिणां।। 125 ।।

खड्गखंडित पादौ वैहयाना दृष्यते रणं।

वीभत्सं चापि रौद्र च कबंधानां हि वर्त्तनैः। 126 ।।

गजकुम्भ स्थलास्थस्त रुधिराज्जात कर्दमं।

भग्नेनापि रथौघेन करुद्धर्दमेरुद्वदिग्मुखं।। 127 ।।

एवं विधं धरं कृत्वा हत्वा शत्रुंवलोत्कटं।

रुक्मिणी सन्निधिं यातौ बलनारायणौ मुदा।। 128 ।।

रुक्मिणी नम्रवदना लज्जा कुलित मानसा।

जगौदामोदरंणत्वा कृत्वा च कर संपुटं।। 129 ।।

श्रृणुनाथ महावाहो कृपा कृत्वा ममोपरि।

वद्धं वलने संग्रामे मुच स्वामिन् स्वसोदरं।। 130 ।।

स्मित्वामुक्त्वा च कृष्णोपि जगावेवंतु रुक्मिणं।

त्वं मेहि परमोबन्धु स्वजनोषीति निष्चितं।। 131 ।।

आनेतव्यं स्त्वयावषां स्नेहोत्यं तं ममोपरि।

रुक्मिणी हि स्वसा ते वैस्मरणीया त्वयानिषं।। 132 ।।

आगन्तव्यं त्वयावष्यं ग्रामे देषे गृहे मम।

धृत्वा तु हृदये स्नेहं रुक्मिणुपरिसंततं।। 133 ।।

इतिनाना विधैः वाक्यैः संसितोपि पुनः पुनः।

नोचेकिंचिद्वचः सोपिलज्जाकुलित मानसा।। 134 ।।

मुक्त्वातुरुक्मिणं तत्र कृत्वा नाना विधंमृतं।

रुक्मिणी बलदेवेन द्वारिकाभिमुखं ययौ।। 135 ।।

रथंतु वाहयामास बलभद्रोमुदान्वितः।

कृष्णोपि रुक्मिणीं प्राप्य कृतार्थ त्वं स्वमेनिरे।। 136 ।।

परस्परं समालापं कृर्वन्तस्ते विचक्षणाः।

सम्प्राप्य वांछितावस्तु कृतकृत्या मनोहरा।। 137 ।।

रिपवोपि जितायेन संप्राप्ताभीष्म भूपजा।

कृष्णस्य पुण्य माहात्म्यं प्रवक्तुं केन शक्यते।। 138 ।।

नानाविधैर्विनोदैष्च प्राप्तारैवतकाचलं।

रुक्मिणीतु नगं दृष्ट्ा सन्तुष्टो ह्दिचाभवत्।। 139 ।।

तत्र नन्दन संकाषे वने वृक्षलताकुले।

कृतं हि बलदेवेन तयोः पाणिनिपीडनं।। 140 ।।

तदादितत् च संजातं श्री रुक्मिणी वनं भुवि।

महतां संगमात् नूनं मुच्चता केन नापिते।। 141 ।।

महान्तः पुरुषा लोके यांति ग्रामेवनेपि च ।

तत्रापि सुन्दराचारं कुर्वन्ति पुण्य योगतः।। 142 ।।

क्रीडाचक्रेथ कृष्णोपि वने नन्दन सन्निभे।

तया नववध्यायुक्तो बालभद्र समन्वितः।। 143 ।।

रुक्मिणी बलदेवाभ्यां मन्यमानस्तदा →दि।

नगरं तद्वनं कृष्णः स्वजनौधैष्च पूरितं।। 144 ।।

रुक्मिणी बलदेवेन यावकृष्णो वने स्थितः।

तावछुद्विष्च संजाता स्वजनानां हि मन्दिरे।। 145 ।।

तावद्वारावती लोकः प्रमोद परिपूरितः।

श्रुत्वा कृष्ण समायात शत्रुं जित्वा वधू युतं।। 146 ।।

श्रृंगारिता पुरीतैष्च तोरणैः केतुभिस्तथा।

पुष्पैस्तु पूरिताः पंथा छंटिताष्चन्दना भसा।। 147 ।।

श्रृंगारियेवं पुरीं तां लोकाः स्वजन संयुताः।

सन्मुखं तु समायाता वेषैर्नानाविधैर्युताः।। 148 ।।

वाजित्राणां सहस्त्रेष्च वंदिनां निवहस्तथा।

महोत्सवेन मिलिता कृष्णदेवं बलान्वितं।। 149 ।।

कृष्णः सन्मानदानैष्च संतोष्यैबंद्याज्जनान् ।

चकारस्वजनैर्युक्त द्वारिकायाः प्रवेषनं।। 150 ।।

प्रवेषं क्रियमाने हि कृष्णे द्वारावतीं पुरी।

आयाता उत्सकालोकामार्ग्रे दृष्टुवधूवरं।। 151 ।।

द्वारिकायाष्च नरीणां कौतुकासक्त चेतसामं।

विनोदा विविधाजातास्तां च वक्ष्ये समासतः। 152 ।।

काचित्समुत्सकानारी समायाता निरीक्षितुं।

चूडाबन्धंकटौबध्वा कृत्वा षिरसि मेखलां।। 153 ।।

अन्यास्तत्र समायाता कृत्वा वेषं नवीनकं।

कुंकुमं नयनाभ्यां तु कज्जलं हि कपोलयो।। 54 ।।

स्तनयोरंचलं काचित्काचिदुद्घाट मस्तका।

कृत्वा तत्र समायाता वीक्षितुं तं वधू वरं।। 155 ।।

स्तनयोर्बालकं धृत्वा का चित्तत्र समागता।

स्वगृहेयापि बालस्य कुर्वन्ता स्तन्यपानकं।। 156 ।।

षिथिलं केषपाषं हि धारयन्ती मुखाग्रतः।

व्यग्राः द्रष्टुं समायाता काचिन्नारीतयान्विताः।। 157 ।।

भर्त्तुरत्नं विमुंछन्ती कडिछ्या धारितंपरा।

तथाविद्या समायाता तत्र द्रष्टुं वधूवरं।। 158 ।।

काचित् त्रुटितहाराच काचित् खंडित वस्त्रका।

द्रष्टुं तत्र समायाता जनसंघद्वयोगतः।। 159 ।।

जलमार्ग्रे स्थिता केचित् पश्यन्तीतिमुर्निर्मुहुः।

लज्जामुक्ता फलोपेता विससर्ज हरिं प्रति।। 160 ।।

दृष्ट्वा तं कौतुकं लोका कृतं नारीकदंवकैः।

जाहा रुच्चकैरेवं कराभ्यां कृत तालकाः।। 161 ।।

जगुरेवं वचोलोका पश्यन्तु कौतुकं स्फुटं।

तदादिहि गर्गाजातिः भण्यते स्त्री जनस्यकाः।। 162 ।।

कृष्णं वधू युतं वीक्ष्य जगुरेवं परस्परं।

पुण्ययोगेन जातोयं संयोग स्त्रीवरस्य च ।। 163 ।।

अपरावनिता प्रोचे धन्येयं कुल बालिका।

यथा लब्धोवरो विष्णुरुप निर्ज्जितमन्मथ।। 164 ।।

मन्मथं रति संयुक्तं विडंवयति निष्चितं।

काचिदन्यावचः प्रोचे जातं योग्यं हि संगमं।। 165 ।।

अपराकामिनी प्राहयकृतं हि पुरानया।

दानं तपो व्रतं चापि ध्यानं यात्रा जपस्तथा।। 166 ।।

तत्सर्वं हि समागत्य कोपिवक्तीहज्ञानवान्।

तत्सर्वं क्रियते स्माभिदानपुण्यव्रतादिकं।। 167 ।।

प्राप्यन्ते हि कृते यस्मिन् श्रीकृष्ण सदृषा नृपाः।

भवन्ति पुण्य हीनानां सफलानो मनोरथाः।। 168 ।।

एवं नाना विधं वाक्यं स्त्रीणां वदन संभवं।

रुक्मिणी सहितो विष्णुः Ük`.ou~ jktiFka ;;kSa ।। 169 ।।

रुक्मिणी प्रमदं प्राप्ता दृष्ट्वा श्रीद्वारिकां पुरीं।

जिनेन्द्रभवनानां च निवहैयातु शोभिता।। 170 ।।

वंदिष्यते मया मूनि चैत्यानि प्रत्यहं मुदा।

गृहीष्यामि फलंचात्रमृत्युःजन्म सद्भवं।। 171 ।।

रुक्मिणी सहितो विष्णु विवेषनिज मन्दिरं।

मांगल्यं हि कृतं श्रेष्ठं तत्र सौवासिनी जनैः।। 172 ।।

बलदेवोपि मनोगेहं कृष्णोगेहं निजं तथा।

कृतकृत्यो हि को लोके सुखं प्राप्नोतिनोनरः।। 173 ।।

रुक्मिण्या हि ददौ गेहं सुन्दरं नव भूमिकं।

धनधान्यैर्भृतयच्च दासीदास समाकुलं।। 174 ।।

रथवाहन संयुक्तं द्विपवाजी समन्वितं।

आयुधैर्विधियैर्युक्तं कृष्णाभरणभूषितं।। 175 ।।

तदैव भोजनं स्नानमाषनं शयनं तथा।

दामोदरस्य तत्सर्वं जातमन्यत्रनो कदा।। 176 ।।

मानसे वनेचापि शरीरे चैव रुक्मिणी।

सर्वत्र वषिता नूनं गुण युक्ता मनस्विनी।। 177 ।।

रुक्मिणी वदनांभोजे स×जातः षद्यदोहरिः।

मनसा वचसा चापि निगग्नः सुख सागरे।। 178 ।।

दुःखिनीं सत्यकां दृष्ट्वा दग्धाच विरहाग्निना।

नारदोथ सुखी जातः प्राप्तचित्र समीहितः।। 179 ।।

पुनःपुनर्ज्जगावेवं गत्वा चै सत्यभामिकां।

स्मरसि यत् कृतं वत्कृंवक्रं मयि समागते।। 180 ।।

प्रत्यहं नारदो गत्वा सत्यभामां प्रचारयत्।

शत्रूं हि दुःखितं दृष्ट्वा हर्षः कस्य न जायते।। 181 ।।

रात्रौदिवपि सर्वत्र स्वप्ने जागरणेपि च।

कृष्णस्य रुक्मिणी जाता नान्यजाता हि मानसे।। 182 ।।

गुणाः सर्वत्र पूज्यन्ते विद्यया किं कुलेन वा।

पुत्री विद्याधरस्यपि सत्यभामापि विस्मृता।। 183 ।।

एकदा कृष्णराजोपि क्रीडन् कामसुखं तथा।

किं चक्रेतत्प्रवक्ष्यामि महाष्चर्यकरं परं।। 184 ।।

एकदातत्य वासाने रुक्मिणी स्वामिनं जगौ।

कृष्णराज कृपाधार श्रृणुवाक्यं मदीयकं।। 185 ।।

मयापूर्वं श्रुतातेहि सत्यभामाभिधाप्रिया।

तस्यास्तु मन्दिरे नाथ गम्यतेन कथंत्वया।। 186 ।।

ततो नारायणः प्रोचे शृणु देवि वचो मम।

येनवाकारणेनापि तस्या गेहं नागम्यते।। 187।।

सहंकारांतु सा देविममतच्चनरोचते।

खंडितेयैस्तु कर्णो चै किं साध्यं स्वर्ण भूषणैः ।। 188 ।।

रुक्मिणी वचनं प्राह कृष्णं तु विनयान्विता।

शृणुनाथ कृपां कृत्वा कथयामि तवाग्रतः।। 189 ।।

योयस्यापि करेलग्नः सकथं तेन मुच्यते।

स्वर्णः खंडतिकर्णं चेत् स्वर्णं केनापि त्यज्यते।। 190 ।।

तस्या वाक्येन संतुष्टः प्रोचे तत्र सनातनः।

तव वाक्यात् गमिष्यामि तस्या गेहं तु रुक्मिणी।। 191 ।।

पत्रं पूगीफलं चैव चूर्णं खदिरसारकं।

युक्तं कर्पूर खंडैष्च रुक्मिण्याष्चर्चितं यदा।। 192 ।।

क्षिपन्ती तत् च तां कूलं भूमौ दृष्टा यदा तदा।

नीत्वा करेण कृष्णेन स्वयं बंधनिजाचले।। 193 ।।

तत्र स्थित्वा क्षणं कृष्णस्तस्तत्र सत्यालयं ययौ

वंचितुं तां प्रियां नूनं मनेकाद्भुत संकुलं।। 194 ।।

सत्यभामापि तं दृष्ट्वा कृष्णं न च वधूपतिं।

ईर्ष्यय वक्र वाक्यैष्च विषिष्टैर्जल्यिता तदा।। 195 ।।

नेदं भवति तद्गेहं वल्लभायास्त चैवहि।

मूढत्वेन समायातो गच्छ–गच्छ सनातना।। 196 ।।

अज्ञातत्वत्समायातस्तद्गेहं प्राणवल्लभे।

तथापि गमने गेहात्कथमन्यत्र शोभते।। 197 ।।

कृष्णोपि चक्र वाक्यैष्च तां सन्तोष्य मुहुर्मुहुः।

नर्ममर्म च हा वाणीं जगौ प्रेम करांपरां।। 198 ।।

यदि जल्यसि हे देवि निद्रायाहं वषीकृतः।

निद्रां भजामि ते गेहे निद्राचात्र गमिष्यति।। 199 ।।

सत्यभामाततः प्रोचे सत्यं निद्राकुलोभवान्।

तयातुन च वध्वाहि कर्त्तुं निद्रां नदीयते।। 200 ।।

सन्तोष्यातु नवीना हि त्वयापि मधुसूदन।

अहं भुक्ता चिरंकालं न किंचित्कथयामि ते।। 201 ।।

निर्विन्नेन त्वया नूनमत्रागत्य गृहे मम।

शयनं प्रत्यहं कार्यं सत्यं तेहं हितावहा।। 202 ।।

कृष्णोजगाद हे देवि हितं न क्रियते कथं।

नवीना वहवः सन्ति सर्वं मध्यत्वमग्रणी।। 203 ।।

इत्युक्त्वा कृष्णराजोपि संछाद्यमुखपंकजः।

निद्रां निषेवितुं लग्नः कपटाकुलमानसः।। 204 ।।

उत्तरीयांचलेवद्धं यच्च गंधवहं परं।

तस्य गंधवषात् तत्र समायाता हि षट्पदाः।। 205 ।।

षट्पदानांततिं दृष्ट्वा ग्रन्थिकायाः समंततः।

सत्यभामापि कोपेन जाता पूरित मानसा।। 206 ।।

रुक्मिण्याः कारणेवद्धमिदं वस्त्राचले निजे।

ममकृष्णेन नोदत्तामागतेनापि मद्गृहं।। 207 ।।

पश्यन्तु मोहमाहात्म्यमेकायास्तु प्रतारिते।

अन्यायादीयते सर्वं गन्धं सौभाग्यकारकं।। 208 ।।

इत्युक्त्वा कोप संयुक्त्वा ज्ञात्वा निद्रावषिकरिं।

संछोद्यग्रांथिकां तां हि निन्ये तस्यां जलादिदं।। 209 ।।

चन्दनेनापि सपीष्यमुक्त्वा चन्दन प्रस्तरे।

सौभाग्यार्थं तया लिप्तं मुखं चापि शरीरकं।। 210 ।।

शरीरं तेन संलिप्य चिंता कर्त्तुं समुद्यता।

अनेन गंधयोगेण कृष्णो मे वष्यतीव्रजेत्।। 211 ।।

इति चिंता कुलामूढा यदा हर्षेन पूरिता।

कौतुकातु मुहुध्याद्य जगौ कृष्णो हसन्निति।। 212 ।।

अयिमूढे किमारध्वं कर्त्तुं लोकविनिंदितं।

सपत्न्यामुखतांवूल कथं लिप्तंत्वयानद्ये।। 213 ।।

पत्रपूगीफलानां हि चयंतु चर्वितं तया।

मुखस्य लालयायुक्तं प्रेमावद्धं ममांचले।। 214 ।।

एतत् च निद्यंसतां नूनं त्वया लिप्तं कथं मुखे।

करतालं ददन्नुचैर्जहास च पुनः पुनः।। 215 ।।

आयताक्षि त्वदीयो हि पिता खेचरणायकः।

ममासि वल्लभानूनं प्राणेभ्यो न गरीयसी।। 216 ।।

अग्रणीत्वं हि नारीणां सर्वासां वर्त्तसे मम।।

तथापि जगतां निन्द्यं कृतं कर्म कथं त्वया।। 217 ।।

नदीनां च नारीणां च गतिनी चैव निष्चितं।

नार्यो वै नीचगामिन्यः सत्यं लोकवचः सदा।। 218 ।।

पुनः पुनः प्रकुर्वाणे हास्यं तिष्टन्ति केषवे।

लज्जितापि जगाचेवं सत्यभामा विचक्षणं।। 219 ।।

किं त्वं हससि रे मूढ़ रुक्मिणी हि ममानुजा।

त्वयानीत हठात् हत्वात् षिषुपाल नराधिपं।। 220 ।।

सा तवाग्रेमयैर्वात्रा रुक्मिणीहिं गुरुकृता।

ज्ञात्वा तदपि ताम्बूलं भीष्मजामुख सम्भवं।। 221 ।।

तस्यांगे भोगमासाद्या ममांगे जायते मुखं।

या मया वर्द्धिता वाल्येद्यौतं मौत्रादिकं पुरा।। 222 ।।

तस्यांगभोगतोमूढ़ निर्विचिकित्सामेदा।

एतएव कथं हास्यं क्रियते कारणं विना।। 223 ।।

कृष्णोजगाद हे देवि रुक्मिण्या वदनस्यहि।

ताम्बूलं वल्लभं चेत्ते ततो दास्यामि प्रत्यहं।। 224 ।।

सत्यभामा ततः प्रोचे श्रृणु वाक्यं जनार्द्दन।

आनेतव्यं त्वया चेत ताम्बूल मम वल्लभे।। 225 ।।

रुक्मिण्या मुख सम्भूतं प्राणनाथांचले स्थितं।

वल्लभामेकथं न स्यात् तत्र किं हस्यते त्वया।। 226 ।।

एवं वदतु हे देवि न हसामि मुनिष्चितं।

इत्युक्त्वा मौनमाधाय स्थितः कृष्णमहीपति।। 227 ।।

किंचित् कालं ततः स्थित्वा सत्यभामाजगौहरि।

रुक्मिण्या मिलितुं वांछावर्त्तते मम मानसे।। 228 ।।

सत्यं करोमि तं वाक्यं मेलयिष्यामि सुन्दरी।

तवचेत् वल्लभा सा हि नात्र कार्य विचारणा।। 229 ।।

इत्युक्त्वा क्षणमास्थाय मन्दं मन्दं विनिर्गतः।

रुक्मिण्या मन्दिरं प्राप्तः कृष्णप्रेमभरालयः।। 230 ।।

कृष्णं समागतं दृष्ट्वा रुक्मिणी सहसोत्थिता।

विनयात्प्रणुता नाथ कुलस्त्रीणामियं स्थितिः।। 231 ।।

कृष्णोप्यथ जगादे मां श्रृणु देवि वचो मम।

सितां शुकधरा भूत्वा रक्ता क×चुकया युता।। 232 ।।

सर्वभूषण संयुक्ता दिव्य रुपधरावरा।

सत्यकायावने गच्छ मदीये वचनात्प्रिये ।। 233 ।।

प्रमाणं हि प्रभोवाक्यमित्यु दीर्यतथाकृतं।

तां श्रृंगार युतां नीत्वा जगाम वनं हरिः।। 234 ।।

नानाविधद्रमाकीर्णां पुष्पुराजी समाकुलं।

कृतं भृंग समूहेन तू रणं हि तदागमे।। 235 ।।

वायुकंपित साखाग्रेवृक्षैष्च कृतं तांडवं।

पक्षिणां निवहैतस्तत्र कृतं जयजयारवं।। 236 ।।

कोकिलानां हि नादेन मयूर कृत्य नृत्यकं ।

एवं विधे वने गत्वा युक्ता कृष्ण महीभृता।। 237 ।।

इन्द्रेणैव समाभाति शचीवनन्दने वने।

तत्रास्ति वापिकारम्या स्वर्ण सोपान संयुता।। 238 ।।

अगाधजल संपूर्णा राजहंसैर्विराजिता।

युक्ता पंकज वृन्देन रथांगमिथुनैष्चिता।। 239 ।।

रत्नैनिवद्वकुलाष्च सत्वराषि समाकुला।

अषोकोनाम वृक्षोस्ति तस्याः पार्ष्वेमनोहराः।। 240 ।।

तस्याधो वर्त्तते रम्या वराहि स्फटिका षिला।

तस्योपरि निवेष्यैनां पर्यंकासन संयुताम्।। 241 ।।

कनवीरस्य गुल्मं तु करे वामे समर्पितम्।

वारणायालिवृंदस्य करं तु दक्षिणे मुखे।। 242 ।।

वनदेवीमयं रुपं नीत्वा तत्र व्यवस्थिता।

स्थापयत्वा तु तां तत्र सत्यभामा गृहंगताः।। 243 ।।

तत्र गत्वा जगादैनां प्रिये श्रृणु वचोमम।।

वर्त्तते हि किमुत्कंठा रुक्मिणी मिलिनायते।। 244 ।।

सत्यभामा ननः प्राह यदिनाथ कृपातव।

तदतुरुक्मिणी नामामद्भग्नी मेल्यतां मम।। 245 ।।

इत्युक्तेतुजगौ कृष्णोवने ते गम्यतां द्रुतं।

पूर्वं तुयात्व हे देवि पश्चात्साचागमिष्यति।। 246 ।।

तामान तुं गमिष्यामि रुक्मिण्या भवनेवरे।

इत्युक्त्वा तु तदा कृष्णः पुनरेव गतो वने।। 247 ।।

गुल्ममध्ये हि संवेस्य स्थितः कौतुक संयुतः।

तयोनिरीक्षितुं दर्प्यं रुपयौवनं सम्भवं ।। 248 ।।

गते कृष्णेपि सा देवि सत्यभामा वनेगता।

रुपयौवन संपूर्णा विविधैः भूषणैष्चता।। 249 ।।

वन मध्ये तु सादृष्टा स्थिताषोक तरोरधः।

एयंतु वन देवी हि ज्ञातं वै सत्यभामया।। 250 ।।

किंवासिद्धस्य कन्या वा किन्नरी वा सुरांगणा।

नागलोकात्समायाता किं वा नागवधूरियं।। 251 ।।

रोहिणीचन्द्रभार्या वा किंवामन्मथवल्लभा।

ब्राह्मी वा कमला वापिकेयं बाला भविष्यति।। 252 ।।

ज्ञातं सत्यं मया नूनं येयं बाला मनोहराम्।

मत्पुण्यत्प्रकटा जाता वनस्यैव हि देवता।। 253 ।।

देवताः प्रकटत्वं हि जायन्ते पुण्ययोगतः।

न तु पुण्य विहीनानां देवता दृष्टिगोचरम्। 254 ।।

देवताराधनं लोके नूनं इष्टवर प्रदम्।

आराधयामि भक्त्याहं निजकार्य समीहया।। 255 ।।

चिंतयित्वा चिरं चित्ते वस्त्राभरण भूषिता।

ममज्जवापिका नीरे कार्यार्थी कुरुतेन किं।। 256 ।।

अवगाह्यजलं तत् च नीत्वा पकंज वृंदकं।

निर्गता तु वहिः शीघ्रं तस्या गमन शंकिता।। 257 ।।

तादृषा एव सा सत्या जाता शोकं तरोरधः।

तत्रासौवर्त्तते रम्या रुक्मिणी कृष्णवल्लभा।। 258 ।।

तां तु नानाविधैः पुष्पैः पूजयित्वा विषेषतः।

पादयोः प्राणिपत्याषु जगादेवं च वोवरम्।। 259 ।।

मत्पुण्यात्प्रकटा जाता देहि मे वरमुत्तमम्।

दर्षनं देवतां हि निष्फलं न कदाचनम्।। 260 ।।

माधवं किंकरं भक्तं कुरु देवि तु सत्वरं।

मयिरक्तं ममाषक्तं विरक्तं रुक्मिणीं प्रति।। 261 ।।

तथा कुरु महादेवि रुक्मिण्युपरितो यथा।

चित्तं वै वासुदेवस्य न तिष्ठतिमनागपि।। 262 ।।

आगमिष्यति हे देवि पश्चात् कृष्णस्तयायुतः।

तावत् शीघ्रं वरं देहि ममोपरिकृपां कुरु।। 263 ।।

वलीवर्द्दो यथा बद्धो घ्राणेवारज्जुयोगतः।

आयातियाति वेगेन कृष्णं मे हि तथा कुरु।। 264 ।।

विधेहि रुक्मिणीं देवि चित्तोत्सिष्टां विषेषतः।

देहिमात वरं शीघ्रं विलम्बंमाकृथावृथा।। 265 ।।

इत्युक्त्वा तु चरणाग्रे पापात सत्यभामिका।

ललोट परया भक्त्या पुनः पुनर्विलापिता।। 266 ।।

एवं नाना विधां चेष्टा कुर्वानां सत्यभामिकाम्।

दृष्ट्वा वै गुल्ममध्येत् च निर्गतोऽसौ सनातनः।। 267 ।।

जहासकरतातैष्व सत्य भामां पुनः पुनः।

जगाद वचनं वाग्मी सत्यभामा सुखावहम्।। 268 ।।

सत्यभामे मदीयं ही वाक्यं श्रणु विचक्षणे।

सौभाग्यं जायते सत्यं रुक्मिणीचरण पूजया।। 269 ।।

रुक्मिण्यः पूजनाचेद्दिच प्राप्यते चिंतित फलम्।

तया स कथं मानं धार्यते मान धारिणि।। 270 ।।

पूजोपकरणं नीत्वा पूजनीया त्वया निषम्।

तस्याः पूजा प्रभावेन प्राप्यते चिंतितंयदि।। 271 ।।

किंकरस्ते भविष्यामि रुक्मिणी पदपूजनात्।

मात हास्यं न कृष्णस्य जठर स्यापि मध्यताः।। 272 ।।

ज्ञाता सा कृष्णवाक्येन रुक्मिणीसत्यभामया।

तदाहिलज्जितात्यन्तं विषणामानसे धनम्।। 273 ।।

चित्तेकोपं तु संयाम्यजाता वह्ये विचक्षणः।

प्रसन्नातु जगौ कृष्णं श्रृणु मुर्खषिरोमने।। 274 ।

यादृषोबालगोपालैः गीयसेनन्दनन्दनः।

तथा विधोभवान्नूनं नात्रकार्य विचारणा।। 275 ।।

गोपालानां भवत्येवं विधा चेष्टा शरीरिणाम्।

गोपालं तु विहायैकं कोन्योनिंद्यो भवेत् जडः।। 276 ।।

किं दीयते विधे नूनं मुपालंभमतः परम्।

एवं विधस्य मूर्खस्य दत्तं राज्यं त्रिखंडजम्।। 277 ।।

हास्यकर्मणि रे मूढकोधिकारस्तवै वहि।

ज्ञात्वा ततो मया सत्यं रुक्मिणीहि ममानुजा।। 278 ।।

अनुजायाः प्रणामेन को दोषो जायते मम।।

येनत्वं हससे मूढ विवेक परिवर्ज्जितः।। 279 ।।

स्त्रियो हि मिलिता यत्र भवन्ति कार्ययोगतः।

तत्र किं गमनं युक्तं नराणां तु विवेकिनाम्।। 280 ।।

विवेकेन तु ये हीनास्त्वादृषास्ते भवंत्यमी।

विलक्षां सत्यकां दृष्ट्वा गतः कृष्णो निरास्यदम्।। 281 ।।

रुक्मिण्या कृष्णवाक्येन ज्ञाता सा सत्यभामिका।

मुक्ता च देवीमयं रूपं लज्जिता सहसोत्थिता।। 282 ।।

नमाम विनयात्पादौ सत्यायारुक्मिणी तदा।

नूनं कुलप्रसूतानां विनयो हि महात्मनाम्।। 283 ।।

दोर्भ्यांततु समालिंग्यं संभाष्यैवं परस्परम्।

कुषलं तव कल्यानि शरीरे वर्त्तते ननु।। 284 ।।

ततोपि रुक्मिणी प्रोचे तवैव कृपया सखि।

तयोरुपं च लावण्यमन्योन्यं प्रविलोकितुम्।। 285 ।।

परस्परं तु संभाष्य वचोभिः प्रेमकारकैः।

यथायथंगतेस्थानं वनिते ते गुणान्विते।। 286 ।।

तदादिसत्यभामापि जातात्यन्तं सुदुःखिता।

निजनाथोपमानेन दुःखं कस्या न जायते।। 287 ।।

एवं यावत् स्थिते तेतुस्वेस्वेरो हे विचक्षणे।

जातं हि भुवि विख्यातं तावदन्यत्कथान्तरम्।। 288 ।।

एकदा कुरु नाथस्य दुर्योधनमहीभृतः ।

सभायां तु समायातो दूतो विष्णु महीपते।। 289 ।।

दूतोपि विनयात् नत्वा माधवं सदसि स्थितम्।

अग्रेलेखंवरं मुक्त्वा यथायोग्यं न्यवीविषत्।। 290 ।।

दृष्ट्वा लेखं स्थितं चाग्रे स्वयं नीत्वा करेण च।

स्वयं विलोक्य कृष्णोपि निजामात्य करे ददौ।। 291 ।।

अमात्योवाचयामास लखं स्पष्टार्थ वाचकम्।

श्रृण्वत्यां हि सभायां हि कृष्णानन्दकरं परम्।। 292 ।।

स्वस्ति श्री जिनमानम्य श्रीमद्वारावतीपुर।

कृष्णराज्यं नृपौधेन सेत्यमान पदाम्बुजम्।। 293 ।।

हस्तिनागपुरात् नूनं दुर्योधन महीपतिः।

प्रणम्य सादरं भक्त्या विज्ञाप्यं भक्तिसादरात्।। 294 ।।

अत्रस्ति कुषलं नूनं श्रीमतां कृपयामम।

तत्रत्यं भवतां सर्वं प्रासाद्यं कुषलादिकम्।। 295 ।।

अत्रापिस्थावयं सर्वे भवतां नैव संषयम्।

नवमस्माकं परोबन्धुः वर्त्तसे हे नराधिपः।। 296 ।।

किंचिद्वच्मि भवन्तं हि तव कर्त्तुं तु युज्यते।

मदीयं वचनं नाथ सर्वदा हितकारणम्।। 297 ।।

आवाभ्यां सुतयोःनूनं भावितः क्रितां ध्रुवम्।

विवाह विधिना मैत्री प्रषस्या सर्व देहिनाम्।। 298 ।।

पुत्रस्याष्च नराधीष तवाग्रमहिषी भवः।

मम पुत्री तदावष्यं विवाहो वरकन्ययोः।। 299 ।।

तव पुत्री कदाचित् च पुत्रस्यात् मम पुण्यतः।

तथापि नियतं कार्यो विवाहोवैविधानतः।। 300 ।।

योग्यो भवति सम्बन्धः सर्वेषां प्राणधारिणाम्।

निश्चयः क्रियतां नूनं तव चेतसि द्रुचितः।। 301 ।।

इति च लेखं वचः श्रुत्वा कृष्णो हर्षेण पूरितः।

विहसि वचनं वाग्मी जगावेवं सभान्तरे।। 302 ।।

करिष्यामि विवाहं तु युक्तं तेन महीभृता।

कोदोषोयोग्यसम्बन्धे युक्तमेतत्सतां ध्रुवम्।। 303 ।।

इत्युक्त्वा कृष्ण राजेन दूतसन्तोषितस्तदा।

वस्त्रतांवूलदानैष्च भूषणावि विषेषतः।। 304 ।।

प्रेषितास्तेन दूतेन समं दूतानिजस्तदा।

कृष्णराजेन तुष्टेन भूषणाभरणैः सह।। 305 ।।

दुर्योधन समीपं ते दूताः कृष्ण महीभृतः।

गत्वा सन्तोष्य सन्मान्य निष्चयौ हि कृतस्तदा।। 306।।

दुर्योधनेन कृष्णस्य दूताः सन्तोष्य प्रेषिताः।

जातोत्यन्तं सुखी कृष्णो दूतैष्च सा समागतैः।। 307 ।।

रुक्मिणी नैव जानाति तां वार्त्ता दूत सम्भवम्।

सत्याएव विजानाति नान्या नारी तु तां विना।। 308 ।।

रुक्मिण्यातु समायुक्तः श्रीपतिः सुखमन्यभूत्।

युक्तो यादव वृंदेन भूपैः मानित शासनः।। 309 ।।

सम्प्राप्य चिंतितं त्वर्थं वुभुजे सौख्यमुत्तमम्।

सौख्यं तु पुण्ययोगेन सर्वेषां प्राणधारिणाम्।। 310 ।।

पुण्याकृष्णोरुक्मिणीमाप नूनं पुण्याकृष्णः शत्रुराषिंविजिग्य।

प्राप्तः कृष्णोद्वारिकायां सुराज्यं पुण्यात् किं किं न प्राप्य भव्यजीवैः।। 311 ।।

पुण्यं कार्यं जिनवरं मते तीर्थनाथैः पुनीतम्।

पुण्यात्पुण्यं भवति भविनां सोमवत् सौम्यचित्तम्।। 312 ।।

यदुः प्राप्यं सकल भुवने दुस्तरं यत् च दूरे।

तत् च सौख्यं नृसुरगतिजं प्राप्यते पुण्ययोगात्।। 313 ।।

*** इति श्रीप्रद्युम्नचरिते श्रीसोमकीर्त्याचार्यविरचिते कृष्णरुक्मिणीपरिणयन, शिशुपालवध सत्यभामा विटंवन अजातसुत विवाहमिलेन वर्णनोनाम**

चुतर्थ सर्गः । *

पंचिमसर्गः

अथ सा सत्यभामापि रुक्मिणी विजिता सती।

दुःखाकुलासती चित्ते जाता निःस्वास मोचिनी।। 1 ।।

चिन्तयामास सा मूढ़ा चित्ते चैवं पुनः पुनः।

केनोपायेनदुःखं स्यात् रुक्मिण्याष्चति दुस्सहम्।। 2 ।।

नोपायं लभते साथकालेयातेधनेपि च।

यावत् पुण्योदयस्तावत् नोपायोदुःखदायिका।। 3 ।।

एवं विचिंत्यमाना सा दुःखोपायं दिवानिषम्।

स्मृतं दूतागमं तावत्तत्च विवाहकारणम्।। 4 ।।

हर्षद्विचिंतयामास लब्धोपायो मम ध्रुवम्।

येनदुःख विमोक्षः स्याद्रुक्मिण्याष्चाति दुःखदः।। 5 ।।

भविष्यति सुतोनूनं पूर्व शीघ्रं ममैव हि।

रुक्मिण्याहि ततः पुत्रो भविष्यत्यथवानवा।। 6 ।।

रुक्मिण्याः सर्वथा ज्येष्टा वयसा वपुषापि च।

शरीरस्यानुमानेन पुत्रस्तस्या भविष्यति।। 7 ।।

उपायंचात्र कुर्वेहं दुःखवारण कारणम्।

समक्षं बलदेवस्य कृष्णस्यापि सुनिष्चितम्।। 8 ।।

उपायं चिंतयित्वैवं सत्यभामा दृढं ह्वदि।

दूतिकां प्रेषयः शीघ्रं रुक्मिण्या मन्दिर प्रति।। 9 ।।

दूतिकापि ततो गत्वा मन्दं मन्दं भयान्विता।

रुक्मिणीं विनयात् प्राह श्रृणु मात वचो मम।। 10 ।।

त्वद्ग्रहेऽहं समायाता प्रेषिता सत्यभामया।

किंचित्कारणमुद्दिष्य दुभाष्यं कथ्यते कथम्।। 11 ।।

ततो भीष्मसुता प्रोचे नोच्यते हि कथं त्वया।

प्रतिशब्द समावाचो भवन्ति त्वदृषां खलु।। 12 ।।

ब्रूहि त्वं निर्भया भूत्वा यदुक्तं सत्यभामया।

तवास्ति निर्भयं दानं सत्यं सत्यं वचो मम।। 13 ।।

इत्युक्ते दूतिका प्राह प्राह श्रृणु मात मयोच्यते।

सुकेतजा वचो नूनं प्रोच्यते तु तवाग्रतः।। 14 ।।

तव पुण्य प्रभावेन पुत्रस्तेस्यात् च रुक्मिणि।

पूर्वं तस्य विवाहो वै भविष्यति न शंसयं।। 15 ।।

तव पुत्र पदस्याधोनीलवक्त षिरोरुहान्।

विदधामि निजांष्चाहं लग्न काले सुनिष्चितम्।। 16 ।।

अथेकदा चिन्मेभावी पुत्रो वै पुण्य योगत।

त्वयाप्येवं प्रकर्त्तव्यं यदुक्तं हि मयापुरः।। 17 ।।

विहस्य रुक्मिणीं प्रोचे दूतिकां प्रति सादरम्।

ममभग्न्यातु यत् प्रोचे तत्प्रमाणं वचो मम।। 18 ।।

एवं तु निष्चयं कृत्वा ताभ्यां दूत्यौ सभान्तरे।

प्रेषितेमान युक्ताभ्यां मनः सर्वस्व नाषनः।। 19 ।।

दूतिकाभ्यां तु गत्वात्र सर्व यादव साक्षिकम्।

कृष्णराजेन संयुक्तो बलोत्रप्रतिभूकृतः।। 20 ।।

इमांतु निष्चयां कृत्वा सर्वलोक समक्षिकाम्।

स्थितिं सुखाश्रिते गेहे निजेतेगर्व संयुते।। 21 ।।

भीष्मराजस्य पुत्रीहि निषाया विरमेन्यदा।

सुखं सुप्ताषयं नीयेमृदो पुष्पमये वरे।। 22 ।।

स्वप्नान्विलोकयामास मदनोद्भव सूचकान्।

पूज्यांष्च सर्वलोकानां प्रमान सुखकारिणः।। 23 ।।

स्वयं नभसि गच्छन्ति विमानेतस्थिता वरे।

विचरामि यथा कामं राज्य लीला समन्विता।। 24 ।।

इन्द्रस्य कु×जरं रम्यमैरावत समाद्वुयम्।

द्वितीयं तु स्वप्ने दृष्टं गंर्ज्जतं हि स्थितं पुरम्।। 25 ।।

उदयाचलमूर्द्धस्थः सविता सन्मुखस्थितः।

प्रकाषयंष्च पÁानां दृष्टः स्वप्ने तृतीयके।। 26 ।।

निर्द्धूमोज्वलनस्तुर्येततः कुमुदवांधवः।

अपांपतिस्तु षष्टे हि गर्ज्जन् दृष्टस्तयापुरः।। 27 ।।

स्वप्नानेवं विधान् दृष्ट्वा विबुद्वा रुक्मिणी ततः।

प्रभात तूर्यनादेन वंदिनां निःस्वनैस्तथा।। 28 ।।

शयनीत्समुत्थाय कृत्वा स्नानं विधानतः।

ययौकृष्णांतिकेसाथस्वं विभूष्य विभूषणैः।। 29 ।।

कृष्णराजं नमस्कृत्य वाम पार्ष्वेन्यवीविषत्।

नाथेनापि ततः पृष्टा तत्रागमनकारणम्।। 30 ।।

रुक्मिणी माधवं प्रोचे शृणुनाथ वचो मम।

निशायाः पष्चिमेयामे स्वप्नानि च दिनोदये।। 31 ।।

दृष्टानि च मया नाथ फलं तेषां निवेदय।

निवेदितानि कृष्णाग्रे तया स्वप्नानितानि च ।। 32 ।।

कृष्णेनापिफलं तेषां रुक्मिण्या विनिवेदितम्।

मोक्षगामी नभोगामी पुत्रस्ते वै भविष्यति।। 33 ।।

तेन वाक्येन तुष्टा सा जगाम निज मन्दिरम्।

मन्यमानानिजांके हि स्थितं पुत्रं विचक्षण।। 34 ।।

मधुभूपोचयोयोहि स्थितो वैषोडषेदिवे।

स×जातो रुक्मिणी गर्भमत्रागत्य स एवहि।। 35 ।।

पुरपुण्य विषेषेण भूषणं जठरस्यतुसांजातः।

स्वर्गसंसौख्यं भुक्त्वा कालं चिरंतनम्।। 36 ।।

तथैवतानि स्वप्नानि दृष्टानि सत्यभामया।

तथैव कृष्णभूपस्य कथितानि विषेषतः।। 37 ।।

कृष्णेनापि फलं तेषां तस्यास्तत् च निवेदिताम्।

सोपिस्वर्गेषितस्तस्या जठरे समाविषत्।। 38 ।।

तयोर्नार्योष्च यज्जातं गर्भयोर्वर्द्धमानयोः।

प्रोच्यं ते च मया नूनं समासाद्हर्षकारणम्।। 39 ।।

नयनयोर्निर्मलत्वं शरीरे चापि पांडिमा

कृष्णतापि ततो जाता कुचचूचकचायोर्भृषम्।। 40 ।।

आलस्यं गमने चाभूदकृषोदरता तथा।

वलीभंग च संजातामागतं रूपमुत्तमम्।। 41 ।।

विकारं विविधं व्याप्ते ते शरीर समुद्भवं।

सम्पूर्ण दोहदेजाते कृष्णस्यात्यन्त वल्लभ।। 42 ।।

सम्पूर्णं समये साथसुषवे रुक्मिणी सुतं।

तिथिनक्षत्रयोगेण शुभे च करणे तथा ।। 43 ।।

रुक्मिणी प्रमुदं प्राप्ता तनवे पुत्र जन्मना।

पुत्रं सूर्यसमं दृष्ट्वा लक्षणैर्विविधौष्चितम्।। 44 ।।

बान्धवै सह सन्तुष्टं कृष्णां ते प्रेषयत् नरान्।

वर्द्धापनाय कृष्णस्य मांगल्यौष्च विभूषितान्।। 45 ।।

ते नराः तत्र गत्वा हि सकाषं कृष्ण भूपतेः।

विलोकयन्ति यावत् च तावत् सुप्तोजनार्ढ्नः।। 46 ।।

उपविष्य स्थितास्ते हि कृष्णे निद्राकुलेतथा।

पादयोरंतिकं प्राप्य विनयानत मस्तकाः।। 47 ।।

प्रभवोयादृषा लोके तादृषाः सेवकास्मृताः।

तावत् तत्र समायाताः खेचर्या प्रेषितानराः।। 48 ।।

कृष्णं सुप्तं समालोक्यते तु गर्व समान्विताः।

मस्तकस्य समीपे हि निविष्टाः प्रौढि समायुताः।। 49 ।।

निद्रा विहाय भूपाले शय्याया उत्थितेसति।

पूर्वम् हि समीपस्थैर्विज्ञाप्तो भूपतिस्तदा।। 50 ।।

चिरंजीव नराधीष चिरंजीव नरेष्वरः।

चिरं राज्यसुखं भुक्त्व रुक्मिण्याः पुत्रजन्मना।। 51 ।।

नरैर्वर्द्धापिते भूपेतोषेन पुत्र जन्मना।

संतोषं परमं प्राप्ताः प्रमोद च नराधिपः।। 52 ।।

राजचिह्नं निराकृत्यं सर्वं तस्मै ददौधनम्।

पुत्रजन्मनिधानस्य कथकायनरायतु।। 53 ।।

कृष्णोपि हि निजान् प्रोचे जनान् समीप संस्थितान्।

आकार्यतां द्रुतं वत्सा आमात्यास्तुममान्तिकम्।। 54 ।।

आकारितास्तद्यदामात्यास्तैर्जनैर्नृपशासनात्।

आमात्यास्ते समागत्य नृपं नत्वा पुरः स्थिताः।। 55 ।।

नारायणो जगावेवं मामात्यान् विहितादरा।

दीयतामर्थिनां दानं यथेष्टं पुत्र जन्मनि।। 56 ।।

कारागृहात् विमु×चतु शत्रुणां च कदम्बकम्।

जिनेन्द्रभवनेस्वेषु पूजां कुर्वन्तु भावतः।। 57 ।।

पुरेहि क्रियतां शोभां महोत्सव पुरस्सरम्।

इत्यामात्यगणान् कृष्णः कार्यार्थ नियोजयत्।। 58 ।।

चक्री कृत्य ततो ग्रीवां विलोकयति माधवे।

वर्द्धापितस्ततः पश्चात् खेचरी प्रहितेष्वरैः।। 59 ।।

एकोजातोस्ति हे देव खेचर्यास्तनु सम्भव।

इत्युक्तेथ जगौ कृष्णो एतेभ्योदीयतां धनम्।। 60 ।।

भाग्यानुसारिणी बुद्धिः सर्वेषां प्राणधारिणाम्।

अतिगर्वाद्विनाषः स्याद्गर्वान्नष्टो हि रावणः।। 61 ।।

पुरे महोत्सवष्चाभूत् कृष्णस्य पुत्रजन्मतः।

याचकेभ्यः परं दानं दत्तामिछा प्रपूर्वकम्।। 62 ।।

बान्धवाः स्वजनाः सर्वे पूजिताः विहितादराः।

कुलस्त्रीभ्यः प्रदत्तानि वस्त्राणि विविधानि च।। 63 ।।

तोरणानि च बद्धानि विधिना नगरे तदा।

वैजयन्ती समूहं तु ततः सर्वत्रधारकम्।। 64 ।।

महोत्सवो महान् जातः सर्वलोक्य गृहेषु च।

कृष्णस्य पुत्रलाभेन हर्षः कस्य न जायते।। 65 ।।

हस्तिनागपुरे पूर्वं यथा जातो महोत्सवः।

शांतिकुंथ्वरनाथानां जन्मकाले सुरैःकृतः।। 66 ।।

ददौ बहुधनं राजा याचकेन्योथ वांछितम्।

वल्लभायास्तु पुत्रस्य लाभेनाथ वषीकृतः।। 67 ।।

मानयन् बहुधपूज्यान् हर्षयत् निजबांधवान्।

परमं तुष्टचित्तोऽसौ सुखेनाथ हरिस्थितः।। 68 ।।

अनेन विधिनातत्र वर्त्तमाने सदुत्सवे।

गेहे यादव भूपस्य गते च दिनपंचके।। 69 ।।

कृष्णपुत्रस्य हरणं ज्ञात्वा वाभाविनं तदा।

प्राप्तेषष्ठदिनेयापि रात्रोस्वजनदुःखदम्।। 70 ।।

तत् दुःख सहने नूनं असमर्थोरविर्यदा।

तदाप्यस्तमनं भेजे सतामेतद्विचेष्टितं।। 71 ।।

रविरस्तं गते तत्र यज्जातं तन्निगद्यते।

संकोचो नलिनीवृंदे मालिन्यं तत्र चाभवत्।। 72 ।।

शब्देन चक्रवाकीनां रुरोदनंलिनावधूः।

निस्सरन्नलिम्मिष्यदश्रुन्मुकुलाह्द लोचनात्।। 73 ।।

पतते चुम्बते चैनं मूर्छां याति पुनः पुनः।

पतिं विलोकयत्येव यथा वलितकंधरम्।। 74 ।।

कुप्यन्ती दिन नाथाय कातरा विरहेण सा।

संध्यायावासरे नूनं चक्रवाकी वियोगिनी।। 75 ।।

विचित्रांवर शोभा भूज्जलधौपतितेरवौ।

तद्वियोगेन संध्या सा कर्त्तुं काष्टस्य भक्षणम्।। 76 ।।

अस्तमितेयतौ सूर्ये परदिग्गणिका वधूः।

चित्रांवरधराजातााति स्वसौवानिषेवितुम्।। 77 ।।

अन्धकारसमूहैतुक्षिप्तौ विस्तरिते सति।

सर्वत्रापि तथा चाभूत्ससमता स्थलनिम्नयो।। 78 ।।

लोकानामुच्च नीचानां विविधाचारवर्त्तिनाम्।

सर्वेषां समता नूनं मलिनेतु यथा प्रभो।। 79 ।।

विस्तरते तमो राषौभिन्नांजाननिभे तदा।

नदिषो न तु वीरुध्यो नो भूमिर्नच पर्वताः।। 80 ।।

न नदी व वनं लोके दृष्यते नैव किं पुनः।

निरवधिर्यथा लोकः पृथिव्यां मलिनप्रभौ।। 81 ।।

अन्धकार समूहेतु दीपानां निकरो निषि।

रराजतेजसा युक्तो लौकैष्च प्रकटीकृतः।। 82 ।।

विमलः सुदषा युक्ताः सुपात्रस्य निषेचकः।

राजते तेजसा युक्तो मलिने मध्यगतेपिहि।। 83 ।।

रात्रौ तु रुक्मिणी सुप्ता गेह मध्ये सपुत्रकाः।

युक्ता नारी कदंवेन गीत नृत्य विधायिना।। 84 ।।

सुभटानां सहस्त्रं तु मुक्त्वा वैर क्षणाय च।

रुक्मिण्याग्रेह परितो विविधायुध धारिणाम्।। 85 ।।

कृष्णो गत्वा निजं स्थानं सुखं चिंता विवर्ज्जितः।

लग्नः कर्त्तुं तु निद्रांष रक्ष माणोङ्गरक्षकै। । 86 ।।

सहस्त्रैर्युवतीनां च युक्ता तत्रैव रुक्मिणी।

पश्यन्ती पुत्रवदनं हर्ष पूरित मानसा।। 87 ।।

यावत् तत्र स्थिता रात्रौ नाना विध महोत्सवैः।

तावदन्यविचारोभूत् रुक्मिण्या दुःखदायिकाः।। 88 ।।

यो सौ हेमरथोराजा जायातस्यह्रतापुरा।

मोहात् च मधुराजेन पापा च दृव्ध चेतसा।। 89 ।।

जायाया हरणं ज्ञात्वा राजापि विरहातुराः।

मुक्त्वाराज्यं तु तत्सर्वं वभ्रामविजने जने।। 90 ।।

गर्गोभूतत् चाति मोहैनमोहोवैः दुःखकारकः।

नगरं च वनं भ्राम्यन् प्राप्तौ सौ पंचतां तदा।। 91 ।।

भ्रमित्वा विविधां योनिं पूर्वकर्मानुसारतः।

ब्राह्मणस्य कुलौत्पन्नो यातोऽसौ तापसा श्रमम्।। 92 ।।

तापसैर्वाधितः सोपि प×चाग्निं साधय हठात्।

तेनकष्ट प्रभावेन मृत्वा प्राप्तो हि दैत्यताम्।। 93 ।।

एकदातु विमानस्थोविचरं निज लीलया।

रात्रौपथ समायातो रुक्मिण्या भवनोपरि।। 94 ।।

दैत्यस्यात्र समायाते विमाने बालकोपरि।

स्खलंनात्रस्य स×जाता वायुवेगेन गच्छतः।। 95 ।।

विमानं स्खलितं ज्ञात्वा चिंचितं वा सुरेण हि।

केनमे स्खलितं नूनं विमान दुष्ट बुद्धिना।। 96 ।।

जैनें वा प्रतिमाचाधो वर्त्तते किं पुरातनी।

शत्रुर्वावर्त्तते चात्र मित्रं वा कष्ट संयुतम्।। 97 ।।

किं वात्रांत्यषरीरोहि वर्त्तते दुःखपूरितः।

अन्यथामद्विमानस्य गतिनैनावरुध्यते।। 98 ।।

स कोस्ति भूतले नूनं येन मे गति रोधनम्।

क्रियते जीव्यते तेन कथं वा भुवनत्रये।। 99 ।।

प्रेषयामि दुराचारं नियतं यम मन्दिरे।

विमानं येन स्खलितं गच्छन्तं वाममांवरेः।। 100 ।।

एवं विमृष्यमाजस्य तस्य कुमति सम्भवम्।

वर्त्तते चावधिज्ञानं तेन ज्ञातं तदाखिलम्।। 101 ।।

मधुभूप चरेणात्र पापेन पूर्वजन्मनि।

कलत्रंतुमदीयं हि ह्रतं मोहातुरेण च।। 102 ।।

तया सह कृतं राज्यं तेन शंकाविवर्ज्जितम्।

ततः स्वर्गसुखं भुक्त्वा विविधं नाकसम्भवम्।। 103 ।।

अत्रैव रुक्मिणी गर्भे संजातः पूर्व पुण्यतः।

दत्तं पुरा भवेनेन जाया दुःखं महत्मम।। 104 ।।

तदायंतु समर्थोभूदषमर्थस्त्वहं पुनः।

अधुनाहं समर्थोस्मि बालोयमसमर्थकः।। 105 ।।

तस्मादेनं दुराचारं हठात् वा मारयाम्यहम्।

नहन्मि यदि तं बालं तदा मे दैत्यता वृथा।। 106 ।।

विमृष्यैवं चिरं दैत्यः कर्त्तव्ये कृत निष्चयः।

अवातरद सौव्यौमात् रुक्मिण्या भवनं प्रति।। 107 ।।

भटानां निवहंदृष्ट्वा सर्वमुद्धाटितायुधम्।

मनाग्रचकित चित्तोसौजातो दैत्यवरस्तदा।। 108 ।।

विमृष्यैवं चिरं चित्ते दैत्योहन्तु नरायमे।

पुनस्त समायातो दैत्य क्रोध विभूषितः।। 109 ।।

मोहयित्वाथ दैत्योपित भटानां निवहं तदा।

प्रविष्टो विवारनासौ दत्तयोष्च कपाटयोः।। 110 ।।

दृष्ट्वातु रुक्मिणीं दैत्यः पुत्र स्नेह भयालसम्।

मौहयित्वा क्षणंताहिजहीर पृथुकं तदा।। 111 ।।

उद्घाटिदैत्यनाथोपि कपाटयुगलं तदा।

बाह्येनीत्वा च तं बालं तथैव प्रददौमुदा।। 112 ।।

आकाषे बालकं नीत्वा जगौ दैत्योति दुष्ट धी।

क्रोधेनारक्तनेत्राभ्यां पुनः पुनर्विलोकयन्।। 113 ।।

रे रे दुष्ट महापापय त्वयातुपुराकृतम्।

मधूभूपेन स्मरसिह्रता जाया ममैवहि।। 114 ।।

तदा त्व हि समर्थोभूदसमर्थस्त्वहं पुनः।

अधुनावकिं किं ते ददामि दुःखमुत्कटम्।। 115 ।।

विदारयामि करजैः खंडखंडैः तिलोपमैः।

क्षयामि सागरे त्वां हि किं विधोर्मिसमाकुले।। 116 ।।

ददामि दिग्बलिं त्वाहि कृत्वा खंडान् सहस्त्रषः।

विदधामिदृषदा त्वां नीत्वा गिरिग→रे ।। 117 ।।

किं किं दुःखं ददामीह रे रे दुष्टराषयः।

स्मर पूर्व कृतं कर्म धनजौवन गर्वितः।। 118 ।।

कथयष्च दुराचार किं किं ते विदधाम्यहम्।

कथंस्यात्यमरं दुःखं पूर्वकर्मानुभागतः।। 119 ।।

विमिष्यैवं चिरं दैत्योर्नत्वातं गगनांगणे ।

तर्ज्जयन्चि विधैर्वाक्यै क्रोधारुण् निरीक्षणम्।। 120 ।।

कर्त्तव्ये निष्चयं कृत्वादत्योथ बालकं प्रति।

नीत्वाबालोत तो जातो गिरौ तक्षक नामनिः।। 121 ।।

नानानोकुह संकीर्णाः कंटका कुलभूतलाः।

कर्करैष्चचितातीक्ष्यौस्तथा गोक्षुर कंटकै।। 122।।

इगुटैः खदिरैर्विल्वैर्द्धवैः पलासकेस्तथा।

विषवृक्षैः समाकीर्णा तत्रास्ति खदिराटवी।। 123 ।।

नकुला हि समाकीर्णाः सिंह व्याघ्रादिभिर्युता।

यमस्यापि भयंकारी तस्यारौद्रं किमुच्यते।। 124 ।।

तत्रनीत्वा च तं बालं मुमोचासौ षिलातले।

द्विप×चाषत् गजानां हि षिलाचक्रे तथोपरि।। 125 ।।

चंपयित्वा तु तं बालं षिलायाचाति प्रौढ़या ।

पदाभ्यां ध्रुफणिकां चक्रे दैत्योऽसौ कृपयोझिता।। 126 ।।

जगाद वचनं दुष्टं दैत्यो दुष्टाषया तदा।

निजकर्मफलं भुक्तु यत्पुरा समुपार्जितम्।। 127 ।।

ममास्ति दूषनं नात्र दूषनं च तवै वहि।

इत्युक्त्वा सौगतोदैत्यः कृत कृत्यौ यथा रुचिम्।। 128 ।।

एवं कृतेपि दैत्येनमृतो नैवार्भकः सच।

न तु पुन्यवतां किंचिदापदं प्रभवंति हि।। 129 ।।

ध्यानं जपतपष्चेति पुराजन्मनिजकृतम्।

तस्य पुण्य प्रभावेन जातात्रांत्यषरीष्कः।। 130 ।।

तेनमोमरणं प्राप्तो न दुःखं लवमात्रकम्।

वने वा नगरेवापि पुण्यं रक्षति देहिनाम्।। 131 ।।

पुण्यं पुरातनं यस्य विद्यते भव्य देहिनः।

प्रभवन्ति न तस्यैवषत्रवो विविधा अपि।। 132 ।।

रात्रौतेनापि दैत्येन् किं कृतं बालकस्य च।

स्मृत्वा पुरातनं वैरं मां विनातद्विलोकये।। 133 ।।

इतिज्ञात्वा समायातो रविर्वाकरुणा परः।

विलोकनाय तत्सर्वमुदयाचल मस्तके।। 134 ।। – **युग्मं**–

तत्रस्थस्य च बालस्य यज्जातं पूर्वकर्मणः।

तत्सर्वं कथयष्यामि समासेन निषम्यताम्।। 135 ।।

जम्बू द्वीपोस्ति विख्यातो विजयार्द्धनगोत्तमः।

दक्षिणस्यां दिषिंस्तत्र मेघकूटादकयं पुरम्।। 136 ।।

विख्यात जन संपूर्णं जिन चैत्यालयैर्युतम्।

समृद्धं धनधान्यैष्च त्रिदषेंद्रपुरोपमम्।। 137 ।।

तत्रास्ति भूपतिः ख्यातो विख्यातो गुण संपदा।

कालसंवरनामेति शत्रुवंष निकन्दकः।। 138 ।।

तस्यास्ति च गुणैः ख्याता रामाश्रीकनकश्रजा।

निर्ज्जितस्वः वधू रूपयापरयारूपसंपदा।। 139 ।।

राज्यं करोति भूपो सौ कंटके परिवर्ज्जितः।

एकस्मिन् समये सोपि वनेरन्तुं विनिर्गतः।। 140 ।।

विमानेथ निविष्टोपि युक्तः कनकमालया।

रमयन् रम्य देषेषु वनेषु विविधेषु च ।। 141 ।।

रम्येषु मेरुश्रृंगेषु गंगाकुले मनोहरे।

रम्भावरे मनोज्ञेषु नन्दनादि वनेषु च।। 142 ।।

रम्यात् विविधान् देषान् युक्तः कनकमालया।

क्रमातत्र समायातो गिरिंबालक भूषितम्।। 143 ।।

कालसंवर भूपस्य विमानं गगने स्थितम्।

चलितं नैव सक्तोति कीलितं पुण्य योगतः।। 144 ।।

पदासौचिंतितुं लग्नष्चिंता युक्तो नराधिपः।

किमुचात्राथ संजातं कीलितं वत्रकेनहि।। 145 ।।

मुनींद्रोवा स्थितोष्चाधः कोपि ज्ञान विभूषितः।

जितेन्द्र मन्दिरं चात्र वर्तात प्रतिमायुत्तम्।। 146 ।।

ममास्ति मित्र शत्रुं वा को वाप्यत्रच संस्थित।

अथवा कष्टसंयुक्तः कोपिचांत्य शरीरकः।। 147 ।।

विलोकयामि तत् सर्वं विचारं चा संस्थितम् ।

विमृष्यन्तु तदा चित्ते स्वयं गत्वातु पर्वते।। 148 ।।

स्वयं तत्र समायातो युक्तः कनकमालया।

तक्षकाख्यै नगे तेन दृष्ट्वा च खदिराटवी।। 149 ।।

तस्या मध्ये नरेन्द्रेण षिला प्रौढा विलोकिता।

बालको मुख वातेन कुर्वनी नमन्नुन्नतिम्।। 150 ।।

एवं विधां षिलां दृष्ट्वा खेटोविस्मयमागतः।

किमेतत्कारणं नूनं दृष्टं हिनमया कदा।। 151 ।।

किंचिषरीर शक्त्या हिं किंचिद्विद्या प्रभावतः।

उधृतासु षिलातेन खेचरेंद्रेण तत्क्षणे।। 152 ।।

तस्याधोपिरिस्थितं दृष्ट्वा बालं चात्यंतसुन्दरम्।

कुर्वन हास्य मनाकूतत्र चपलं वक्रकुंतलम्।। 153 ।।

चपलौपाणिपादौ च बद्धमुष्टि युतौकरौ।

उत्पुलपÁवत् नेत्रं प्रतप्तकनकत् विषम्।। 154 ।।

निजवक्र समृध्या हि जितपर्वनिषाकरम्।

नवमृणालवत् भुजं सर्वलक्षण लक्षितम्।। 155 ।।

सुन्दरं सबलं धीरं सर्वावयवभासुरम् ।

सर्वेषां प्राणिना नेत्र मनोहरणकारणम्।। 156 ।।

निज पुण्यं प्रकाषतं पुराजन्म निज कृतम्।

निजेनांऽत्यषरीरेण जितदैत्य महारिपुम्।। 157 ।।

एवं विधं च तं दृष्ट्वा बालसर्वगुणान्वितम्।

कराभ्यां नृपतिर्निन्येतं च भूमितलात् तदा।। 158 ।।

नीत्वा बालं च भूपोपि चिंतां कर्त्तुं समुद्यतः।

कोऽप्ययं भाग्यवान् जीवोऽत्यन्तं प्रौढकुलोद्भवम् ।। 159 ।।

विमृष्यैवं क्षणं चित्ते जगाद दयितां प्रति।

गृहण बालकं देवि सर्व सुन्दर विग्रहम्।। 160 ।।

पुत्रार्थिनी तु त्वं बाले पुत्रस्त वनविद्यते।

अतएव गृहाणैवं पुत्रं सर्वगुणाकरम्।। 161 ।।

इति पत्यूदितं श्रुत्वा कर्णांमृतकरं वचः।

प्रसारितौ करौ हर्षात् तया कनकमालया।। 162 ।।

मोक्तुसमुद्यते भूपे तया संकोचितौ करौ।

तदा भूयो जगावेनां कथंतकर संहतिः।। 163 ।।

तदादेवी जगावेनं कुर्वतीचाश्रु संततिम्।

दुःखं सम्पूर्णं मेह्वदिया कृत्वा कर संपुटम्।। 164 ।।

श्रृणुनाथ महाभागममयत्कर संहतिः।

वर्त्तते तव गेहे तु पुत्राः प×चषताविभुः।। 165 ।।

तेषामनुचरो भूत्वा यदि जीवति बालकः।

ह्वदयं मम शल्यंस्या तदा किं जीवितेनमे।। 166 ।।

कृतं पुण्यं मयाचेत्स्यात्युराजन्मनि निष्चलम्।

तदामदुदरे बालोनिवसेत् च कथं विभो।। 167 ।।

अहं पुण्य विहीनास्मि यया जातो सुतोनहि।

सुखं स्यात् मम किं देव नूनं परसुते नहि।। 168 ।।

पूर्यतां नाथवानेन महादुःख करेण च।

इत्युक्तवा रुदितुं लग्ना दुःख◌दगभाषिणी ।। 169 ।।

एवं विधां च तां दृष्ट्वा राजापि करुणाकरः।

जगादमावृथा देवि दुःखं संतापकारणम् ।। 170 ।।

वृथा दुःखे कृते देवि म्लानंस्यान्मुखपंकजम्।

शरीरे कृषता भावो जायते तेज हानिता।। 171 ।।

समीक्षं ते मया दत्तं युवराज्यं सुयायते।

इत्युक्त्वा मुख ताम्बूलं नीत्वा तु तिलकं कृतम् ।। 172 ।।

युवराज्यपदे वत्स स्थापितोसि मया ध्रुवम्।

एकोहं द्वितीयस्त्वं हि मम राज्येनचापरः ।। 173 ।।

इत्युक्त्वा तिलकं कृत्वा दत्तोबालो नृपेणहि।

गृहीतो सौ तया सोपि प्रसार्य च निजौकरौ ।। 174 ।।

पित्रोः सौख्य करोवत्स भवजीवचिरं पुनः।

इत्युक्त्वा मस्तकं बालं चुम्बित्वा हर्षिताभवम्।। 175 ।।

विमानषिखरारुढ़ो पुरं जातो हि खेचरौ।

सन्मुखं हि समायातो लोकाः सामंत संयुताः।। 176 ।।

महोत्सवपरंचाभूत कृतोलोके नृपाज्ञया।

विभूत्यामन्दिरे गत्वा जगावेवं सुमन्त्रिण।। 177 ।।

श्रृणु तु सचिवा सर्वे वाक्यं कौतुककारणम्।

पूर्वं केनापिनोज्ञाता गूढ़ गर्भाप्रीया मम।। 178 ।।

भवदिभ्ः किं श्रुतं क्वापि गूढगर्भास्त्रियो ध्रुवम्।

आमात्यै नृपतेष्चिन्तं सन्तोषमय प्रजल्पितम्।। 179 ।।

श्रृतं पूर्वघनादेव गूढगर्भास्त्रियोधृतम्।

शास्त्रे श्रूयते चैवं प्रत्यक्ष्यमपि दृष्यते ।। 180 ।।

इत्युते सचिवैः सर्वेर्त्झगौ भूयो वचोवरम्।

प्रसूता तु वने देवि पुत्ररत्नमजीजनत्।। 181 ।।

प्रवेष्यतामियं शीघ्रं राज्ञी सूतगृहं वरम्।

सूतिका शीघ्रमागत्य सूतिकर्माखिल स्फुटम् ।। 182 ।।

कुर्वन्तु हि निजं कर्म योग्यं यत् च भवेत्मरम्।

अपुत्रिणी पुरादेवी तया जातोत्तोमासुतम्।। 183 ।।

इत्युक्ते तत्कृतं सर्वं यच्च भूपतिमानसे।

भूपतिस्तु पुनः प्रोचे श्रूयतां सचिवावचः।। 184 ।।

पुरेहि क्रियता शोभामुत्सवो जिनमन्दिरे।

याचकेभ्यः परं दानं दीयतां तु यथेप्सितम् ।। 185 ।।

शत्रवोचतां शीघ्रं सर्वेबन्दिगृहादिति।

राजचिË विहायोकमन्यत्सर्वं प्रदीयताम् ।। 186 ।।

इत्युक्ते तैः कृतं सर्वं महोत्सव पुरस्सरम्।

ध्वजतोरण संयुक्तं पुरं शोभान्वितं कृतम्।। 187 ।।

सज्जनामानिते सर्वे पूजिता बांधवास्तथा।

दुःखं निराकृतं तत्र सर्वेषां प्राणधारिणाम्।। 188 ।।

पश्यन्तु पुण्य माहात्म्यं भो भो भव्यजना भुवि।

उत्तमायत्रमाश्रंति तत्रापि शुभकारणम्।। 189 ।।

एवं महोत्सवं जातो नगरे तु षट्वासरेः ।

सप्तमे दिवसे प्राप्ते तस्य नामं प्रकल्पितम्।। 190 ।।

मिलित्वा स्वजनैः सर्वे महोत्सव पुरस्सरम्।

पराष्चदमतीत्यर्थे कृतः प्रद्युम्न संज्ञकेः ।। 191 ।।

तोषयन् स्वजनान् सर्वान् वर्द्धमानो दिने दिने।

यथा वर्द्धति बालो सौ रिद्धिः वृद्ध्यादिकं तथा ।। 192 ।।

भ्रमरो रमते नूनं कमात्कमले यथा।

करास्वकर संचारं प्राप्तो सा चर्भकस्तथा ।। 193 ।।

तत्र केचित् जनाः प्रोचुः किमेवालभ्यते सुतः।

न तु गर्व विहीनानां नारीणां जायतेंगजः।। 194 ।।

कोयं वा कस्य पुत्रो वा कस्य वाचटितः करे।

भूपतेः स्त्री सहास्य बालोयविजने वने।। 195 ।।

तत्रापरः परं प्रोचुः किं कार्यं भवतामिति।

तत्सर्वंत्यं मान्यते सर्वयच्च भूपतिनाकृतम्।। 196 ।।

न तु पुण्य विहीनोयं बालो में प्रतिभासते।

न तु पुण्य विहीनानामुत्सवाः खलु देहिनां।। 197 ।।

पुण्यात्समाप्यते सर्वंयच्चचित्ते विवस्थितम्।

एतएव नरैः कार्यं पुण्यं जन्मनिजन्मनि।। 198 ।।

वल्लभः सोन्यरामानां जातः पुण्य प्रभावतः।

प्रियः पुण्य प्रभावेण स्वजनस्य परस्य वा ।। 199 ।।

बालेपि हृयते तस्मिन् शत्रुणा पूर्व कर्मतः।

परदेषे सुखं प्राप्त स्तच्च पुण्यैक कारणम्।। 200 ।।

विविध पुण्य विषेष वा तां सदा भवति सौख्यमनेकविधंकरे।

इतिविबुद्धा सदैव हितावहं कुरुत भव्यजनाधर्ममुत्तमम् ।। 201 ।।

धर्मः सर्वसुखाकरो हितकरो धर्मो गुरुणां गुरुः।

धर्मात्सौख्यमनेकधा बहुमतं स्वर्गयवर्गादिकम्।। 202 ।।

धर्मात् कीर्त्ति समुन्नतासु विषदा शोमेव शुभ्रानिषम्।

तस्मात् जिनभषितं मुनिनुत्तं धर्मभजध्वं बुद्धाः।। 203 ।।

*** इति श्री प्रद्युम्नचरित्रे श्रीसोमकीर्त्याचार्यविरचिते प्रद्युम्नहरिणात् निधानं नाम पंचिमः सर्गाः ***

षष्ठमसर्गः—

तत्र स्वर्गासमाकारे पुरे खेचरसद्मनि।

सुखं पित्रोर्ददति च तस्मिन् कामेभिनन्दति।। 1 ।।

हतेथरिपुना बाले राज्यपत्न्या विचोष्टितं।

कथयामि समासेन जन्तूनां च दयाकरम्।। 2 ।।

बालेह्वतेथरिपुना विबुधा रुक्मिणी तदा।

विलोकयति सर्वत्र बालं सर्व गुणाकरम्।। 3 ।।

तल्यंतनूज रहितं तया दृष्टं यदा तदा।

परिवारं तया प्रोचे परं चकित मानसा।। 4 ।।

भो भो परिजना यूयं कथयत्वतियोगतः।

ममापहाययातोहि क्वासौबालो गुणाधिकः।। 5।।

इत्युक्त्वा सा पुनष्चिंतां कर्त्तुं लग्ना विचक्षण।

किं वा सुर कृता माया चेन्द्रजालं भवेदिदम्।। 6 ।।

स्वप्नोथवा किमथवा दृषो मे तिमिरं ननु।

चित्ते वा शून्यता जाता ममकिंवात सम्भवा।। 7 ।।

ह्वतोसुरेण में बालः केनापि पूर्वा वेरिणा।

चेटिकाया करे किं वा रमनाय स्थितोर्भकः।। 8 ।।

धात्रिकाया समीपेस्ति पयः पानार्थमेव किं ।

किं वा परिजनैः नीतोरमणायाति प्रेमतः।। 9 ।।

इति विकल्य जालं हि कृत्वा नाना विधं तु सा।

मूर्छामवाप्य निष्चेष्टा जाता प्रेम भरालसा।। 10 ।।

देवेनदारुणे नासौ हतो बालोतिवेगतः।

भूमौपयात सहसा मुक्तके साथ तेन किं।। 11 ।।

ततः परिजनैर्वोधं नीता सा तु विचकक्षणा।

कृत्वाषीतोपचारं हि हरिचन्दन सम्भवं।। 12 ।।

वक्षौजघान हस्ताभ्यां मुक्त कंठरुरोदसा।

कुर्वती करुणासक्तो परिवारजनं तदा।। 13 ।।

हार्बल क्व गतोसि त्वं हा हा कुटिलकुन्तला।

हा सुनासिकलायुक्तः पूर्णचन्द्र निभानन।। 14 ।।

हा हा कमलनेत्रोसि भ्रू विकार युतोसिहा।

कामपाष समो नूनं कर्णयाषोसिहासुत।। 15 ।।

हा हा कम्बुसमः कंठोवर्त्तात तव सुन्दरः।

हा हा करिकराकारौ दृढौ बाहूतवै वहि।। 16 ।।

इति नाना विधैर्वाक्यै रुदितारुक्मिणी यदा।

अन्तः पुरं च कृष्णस्य रुदितं तु तदाखिलं।। 17 ।।

तदायौरजनाः सर्वे ज्ञात्वा वृत्तं तथैव तं।

विलापं परमं चक्रु ल्लोकानां दुःखकारणम्।। 18 ।।

तद्विलापं समाकर्ण्य रुदितं यादवायपि।

तारहार समाकारैस्तत्र तैर्वाष्पबिन्दुभिः।। 19 ।।

आकस्मिकं च तं नादं श्रुतांनेव कदाचन।

विबुद्धः सहसाकृष्णः श्रुत्वा तत् चातिदुःखदं।। 20 ।।

ततः पार्ष्वजनान् कृष्णमं प्रोचे श्रृण्वन्तु हे जनाः।

कोलाहलं निषान्ते किं हाहाकारेण मिश्रितं ।। 21 ।।

गत्वा कृत्वा विलोक्यापि ज्ञात्वा त्वागम्यते द्रुतं।

इत्यादेषं विभोः प्राप्य गतोवैत्री सुचेगतः।। 22 ।।

गत्वासौद्धांतमध्ये सौ ज्ञात्वा तच्चरितं तदा।

विनिवृत्य समायातो दुःख पूरित मानसः।। 23 ।।

वासुदेवोग्रतः स्थित्वा नोचे किंचिन्नताननः।

कृष्णो जगाद तं तत्र कथं जल्यसिनो मम।। 24 ।।

दुःखगद्गदया वाचा जगौ वेत्री हरिं प्रतिं।

किमुच्यते मया नाथ वक्तुं लजुक्रंन साम्प्रतिं।। 25 ।।

कृष्णं जगाद किं नूनमसंभाव्यमिदं परं।

न जल्यसि महादुःखं दुःख युक्तो भवानपि।। 26 ।।

जगौवेत्रीतु हे नाथ रुक्मिण्याथ सुबालकंः।

ह्रतः केनापि दुष्टेन ज्ञायतेनहि कारणं।। 27 ।।

तत् व्रजपात सदृषं श्रुत्वा वाक्यं स जनार्द्दनः।

किं कि किमिति सजल्यन् ततो मूर्छामुपागतः।। 28 ।।

तद् दुःख भार भग्नो वा शखीव पतितो भुवि।

दृष्टं पार्ष्वः स्थितोलोकैः किमयंपतितो गिरिः।। 29 ।।

ततः परिजनैत् दुःखात्कृत्वा शीतोपचारतां।

निराकृत्य च तां मूर्छां संज्ञातां लभितोहरिः।। 30 ।।

संज्ञामप्राप्य कृष्णोपि तेनेथ परिदेवनं।

तेन नादेन लोकोपि जातः शोकभराकुलः।। 31 ।।

हा पुत्र किमिदं जातं क्व गतोसि भवानपि।

त्वां विनाजीव तव्ये न मम नास्ति प्रयोजनं।। 32 ।।

राज्यनाप्यथ कौषेन किं वा परिजने नमे।

ग्रामकर्वट खेटोघैर्मटं वानां चयैरपि।। 33 ।।

किं वा राज्य समूहेन गजवाजिरथेष्च किं।

मम सर्वंच्चदायत्वं त्वां विनाविफलं जगत्।। 34 ।।

पुण्यहीनं च मा त्यक्त्वा कथं यातोसि पुत्रक।

दीनं च दुःखिततरं निर्बन्ध च त्वयोष्भितं ।। 35 ।।

सा धारय निजं तातं पतन्तं दुःख सागरे।

कुलारविंद सूर्योसि नूनं वत्सुगुणाकरः।। 36 ।।

ह्रतोथ यादवानां हि त्वं कुलार्णवचन्द्रमा।

हा सुन्दरषरीरोसि हाहा वै मधुर स्वर।। 37 ।।

हा हा वत्स महाभाग हा बान्धव मनांम्बुजे।

राजहंस समोसित्वं क्व यातोसि गुणालय।। 38 ।।

विलाप्य विविधेर्वाक्येष्चिरं गरुडकेतं।

बन्धुभि सहितः शोपि वाष्पधूताधरस्तदा।। 39 ।।

धुन्वन् षिरष्च दुःखेन रुक्मिणी मन्दिरं प्रतिः।

उपालम्भं विधेर्यछन् मन्दं मन्दं यायोहरिः।। 40 ।।

कथं सृजसि हे नाथ नररूपं मनोहरं।

लावण्य लक्षणोपेतं मनोहरण कारणम्।। 41 ।।

एवं विधं नरं सृष्टात् कथंभो ह्रियते त्वया।

यत्कृत्वा ह्रियते नूनं धिक् पांडित्यं तवैवहि।। 42 ।।

रुक्मिणी सदनं प्राप्य सपन्नैवं प्रजायतिं।

आगच्छन्तं हरिं दृष्ट्वा रुक्मिणी सहसोथिता ।। 43 ।।

विनयं कुलजं कृत्वा पुनः मूर्छामुपागता।

दृष्टे प्राणसमे नूनं दुःखं स्यात् प्रकटं नृणाम्।। 44 ।।

पुनः शीतोपचारेण मूर्छा तस्या निराकृता।

संज्ञामप्य सा बाला विलाप कर्त्तुमुद्यता।। 45 ।।

उपविष्य हरिस्तत्र सन्मुखं दुःखपूरितः।

गाढं कर्त्तुं प्रवृत्तोऽसौस्मरन् बालं मुहुर्महुः।। 46 ।।

विलापं कुर्वती बाला प्राणनाथं जगाविति।

कथंगतोहि मे बालः प्राणनाथे विभो त्वयि।। 47 ।।

मम भाग्यवषानाथ ह्रतोबालो मामेवहि।

करोमि मंद भाग्या किं गत पुत्रास्म्यहं विभो।। 48 ।।

पतन्ती च लुठन्ती च भूमो वि·लमानसा।

कुर्वन्ती च कराभ्यां साहृदयास्फालनं तथा ।। 49 ।।

मुक्तकेषाकुला बाला मुक्तकंठ रुरोद सा।

किं करोमि क्व गच्छामि धीरयामि कथं मनः।। 50 ।।

विलपन्ती च तां दृष्ट्वा कृष्णोदुःख भरालस।

विलपन्ती जगौ रामां श्रृणु देवि वचो मम ।। 51 ।।

मत्प्रामादवसेनासौ हृतोबालोगृहांतरात्।

किं करोति च मूढात्मा विधिनाहं प्रतारिता।। 52 ।।

एवं दुःखाकुलौ जातौ विलापं कुर्वातो यदा।

तदामागत्यमागत्य स्थिता वृद्धाः कुलागताः।। 53 ।।

प्रणम्यपरयाभक्त्या हरिं रुक्मिणीमं युतां।

दुःखगद्गदया वाचातेपिषोक समन्विताः।। 54 ।।

श्रृणुनाथ महाभाग जानात्सि भव चेष्टितं।

ये ये संसारिणो जीवाः तेषां नाषोध्रुवं मतः।। 55 ।।

ये ये विचक्रिणो जाताजित खेचर भूमियाः।

वशीकृता हितैरेषा षट् खंण्डा च वसुन्धरा।। 56 ।।

अन्तकेन च ते सर्वे कवलीकृत सत्वकाः।

नामावषेषतो नूनं पठिता भांति भूतले।। 57 ।।

ये च तीर्थाधिया जाता सुरासुर नमस्कृता।

केवलज्ञान दीपेण ज्ञात विष्व विचेष्टिताः।। 58 ।।

संसारात्सर्व जन्तुनां तरितुं तारितु क्षमाः।

कृत्तां तस्य मुखे तेपि गताः कवलमात्रतां।। 59 ।।

बलदेवाष्वयेनाथ जे चवै मधुसूदनाः।

महासत्ववलोपेता नूनं ये प्रति सत्रवः।। 60 ।।

द्विपेन्द्र रथयोधेष्च वाजिभिः तरक्षकाः।

कीनाषदं तदलिताः सर्वेतनिधनं गताः।। 61 ।।

अन्येपि महासत्वा शूरावीरा बलोधत्ताः।

कृतकर्मप्रभावेन जातास्ते च क्षयं विभो।। 62 ।।

शूरावीरा नराधीषा ये च खेचर नायकाः।

तिर्यं चः यन्नगाष्चापि गतास्ते हरि मंदिरे।। 63 ।।

जातस्य हि ध्रुवं मृत्युरित्युक्तं जिननायकैः।

निजकर्म वषात्प्राणी सुखं दुःखं च भुंजति।। 64 ।।

कृतां तस्य विचारं च मत्वात्वेवं च भो विभो।

मु×चषोकं च दुःख च शोकं संसार कारणम्।। 65 ।।

शोकात्प्राणिनां दुःखं नैव जाति कदाचन।

गतं मृतं विनष्टं चानेव षोचन्ति पंडिता।। 66 ।।

शोकक्षुधा च निद्राच क्रियतेहि यथा यथा।

सर्वं चिन्ता विषेषेन वृद्विं याति तथा तथा।। 67 ।।

त्वयि शोकाकुले नाथ नूनं विष्वस्य भर्त्तरि।

लोकः शोका कुले नूनं विकलत्वं प्रयास्यति।। 68 ।।

एवं विचार्य हे नाथ शोकः कार्यस्त्वया नहि।

ज्ञातविष्व विचेष्टानां शोकः किं क्वापि युज्यते।। 69 ।।

प्रायेन यादवकुलेप्रसूतो यस्तु बालकः।

सौभाग्य बाल संयुक्तः सचिरायुर्नसंसयः।। 70 ।।

क्वापि तिष्टति बालोसोनीत्तः केनापि शत्रुणा।

कलांतारण बालस्ते समेष्यति विभो गृहं।। 71 ।।

आमात्यानां वचोभिष्च हत्वा शोकं निजं हरिः।

लोलालकाकुले मुखी जगाद रुक्मिणीं प्रति।। 72 ।।

दीर्घायुषो न मरणं तव पुत्रस्य वत्तेते।

एतएव त्वया देवि शोकस्त्याज्यो विचक्षणे।। 73 ।।

मत्प्रामाद वषाबालो हृतः केनापि वेरिणा।

राकाशषांक वदने शोकं जहि मृगेक्षणे।। 74 ।।

त्वत्पुत्रं सकलां भूमिं नूनं भट कदम्बके।

अन्विष्यतं सुवदने त्वत् अ🕛तु करोम्यहं।। 75 ।।

निवार्यरुदन्ती बालां शोकारुण निरीक्षणां ।

प्रेषयामासा सेन्येन संयुक्तान् सुभटोत्रमान्।। 76 ।।

दुर्भेद्यकवचान् शूरान् निषितायुध धारिणः।

नवजौवन संयुक्तान् हयारुढान् बलान्वितान्।। 77 ।।

सद्धं सकुषलोद्भूतान् वीरान् सत्यव्रतान्वितान्।

विससर्ज प्रतिदिषं पुत्रान्वेषन हेतवे।। 78 ।।

गताः स्तेसुभटाः सर्वे विसृष्टा हरिणातुये।

गिरिकंदर दुर्ग्रेषु वनेषु विविधेषु च।। 79 ।।

सरित्सागर तीरेषु ग्रामेषु नगरेषु च ।

जलस्थल निकायेषु विविधाश्रय भूमिषु।। 80 ।।

विलोकेवं भटाः सर्वे सर्वत्र क्षितिमंडलं।

न दृष्टो सौ यदा बालस्तदा ते खिन्नमानसाः।। 81 ।।

व्यावृत्य च समायाताः पुनःऽस्त द्वारिकांपुरीं।

मिलिताः कृष्णभूपस्य पश्यतोधो भुवस्थलं।। 82 ।।

दृष्ट्वा म्लान् मुखान् कृष्णष्चिंतयामास मानसे।

एतैष्च मम पुत्रस्य शुद्धिर्लब्धान साम्प्रतं।। 83 ।।

चित्तेषोकं च संयम्य स्थितो सौ माधवोनृपः।

तथैव भूपतेपुत्री कृष्ण वाक्यानुरोदतः।। 84 ।।

तथैव च स्थितालोको द्वारिकाया निवासिनः।

नष्टोत्सवापुरी जाता राजायत्तं भुवस्थलं।। 85 ।।

नोत्सवान च वाजित्रं नो गीतं न च नृत्यता।

नष्ट शोभापुरी सर्वाः पुत्रस्य विरहे भवेत्।। 86 ।।

तावत् समागतो व्योमात् नारदोमुनि सत्तमः।

अवतीर्यवने जावदसौ त्मो विवस्थिता।। 87 ।।

पुरीं विलोकयामास नारदोमुनि नायकः।

तावत् निरुत्सवा दृष्ट्वा पुरी शोभा विवर्ज्जिता।। 88 ।।

पृष्ट्वा च केचिन्नितरं ज्ञातं सर्वं विचेष्टितं।

रुक्मिण्याः पुत्रहरणं कृष्णस्य शोक कारणं।। 89 ।।

श्रुत्वा वज्रोपमं वाक्यं कर्णयोर्दुःख कारकं।

तेनदुःखाकुलो भूमौ पपात मुनिनायकः।। 90 ।।

किंचित्कालं स्थितं तत्र मूर्छया सहितोमुनिः।

पुनष्चवनया तेन मुनेर्मूर्छागता तदा।। 91 ।।

गुणदोष विवेकादि शून्यो जातोति दुःखतः।

स्थित्वा मुहूर्त्तमात्रं तु चलितो नगरं प्रति।। 92 ।।

मन्द मन्दं गतस्तत्र यत्रसौ माधवोनृपः।

कृष्णोपि नारदं दृष्ट्वा विष्टरादुस्थितस्तदा।। 93 ।।

मुनिष्च पादयोर्नत्वा शोकं चक्रे जनार्द्दनः।

नारदो मौनमालंव्यं स्थितो दुःख भरेण च।। 94 ।।

मौनं स्थित्वा क्षिणं सोपि दुःखं संयम्य मानसे।

दुःख गद्गदयावाचा कृष्णमूचे मुनिर्वरः।। 95 ।।

स्याद्वदगर्भ सम्भूतं यद्गीतं जिननायकैः।

तेन बोध बलेनापि निवार्जनिज दुःखतां।। 96 ।।

जानाति सकलं तत्वं प्रतिबोध न पंडितः।

एवं विधोपि कृष्णस्य दुःख दुखी ऋषीष्वरः।। 97 ।।

श्रूयतां कृष्ण भूपाल वचो मे जिन भषितं।

जीवासंसारिणोस्तेषां नाषोजाति न संसयः।। 98 ।।

अतः शोको न कर्त्तव्यः शास्त्रार्थ कुषलैर्नरिः।

शोकेनापि न चायाति गतवामृतवेवहि।। 99 ।।

य वैत्यक्त्वानु संसारं ज्ञासर विवर्ज्जितं।

वनेया यमेवात्र धन्यास्ते तु नरोत्तमाः।। 100 ।।

तेषां सुखं न दुःखं हि मातृ पितृ वियोगजं।

पुत्रेहतेथ रिपुना मृते नष्टेताथे वच।। 101 ।।

वनंगतोस्म्यहं नूनं त्यक्त्वा संसारिकं सुखं।

देषव्रता निसंगृह्य सम्यक्त्वे न विभूषितः।। 102 ।।

तथापि तव शोक न शोकी जातो जनार्द्दनः।

स्नेहो बंध निमित्तं च सर्वेषां प्राणधारिणं।। 103 ।।

तव दुखं समालोक्य जातं पुत्र वियोगतः।

मन्येन जीवितं नूनं निष्चया विफलं मम।। 104 ।।

बान्धवानां समालोक्य दुःखं शोकं तथेव हि।

सन्तोषं को नरोजाति कृतोपकारकं विना।। 105 ।।

तव दुःखवसात् नूनं दुःखमस्मादृषां ध्रुवं।

तस्माद्विमुंच कृष्णत्वं दुःखं संकावियोगजं।। 106 ।।

स्नेहोनि सुतस्यैव दुःखं कस्मै ददाति न।

देवमन्त्र समानोपि कस्त्वां शोकद्विमुंचति।। 107 ।।

एवं विबुद्धा चित्तेस्वे शास्त्रार्थ कुषलो भवान्।

निवारय निजं शोकं संसारस्येव कारणं।। 108 ।।

एवं विधोस्ति को लोकेयस्त्वां बोधयितुं क्षमः।

सूर्यस्यापि प्रकाषाय दीपो वा केन दीयते।। 109 ।।

इति नाना विधेर्वाक्यै मुनिना बोधितो हरि।

जगाद नारदं सोथ श्रृणुनाथ वचो मम।। 110 ।।

रुक्मिणी सदनं गच्छ बोधयत्वहि रुक्मिणी।

विलोक्य रुक्मिणी दुःखं मम दुःखं महद्विभो।। 111।।

दुःखापनोदं कृष्णस्य कृत्वा नारद सन्मुनिः।

जगाम रुक्मिणीगेहं तस्या दुखेन दुखतः।। 112 ।।

आगच्छन्तं मुनि दृष्ट्वा रुक्मिणी नारदाट्कयं।

समुथाय स्वयं मुक्त्वा विष्टरं नारदाय सा।। 113 ।।

उपविष्य मुनिं तत्र भक्त्यातं प्रणनाम च।

इष्ट दृष्टोहि दुःख महतां दुःख जालेपि विनयोनैव गच्छति।। 114 ।।

पादाब्जयो रूपरिसा पतिच्चैव रुरोद च।

इष्ट दृष्टे हि दुःखस्य द्वारमुद्घाट तुं भवेत्।। 115 ।।

पुत्रिसुतं च केनापि हृतं तत् पूर्व वेरिणा।

अतएव महत् दुःख जलघौयाति तात्यहं।। 116 ।।

किं करोमि हताषाहं दुःखितातेन पापिना।

विद्यमाने कथं तातेत्वद् दुःख ममेदृषं।। 117 ।।

नारदो रुक्मिणी वाक्यं श्रुत्वा दुःखं भरालसाः।

शोक संयम्य कष्टेन जगाद रुक्मिणी प्रति।। 118 ।।

उतिष्ठ वत्से त्वं दुःखं शोकं तु मा कृथा वृथा।

गतं मृतं विनष्टं च सुधियः शोधयन्ति चः।। 119 ।।

त्वं मां जानासि, हे पुत्री दुःखं जातं तवैवहि।

पूर्वं कस्यापि नो भूतं एवं मा मानसे कृथा।। 120 ।।

साधारयन्तु सर्वेषां तनूज विरहोत्थितं।

दुःखं भव भृतां नूनं वारितुं के न शक्यते।। 121 ।।

पुराणोनो श्रृतं किं हि विख्यातं क्षिति मंडले।

बाहूनां चापि स×जातं दुःखं विरह सम्भवं।। 122 ।।

यस्य कृष्ण पिता नूनं मातात्वंचिदिता भुवि।

तस्य को मारणेसक्तः स्वल्पायोष्च कथं भवेत्।। 123 ।।

पराभवस्य केनापि ह्वतोदैत्येन वेरिणा।

समेष्यति पुनर्बालो लाभसौभाग्य संयुतः।। 124 ।।

पुराणेषु श्रुताः पूर्वं मया भामंडलादयः।

जातमात्र ह्वतास्ते हि शत्रूणा पूर्व कर्मतः।। 125 ।।

तेपिविद्याधरानां हि याया वृद्धिं गृहे ध्रुवं।

विद्याविभव संयुक्ता ज्ञानविज्ञान भूषितः।। 126 ।।

समायाता निजं गेहं पित्रोष्च मिलिताः पुनः।

तथा तवापि पुत्रो हि तवान्ते तु समेष्यति।। 127 ।।

रुक्मिणी च ततः प्रोचे विनिवार्य शुचं निजं।

श्रृणुनार मे वाक्यं तवात्र कथयामि यत्।। 128 ।।

अथ बहुधालोकितो बालो हया रुढैर्भटोत्तमे।

सरित्सागर पर्यन्तं कथं सम्प्राप्यते मया।। 129 ।।

तथापि तव वाक्यं हि मम कल्याण कारणं।

सर्वतु सफलं भूयात् नान्यथा तव भाषितं।। 130 ।।

त्वमेव तातोसि भगवन् जननी च त्वमेवहि।

त्वत्पादपÁरजसानिः पाप तु कृपास्म्यहं।। 131 ।।

मृग नेत्रा पुनः प्रोचे नारदं प्रतिसादरात्।

यावत् मनोगुण गणान् स्मृति मेति च हे विभो।। 132 ।।

तावत्तमेव पश्यामि पुरस्थं मुनिपुंगवं।

ग्रीष्मे यथा मृगगणो मृगतृष्णां विलोकये।। 133 ।।

एवं वदन्त्य विदधे मुनिनामा मृगेक्षणा।

शोकं विमुंच्य हे वत्से भव्यंतेत्र भविष्यति।। 134 ।।

आनयामि च हे नाथ विलोक्य क्षितिमंडलं।

कार्यं बिना मया भूमि निखिलां भ्रमते ध्रुवं।। 135 ।।

जायते न च मे दोषो भ्रमतापि भुवस्थलं।

तवर्थे च कथं वत्से जायते खेदता मम ।। 136 ।।

गतेमषलंनं नास्ति सार्द्ध द्वीप द्वयेपि च।

सर्वत्रापि विलोक्येहं तव पुत्रं धरातले।। 137 ।।

इत्युक्ते रुक्मिणी प्रोचे न लभ्या सुखतो विभो।

ममपुत्रस्य वार्त्ता हि भाग्यहीनास्मि साम्प्रतं।। 138 ।।

तथापि तव वाक्यं मम मंगलायस्तु हे प्रभो।

तां दीनां नारदो दृष्ट्वा श्रृणु वत्से ममोदितं।। 139 ।।

सत्यं जानीहि में वाक्यं नासत्यं च वदामिहं।

नीतं केनापि रिपुना खलेन पाप चेतसा।। 140 ।।

नानयामि च ते पुत्रं तदा मे वचनं वृथा।

समास्वसहि हे वत्से धारय स्व निजं मनः।। 141 ।।

अतिमुक्तनामासीत् मुनीन्द्रो ज्ञान भूषितः।

कंसस्यै वानुजो लोके ज्ञात विष्वविचेष्टितः।। 142 ।।

हत्वा कर्म महाषत्रुं मुक्तियातो मुनीष्वरः।

नेमिस्त्रिज्ञान युक्तोपि नैव जल्यति सत्यधीः।। 143 ।।

गतास्मि पूर्व विदेहं क्षेत्रं ज्ञातं भुवस्तले।

तत्रास्ति नगरी रम्या प्रसिद्ध पुंडरीकिनी।। 144 ।।

तत्र सीमंधरं नाथं प्रणम्य परया मुदा।

त्रिः परीव्याभि भक्त्या च स्तुत्वा नत्वा विधानतः।। 145 ।।

ज्ञात्वातनूजचरितं दृष्ट्वान्तं जिननायकं।

आस्वासनायत्वं वत्से शीघ्रमागम्यते मया।। 146 ।।

माकृथास्त्वं वृथा शोकमागच्छामि न संषयं।

नारदस्य वचः श्रुत्वा जाता शोकेनवर्ज्जिता।। 147 ।।

संभाष्य नृपतेः पुत्रीं वचसा मधुरेहि।

दूरं पतंग पदवी जगाम नारदो मुनिः।। 148 ।।

ऊर्द्धाननेः परिजनै दृष्यमानो नभस्तले।

तावद् जगाम लोकोर्धेर्न दृष्टोया वदं वरे।। 149 ।।

गच्छन्मार्ग वषात्सोपियायो मेरुगिरिं मुनिं।

तावद्रातिः समाया निजकर्म चकार च।। 150 ।।

जिनबिम्बान्नमष्चक्रे भक्त्याहर्ष भरालसः।

ववंदेचारणमुनीन् गुरुभक्त्यादि पूर्वकं।। 151 ।।

स्थित्वारात्रि मुनिस्तत्र प्रभातकृत कर्मकः।

जिनालया नमस्कृत्य चचाल वेगवत्तरः।। 152 ।।

श्री पुंडरीकनगरं समवाप्य क्षणादषौ।

दृष्ट्वा तु विस्मयं प्राप्तो नो दृष्टं पूर्वभेवहि।। 153 ।।

तीर्थाधिराजस्तत्रैव वर्त्तन्तेषास्वताजिनाः।

षट्खंड भूमिपतयो राजं चक्रधारिणः।। 154 ।।

वर्णनाका पुरस्यैव क्रियते सुन्दरस्यहि।

तस्मिन् दर्षनपूरात्स शरणं समवादिकं।। 155 ।।

श्री सीमंधरनाथस्य वंदितस्य सुरासुरैः।

पूर्वं नृनाकि नागेन्द्र गणैः सख्याविवर्ज्जितेः।। 156 ।।

त्रिलोक्य मन्य दिवस सन्मिलितं भाति भूतले।

दृष्ट्वावतीर्य वियतो नारदोमुनि पुंगवः।। 157 ।।

प्रतिज्ञा युक्त चित्तो सोमुनिब्रह्मांगभूस्तदां।

विवेष परया भक्त्या शरणं समवादिकं।। 158 ।।

दृष्ट्वा तं तीर्थनाथं हिस्तुति कर्त्तुं समुद्यतः।

नारदः प्रमुदापूर्णो जिनेन्द्र दर्षनात् तदा।। 159 ।।

नमस्ते देव देवाय सेव्यायतनमः।

नमोभवकरीन्द्रस्य मृगेन्द्राय नमोनमः।। 160 ।।

भव्यजीवा अखंडस्य भास्कराय च ते नमः।

नमः क्षीणकलंकाय क्षीण मोहयते नमः।। 161 ।।

नमः सुरासुरेन्द्रौधेः वंदिताहि भवद्यायते।

मोहांधकार पटले चन्द्रे तुल्यायते नमः।। 162 ।।

संसार काननस्यैव दाव तुल्यायते नमः।

मोक्षसोख्यफलस्यार्थं गन्तु कामायते नमः।। 163 ।।

नमः सर्वज्ञ नेत्राय स्याद्वाद मतये नमः।

नमस्ते तीर्थनाथाय विमुक्त पद भागिने।। 164 ।।

संसारार्णवयाराय विष्वपालायते नमः।

नमस्तेज्ञानतत्वायानन्तवीर्याय ते नमः।। 165 ।।

शंकराय नमो नित्यं दुरितारि हराय च।

पापकंदविनासाय नमस्ते ज्ञानमूर्त्तय ।। 166 ।।

नमोहिरण्यगर्भाय नमः परम वैष्णवे।

भक्तानां कल्पवृक्षाय जिनेन्द्राय नमोनमः।। 167 ।।

स्तुत्वा नानाविधैर्वाक्येर्जिन्द्रं नारदो मुनिः।

गत्वा मानवके कोष्टेनत्वा चिंता चकार सः।। 168 ।।

शतानि प×चधनुषां अत्र सन्ति नरा ध्रुवं।

अहं तुदसधनुषां प्रमाणो हीन शक्तिकः।। 169 ।।

एतेषां पाद घातेन यास्यामि निधन ध्रुवं।

तिष्टामि च कथं चात्रजिनेन्द्रस्य पदातिके।। 170 ।।

चिन्तयित्वे तु चित्ते सोजिन सिंहासनादऽधः।

प्रविष्यतु स्थितस्तत्रः निर्भया नारदोमुनिः।। 171 ।।

तावत् जिनाग्र भूम्यां तु स्थितष्चक्रधरो हियः।

तेन दृष्ट्वा स्थितं तत्र नारदं चिन्तयन् ह्वदि।। 172 ।।

विस्मयाकुलचित्तो सो षिरोधुन्वन्मुहुर्महुः।

चिन्तयित्वा चिरं चित्ते चक्रेकरतले च तं।। 173 ।।

कोयंवाकस्य जातिर्वा पूर्वदिष्टो न जात चित्।

तावबुसमुत्यंन्नासत्या संदेह नाषिनी।। 174 ।।

विद्यमाने जिने नूनं संदेह क्रियते कथं।

कंकने तु कथस्थेहि दर्पणालोकनं वृथा।। 175 ।।

पÁनाभ जिनं प्रोचे नत्वा विनय पूर्वकं।

ममचित्ते महद्देव संदेहो वर्त्ततधुना।। 176 ।।

देवत्वया निगदितोष्च्यतस्त्रोगतयो ध्रुवं।

तासां मध्येतु कतयागतीयंतु निगद्यतां।। 177।।

तीर्थनाथोपि तत्रोचे श्रृणु भूप महामते।

मनुष्योयं ध्रुवं विद्धिभरते तु स वः।। 178 ।।

श्रीमन्नारद को नाम प्रसिद्धा क्षितिमंडले।

प्राज्ञोति चतुरो नूनं कृष्ण स्नेह भरालसः।। 179 ।।

जिनोदितं वचः श्रुत्वा प्रोचे चक्रधराः तदा।

भरते किं मनुष्याहि सन्ति नाथे दृसाषलु ।। 180 ।।

मयाज्ञातो च कीटोऽयं तव सिंहासनादऽधः।

मरिष्यतीति मत्वा हिं ध्रुवं नीतो जिनेकरे।। 181 ।।

जिनोजगाद हे वत्स कालस्तत्रावसर्प्यकः।

अत परं भविष्यन्ति यादृषाः तादृषाः श्रृणु।। 182 ।।

तत्रेव प्रथमे काले गव्यूति त्रयमात्रकाः।

उन्नतास्तु नराः सर्वजाता पल्य त्रयायुषः।। 183 ।।

द्वितीये तत्र स×जाता गवूतिद्वयमात्रकाः।

कालसर्वे नरानूनं पल्य द्वितय जीवितः।। 184 ।।

एकपल्योपमायुष्णाः क्रोषमे कोन्नतानराः।

भरते पूर्वमेवात्र काले चालि तृतीयके।। 185 ।।

तत्रैव च युगस्यादौ काले चापि चतुर्थके।

सजातवृषभोनाम तीर्थराजो जिनाग्रणी।। 186 ।।

चतुराषीति लक्षाणि पूर्वांना तस्यचायुषः।

उत्सेधष्वापि धुनषां नूनं प×चषतानि च।। 187 ।।

क्रमेणयाति काले च जातास्तीर्थकरावराः।

एकविंषति संख्याता मोक्षमाग्रेपि देषकाः।। 188 ।।

ततोवसर्प्यिणी काले क्षितौ विस्तरिते सति।

जिनाद्वाविंषको जातो हरिवंष विभूषणं।। 189 ।।

तस्यकाले ध्रुवं वत्स प्रमाणं धनुषांदष।

उत्सेधः सर्वलोकानां वर्त्तते तु जिनादितः।। 190 ।।

अयं तु नारदोनाम मुनिः देषव्रतान्वितः।

मामुद्दिष्य समायातो विद्धिचैवं नराधिपः।। 191।।

अतः परम् भविष्यति सप्तार्द्धहस्तत्रयाखिलाः।

काले तु पंचमे नूनं शतवर्षां युषोनरा।। 192 ।।

तत्र काले तु षष्ठेहि हस्तमात्र नराध्रुवं।

वर्ष षोडषकायुष्कास्ते तु काल विषेषतः।। 193 ।।

सर्वं कालविषेषण घटतेचापि वर्द्धते।

इति श्रुत्वा तदा चक्री जिननाथ जगाविति।। 194 ।।

किमर्थं तु समायाताष्चोलंध्यगिरि सागरं।

मनसाप्यिचलं योहि विदेषे चाति दुस्तरो।। 195 ।।

चित्तेकार्यं हि किं धृत्वा कस्य पार्ष्वे समागतः।

तत्सर्वं च कृपां कृत्वा निवेदय विभो मम।। 196 ।।

इति पृष्टो जिनोदेवो रथांगपतिना यदा।

जगौ वाक्यं मनोज्ञं च सभायाः प्रतिवर्द्धनं।। 197 ।।

जम्बूद्वीपस्य भरता समायातो ममांति च।

हरिराजा नरेन्द्रस्य पुत्रान्वेषण हेतवे।। 198 ।।

तस्य स्नेह वषेनासौ वर्त्तते अत्यन्तमाकुलः।

विलोक्य जगतीं सर्वां वार्त्ता ज्ञातुं समागतः।। 199 ।।

चक्रनाथः पुनः प्रोचे कोसौहरिसमाद्वयः।

किं धैर्यं किं बलं तस्य किं गोत्रं क्व निवास भूः।। 200 ।।

क्वास्ति पुत्रोस्य हे नाथ नीतोचाकेन वैरिणा।

समेष्यति कदा काले तत्सर्वं त्वं निरुपय।। 201 ।।

श्रीमान् जिनेष्वरः प्रोचे शृणुभूप महामते।

भव्यपृष्टं त्वया सर्वं श्रोत्राणां पापनाषनं।। 202 ।।

त्रिखण्ड भूपति कृष्णो वर्त्तते द्वारिकाधिषः।

यदूनां कुल शृंगारो हरिवंषषिरोमणिः।। 203 ।।

रुक्मिणीति प्रिया तस्य प्राणेभ्योपि गरीयसी।

एवं श्रुत्वा च वृत्तान्तं जगौ चक्रधरोजिनं।। 204 ।।

वांछनाकल्पवृक्षोसिः त्वं मनोरथ पूरकः।

वांछामि चरितं श्रोतुं हरिराज सुतस्य हि।। 205 ।।

प्रसादं कुरु हे नाथ कृपां कुरु ममोपरि।

आदिमध्यावसानं च कथयस्व विभो ध्रुवं।। 206 ।

इति विज्ञापिते तेन कथितुं प्रारभेतसः।

जिनेन्द्रः शृणु भूपालं चरितं पापनाषनं।। 207 ।।

भूपोस्ति यादव कुले हरिर्नामा विचक्षणः।

तस्यास्ति भामिनीख्याता रुक्मिणीनामिका भुवि।। 208 ।।

तस्यास्तनु भवो जातः जन्मतः षष्ठवासरे।

रात्रोमात्रासमं सुप्तोहृतोवैपूर्व वैरिणा।। 209 ।।

हृत्वा दैत्येन दुष्टेन गिरौ तक्षकनामनि।

षिलयापि हितष्चक्रे स्मृत्वा वैरं पुरातनं।। 210।

तावत्समागतस्तत्र कालसंवर भूपतिः।

खेचराणामधीषोमौ युक्तः कांचन मालया।। 211 ।।

बालं विलोक्य तत्रस्थं जग्राहः पृथिवीपतिः।

पुरं नीत्वा निजं सोपि ववृधे प्रमुदान्वितः।। 212 ।।

दिनेदिनथववृद्धे कलायुक्तः शषिर्यथा।

प्रद्युम्न इत्याभिधिया प्रथितः क्षितिमंडले।। 213 ।।

लाभौः षोडषभिर्युक्तो वर्षैः षोडषभिस्तथा।

समेष्यति गृहे नूनं विद्याद्वय समन्वितः।। 214 ।।

मिलिष्यति ध्रुवं पित्रोः सर्वलक्षण संयुतः।

तस्मिन् समागते नूनं भविष्यति शुभावहाः।। 215 ।।

तेतुत्वां कथयामीति शृणु भूपमहोदितं।

रुक्मिण्या स्तनयो नूनं पयः श्रावं भविष्यति।। 216 ।।

भविष्यति वने सर्वं शुभ शंसीकरं परं।

उन्निद्रपंकजवनं शुष्काचागृहदीर्घिका।। 217 ।।

स्थितोगेहाग्रतो नूनमशोकः शुष्कतां गतः।

मूलात्सोपि विंगुच्छैष्च पूरितो च भविष्यति।। 218 ।।

वनमध्येतु वृक्षाये पूरिता कुसुमैर्दलै।

भविष्यति च मधुपा गन्धलुब्धारवाकुलाः।। 219 ।।

अन्येपितरवः सर्वेविलंष्य समथंनिजं।

सर्वर्न्तुभिः कृतावासाः भविष्यन्ति गृहे तदा।। 220 ।।

कोकिलानां निनादो हि भविष्यति मनोहराः।

नर्त्तनंवर्हि वृंदानां वद्धतांडारवं यथा। 221 ।।

चूताष्चपुष्पिताः सर्वे फलिताः केचिदत्रहि।

भविष्यति वने सर्वे सर्वेषां प्रमुदावहं।। 222 ।।

मूकाविचित्र वचना कुब्जाष्च सरलास्तथा।

काणाष्चक्षुयुता सर्वे विनेत्रा सर्वे मगनेत्रकाः।। 223।।

कंठहीना सुकंठास्यः कुरुपारूयसंयुताः।

लक्षणैष्चापि ये हीनास्तेपिस्फर्ल्लक्षणैर्युता।। 224 ।।

विवर्णावर्ण संयुक्ताः शृण्वंतिवधिरास्तथा।

पुलकितास्व शरीरेस्याद् रुक्मिण्याष्च भविष्यति।। 225 ।।

एतत्सर्वं तदाराजन् भविष्यति तदागमे।

एतैष्च सूचकैः कृत्वा ज्ञातव्यः स समागतः।। 226 ।।

योयंकरतले भूप स्थितस्तेति मनोहरे।

मान्योमुनिजगत्पाहि प्रसिद्धोनारदाद्वयः।। 227 ।।

निर्वाणमार्ग कुषलोनवमो नारदोद्वयं।

देषव्रती समायातो हिताय कृष्ण भूपते।। 228 ।।

एतत् सर्वं समासेन त्वया पृष्टं ममौदितं।

ततोजिनवरं नत्वा जगौ चक्रधरो वचः।। 229 ।।

Ük`णुनाथ कृपाधार कृपां कृत्वा ममौपरि।

सर्वं त्वं कृष्णपुत्रस्य वृत्तांत में निवेदय।। 230 ।।

वैरस्य कारणं सर्वं जातं दैत्यवरेण यत्।

जन्मान्तराणितस्यैव पुण्यापुण्यं तथैव च।। 231 ।।

इति पृष्टो जिनाधीषः तदाचक्रधरेण च।

जगादवचनं रम्यं सप्तभंग समन्वितं।। 232 ।।

जम्बूद्वीपे भुविख्याते क्षेत्रे भरतनामनि।

मगधाभिधेस द्वेशे विख्यात्तजनसंकुले।। 233 ।।

तत्रदेषेस्ति। विख्यातं शालिग्रामाद्वयंपुरं।

तत्रास्ति सोम च दनसो मदत्ताभिधोद्विजः।। 234 ।।

निजजाति कुलस्यापि गर्व पूरित मानसः।

अग्निलेति प्रसिद्ध हि तस्यास्तिदपिताचरा।। 235 ।।

तयोःपुत्रौ च विख्यातौ वेद शास्त्रार्थपारगौ।

नवयौवन सम्पन्नौ धनधान्यवलान्वितौ।। 236 ।।

स्वजाति कुलगर्वेण मन्यमानो जगत् त्रयं।

जीर्णतृणसमं सर्वं विद्या विभवसंयुतौ।। 237 ।।

एकोत्रचाग्नि भूनीति द्वितीयो वायु भूतिकः।

मिथ्यात्वस्य मतेलग्नै जिनधर्म परान्मुखौ।। 238 ।।

स्वमते पातिता शेषं बाल लोकौ विचक्षणौ।

मिथ्यापदार्थ घटना दुष्टचित्तौ स्वभावतः।। 239 ।।

हर्ष पूरित चित्तौ तौ स्मृति शास्त्रार्थ पारगौ।

वासुपूज्य जिनेन्द्रस्य तीर्थं वहति पावने।। 240 ।।

एवं विधौ च तौ तत्र स्थितौदर्प्य समन्वितौ।

यावत्त वत् च संजातं वरमन्यत्कथान्तरम्।। 241 ।।

श्रीनंदिवर्द्धनोनाम मुनींद्रोमारभंजकः।

सर्वषास्त्रार्थ कुषलो ज्ञाननेत्रो गम्भीर वाक्।। 242 ।।

नाना लब्धियुतैः षिष्यैर्योगत्रि तयधारिभिः।

युक्तः समागतो योगी पुरवाह्येवनेचरे।। 243 ।।

आपृच्छविधिपूर्वं सोवनस्यैवन्तुरक्षकं।

योगीयथोचितं कर्मकृत्वा सर्व जिनोदितं।। 244 ।।

तत्राषोकतरोर्मूले विषुद्धं हि षिलातलं।

विविक्तं जन्तुरहितमलंचक्रे मुनिस्तदा।। 245 ।।

पठनं पाठनं कर्म कुर्वन् यावदसौ स्थितः।

तावत् तत्र समायातो वनपालो विलोकयन्।। 246 ।।

आकस्मिकां समालोक्य वनेषोभांनवीनकां।

तस्य प्रभाव जनितां मुनिनाथस्य सुन्दरां।। 247 ।।

विस्मितो वनपालोसौ नमष्चक्रे मुनीष्वरं।

भक्त्याप्रदक्षिणं कृत्वा गुरु भक्ति समन्वितः।। 248 ।।

एवं विधोथयोगीन्द्रः सर्वेलक्षण संयुतः।

समुद्रवच्चगम्भीरो धीरोसौ गिरिराजवत्।। 249 ।।

निर्मूलिताद्य वृक्षोवैमदाष्टक गजेहरिः।

परीषह महाराति जयनैक महाभटः।। 250 ।।

सर्वसंगविनिर्मुक्तो न मुक्त गुण सम्पदा।

सन्मार्ग दर्षनरतो ज्ञानत्रय विभूषितः।। 251 ।।

ज्ञात्वागतं यतिपतिं सर्वोपि नगरी जनः।

जगाम वन्दितं भक्त्या जिनधर्म परायणः।। 252 ।।

केचिद्भक्त्या मुनीन्द्राणां जिनशासन भाविताः।

लज्जाया केचिदायाताः परैराकारिताः परे।। 253 ।।

माध्यस्थ भावमालं व्यपरे केचित्समागताः।

एकचित्तं तु सर्वेषां कदाचित् जायतेन हि।। 254 ।।

गच्छन्तं नगरी लोकं वरवेषधरं तदा।

समुत्सव समायुक्तं समयेन विना यदा।। 255 ।।

प्रप्रछतुर्द्विज सुतौकंचिच्चश्रावकं जनं।

क्वप्रयात्पद्यलोकोयं वरवेषधरोवने।। 256 ।।

ततो वाक्यं समाकर्ण्य जगाद श्रावकोत्तमः।

आकाषात्पतितौ वाक्यं याभ्यां तु ज्ञायतेनहि।। 257 ।।

सर्वषास्त्र समुद्रस्य पारेयांत मुनीष्वरः।

साधुवृत्ति समायुक्तं सेव्यं नर सुरैरपिः।। 258 ।।

मुनीन्द्रं तं नमस्कर्त्तुं प्रपाति सकलो जनः।

श्रावकस्य वचः श्रुत्वा प्रोचतस्तौ द्विजौक्षदा।। 259 ।।

रे रे मूढा ग्रहीभूतः किं वाजल्यसि निंदितं।

दिग्वास संजगान्निंद्यं मललि प्रषरीरकं।। 260 ।।

मूर्खंवेद विहीनं च तं साधुं प्रोच्यते कथं।

द्विजानां चोत्तमकुले जातो वेदार्थ वित्सुधाः।। 261 ।।

तारणेतरणेचापि समर्थ श्रुतये वहि।

साधुं मुनिं तमे चात्र प्रोच्यते नापरं जनं।। 262 ।।

तस्मात् क्षितितले नूनं पूजनीयावयंषठ।

मूढोलोकः कथं याति वंदितुं दिग्वाससं।। 263 ।।

मुनि भक्त्याह्वत चित्तोसौ जगाद श्रावकाग्रणाः।

रे रे मूढौ महादुष्टो धर्मकर्म क्रियाभितौ।। 264 ।।

गृह धर्मरतौ निंद्यौकान्ता प्रेम भरालसौ।

भवतो साधुता नूनं युज्यते हिकथंवरा।। 265 ।।

यत्पादपÁरजाये पवित्रांगिकानरः।

भुक्त्वासुखं षिवपदंयांति भव्या न संषयं।। 266 ।।

ते साधवो जगत् पूजाः सर्वसत्वहिता वहाः।

लोकापवादेयेमूकास्त्यक्तमन्मथ संकथा।। 267 ।।

तरितुं तारितुं नूनं ते एव जगतां क्षमाः।

विषया सर्वषंषक्त्या नान्ये विप्रा भवादृषाः।। 268 ।।

साधून विनिद्ययुवयोः शतधारसना कथं।

न जातात्रद्विज सुतौचित्रमेतन्महन्मम।। 269 ।।

एवं श्राद्धवचः श्रुत्वा क्रोधाषक्तौद्विजौ तदा।

शेष संरक्तवदनौ प्रोचतुर्वाक्यमूर्ज्जितं।। 270 ।।

अनेन किमुमूर्खेन विवादः क्रियते वृथा।

दिग्यटैष्च समंगत्वा करिष्यामो न संषयं।। 271 ।।

इत्युक्त्वा प्रेषयित्वां तं श्रावकं तु गृहे गतौ।

पितृभ्यां पादयोः नत्वा प्रोचतुस्तौ दुराषयो।। 272 ।।

तातात्रये समायाता मुनयो दिग्यटाः शठाः।

तैरेवसमं विवादं कर्त्तुं यावो वने ध्रुवं।। 273 ।।

द्वितीण्यहानियादिते निवसन्ति वनेषठाः।

शत्रवोवेद मार्गस्य जिनमार्ग प्रकाषकाः।। 274 ।।

तदा ते सकलं लोंक वेदषास्त्र पराङ्मुखं।

निजषास्त्रस्य दृष्टां तैरुन्मूलयन्ति मूलतः।। 275 ।।

वादेविजित्य तान् सर्वान् निजषास्त्र वलेन हि।

तया कुर्वोयथा ते वैनवसन्ति क्षणं वने।। 276 ।।

पितृभ्यां वारितौ तौ हि न गन्तव्यं वने सुतौ।

तेत्यन्तचतुरानाना देष हिंड़न पंडिताः।। 277 ।।

दिग्पटैष्च विवादं हि कर्त्तुं केनात्र शक्यते।

सर्वषास्त्रार्थ कुषलाः प्रत्यहं पठनेरताः।। 278 ।।

तौपित्रौ वचनं श्रुत्वा गर्व पूरित मानसौ।

प्रोचतुर्गर्व संयुक्तं मूढोवाक्यं तदोद्वतं।। 279 ।।

कोस्त्यावयोर्विजेतायो विद्यावादेत्र भूतले।

ईदृषं वचनं दीनं युवाभ्यां प्रोच्यते कथं।। 280 ।।

अधुनैव वनं गत्वा जेष्यामिस्तात् न संषयं।

इत्युक्त्वा निर्गतौ तौ हि पितृभ्यां वारितावपि।। 281 ।।

जग्मतुस्तौतमुद्देषं यत्रासौ मुनिसत्तमः।

उत्श्रृंखलैर्वहुजनै परीतौ परितस्तदा।। 282 ।।

तस्यान्तिकं जगमिषूजेतुं तं नन्दिवर्द्धनं।

मागैतावत् च जल्पंतौ किंचिद्गर्व समन्वितौ।। 283 ।।

तत्र मार्गे नगस्याधः स्थितेन मुनिना च तौ।

साधुनासात्यकिं नाम्ना संपृष्टौ ता वुभावपि।। 284 ।।

अभिमानवताभ्यां च भवद्भ्यां गम्यते क्व च।

ततस्तावूचतुः स्वीयंकारणं तत्पुरोमुदा।। 285 ।।

नन्दिवर्द्धननामायो वर्त्तते यतिनायकाः।

यावोजेतुं च तं साधुं विद्यावादे स्फुटं मुने।। 286 ।।

श्रीनन्दिवर्द्धनसारं दयारस समन्वितं।

सेवितं यतिहं सौधैः क्रियाकाष्टादि निर्मलं।। 287 ।।

तत्सरः कलुषी कर्त्तुं भवन्तौ महिषाविव।

अत्यन्तगर्व सम्पूर्णमानसौ चालितौ कथं।। 288 ।।

अत्रागत्य मया सार्द्धविवादः संविधीयते।

तूर्णं पूर्णं करिष्यामि युवयोष्च मनोरथं।। 289 ।।

ताभ्यां तद्धचनं श्रुत्वा वादहेतु करं परं।

तावुभौ तस्य निकटे समायातौ महोद्धतौ।। 290 ।।

ततस्तावूचतुस्त्वं हि वृथागाल्यो ददासि किं।

रे रे लज्जाविनिर्मुक्त वेदमार्ग पराङ्मुखः।। 291 ।।

यदि ज्ञातासि गुणवान् विद्यावानसिः हे यते।

तदा सज्जीभवावाभ्यां सार्द्धं कर्न्तु विवादकं।। 292 ।।

पुनः विप्रोजगावेवं यतिं क्रोध भरेण तौ।

किं वा निगदिते मूद वचोभिगर्व संयुतौः।। 293 ।।

आवां वादे जितौमूढत्वत् त्वया विदुषां पुरः।

तदा यथा पुरा प्रोक्तौ तथैवावां न संषय।। 294 ।।

अन्यष्चजल्प समये चात्रवादे जितस्य हि।

निग्रहः कस्तुवर्त्तव्यो निष्चयः प्रोच्यतां त्वया।। 295 ।।

सभाजन समक्ष हि विमृष्य च मुने वद।

विवादोमिष्फलं याति विदुषां तु पुणं विना।। 296 ।।

मुनिनाथो जगावेवं यद्युवां रोचते द्विजौ।

विदुषां तु सभामध्ये सएव क्रियतां पुणः।। 297 ।।

प्रोचतुस्तौ द्विजौ वाक्यं मुनीन्द्रं प्रतिचोत्कटं।

जेतावयोर्यदि भवन् विवादं विदुषां पुराः।। 298 ।।

नियतं ते व्रजावो षिष्यतां शठते ध्रुवं।

यदि त्वं निर्जितो नूनमावाभ्यां वादसत्यनि।। 299 ।।

निर्वास्योसि विपयतः सनिकारपुरस्मरं।

एवं विधः पनौनूनमावाभ्यां क्रियते स्फुटं ।। 300 ।।

मुनिनापि तदा प्रोक्तं युवयो रुचितं हियत्।

प्रमाणं च तदेवात्र ममैव तु मतं हृदि।। 301 ।।

एवं विधाय विदुषां प्रतिज्ञां पुरतस्तदा।

स्थितेषु तेषु तत्रैवसाभ्यस्वयं परस्परं।। 302 ।।

श्रुत्वा विवादमेषां च जनौघः कौतुकान्वितः।

तेदेषमाप्य विरलं चकार निवडं तदा।। 303 ।।

एवं तत्र स्थिते तस्मिन् सभायां सकला जना।

विचार दक्षौ तत्रैव स्थितैः सत्प्राष्णिकैः पुनः।। 304 ।।

श्रीसत्यकि मुनिः प्रोचे वचनं विदुषां हितं।

पृछतांवट् किंचित् पूर्वं मां भक्तिपूर्वकं।। 305 ।।

नावगतं यदा किंचित् शास्त्रं सन्दैह कारकं।

पृष्टव्यौवैनियमे न भवद्भ्यां कथयाम्यहं।। 306 ।।

इतिश्रुत्वा मुनेर्वाक्यं दर्प्यादेतद्वदुद्वयं।

जगाद वचनं दुष्टं गर्वात् स्मित पुरस्सरं ।। 307 ।।

आवां प्रपूज्य मूढत्वं परिपृछय सत्वरं।

कुत्रापि वस्तु विषये संदेहस्तवचेतसि।। 308 ।।

अवष्यं कथया वोचै तवैव च शठात्मकं।

नत्वात्वं पदयोर्द्वद्वमावाभ्यां परिपृछय।। 309।।

इत्युक्तेथ मुनिं प्रोचे सत्यं पृछामिमांप्रतं।

एवं भवत्वथकुतो युवां चात्र समागतौ।। 310 ।।

इतिपृष्टे ततस्ताभ्यां हसित्वा तत्र जल्पितं।

ग्रामात्समागतो मूढ त्वया ज्ञातं न साम्प्रतं।। 311 ।।

एतावदपिनोज्ञातं त्वया ज्ञातं न किंचन।

त्वं न वेत्सिपरं मूढ पुष्पदन्ता चापि स्फुटं।। 312 ।।

मुनिनाथस्ततः प्रोचे जानाम्येवं मुनिष्चितं।

ग्रामात्समागतौ चां हि सोमषर्मसुतौ ध्रुवं।। 313।।

अग्नित्वायाः सुतौ विप्रौ वेदगर्व समन्वितौ।

नाम्नाग्निभूतिरितरोवायु भूति सुतौ ध्रुवं।। 314 ।।

इतिज्ञातं मया सर्वमागतौ वा द्विजौत्तमौ।

पृष्टमेतन्मया नूनं कुतः परभवार्द्दितः।। 315 ।।

इत्थं निषम्य वचनं विप्रोतौ समवोचतं।

विमुकोपिपूर्वभव विन्मजेष्णिह विद्यते।। 316 ।।

शंकया वर्ज्जितो भूत्वा पृष्छस्यैवं सभान्तरे।

तथा विधः शठोषित्वमावाभ्यां कथितो यथा।। 317 ।।

मुनीन्द्रोथ तदा प्रोचे भवद्भ्यां ज्ञायतेन हि।

यद्यात्मसंभवं विप्रौ विवादः क्रियते कथं।। 318 ।।

प्रोचतुर्वाडवावेमावाभ्या ज्ञायतेन हि।

त्वया चेद् ज्ञायते मूढत्वमप्यादिष वेगतः।। 319 ।।

श्रृणुतां वाडवौ वाक्यं मदीयं सत्य संयुतं।

सभायास्तु समक्षं हि भवतोत्र भवान्तरं।। 320 ।।

जगावेव ततो वाक्यं को पात्तद्वादवद्वयं।

आवां भवान्तरं ब्रूहि ज्ञातं ते शठदिग्यट।। 321।।

मुनिराजवचः प्राह श्रृण्वन्तु हे सभाजनाः।

एतयोष्चभवं ब्रूमि जगत्प्रत्ययकारकं।। 322 ।।

अत्रैव षालिग्रामे भूत् प्रसिद्धोवाडवोधनी।

क्षेत्राधिपस्तुप्रवर नाम तु कृषि कारकः।। 323।।

तस्य क्षेत्र समीपेस्ति प्रग्रोधोनाम पादपः।

श्रृगालं युगलं तस्य जातौ च विधियोगतः।। 324 ।।

वृद्धिं क्रमेण तदगात्कुण पाषनयोगतः।

कालः कियानपि गतः सुखेनास्य स्थितस्य हि।। 325 ।।

प्रवरोथगतः क्षेत्र मे कदाजल दाग मे।

हलोपकरणैयुक्तः सर्वेकर्मकरैस्तथा।। 326 ।।

दूराद्ददर्ष नभसि मेघौघः प्रवरेणतुः।

गर्ज्जन् गम्भीरशब्देन कुर्वंष्चापं नभस्तले।। 327 ।।

संतर्ज्जन्निव ग्रीष्मारि विष्वसंताप कारकं।

सीत्कार वायुवेगेन परिकंपित भूतलेः।। 328 ।।

विमु×चति जलं तत्र वारि वाहे निरन्तरं।

प्रवरोदुःख सम्पूर्णो जातो सौ विकलेन्द्रियः।। 329 ।।

सर्वं हलोपकरणं मुक्त्कातत्राति वेगतः।

कम्पमान शरीरो सौ जगाम भवनं द्विजः।। 330 ।।

वृष्टिर्वभूवलि वडासप्तैव हि दिनानि च ।

जातां तु क्षुधया व्याप्ता दुःखिता जीव राषयः।। 331।।

गोमाय युगलं तत् च जातं तीव्र क्षुधाकुलं।

वृष्टिर्वभूव विरला सम्प्राप्तेचाष्टमे दिने।। 332 ।।

निःसृज्यगुल्म गहना श्रृगाल युगलं तदा।

क्षेत्रे ददर्ष सरसामिह रज्जु मनोहरां।। 333 ।।

तत् तां जघाससहसा क्षुधाया परिपूरितं।

पीडां ततोपि महतीं प्राप्तौ तौ शूल सम्भवां।। 334।।

प्रक्षिप्यक्षुचरणान् जातौ तौ निधनं तदा।

सोमषर्म गृहे नूनं उत्पन्नौ वाडवौ युवां।। 335।।

श्रृगालौ दैवयोगेन जातौ द्विज सुताविह।

न क्वापि चोत्तमाजातिर्न क्वापि चाधमानृणां।। 336 ।।

एतदेव महाष्चर्यं स्वयं भुक्तं न विंदति।

तथापि कुरुते गर्वं प्राणीजाति मदाविला।। 337।।

अषुचेर्भक्षणा देव यौ पुरा निधनं गतौ।

तावेवचाधुना गर्वं कुरुतो विदुषां पुरः।। 338।।

निर्वेदकारणं यत् च तत् च किं विस्मृतं द्विजो।

सर्वत्रभुंजते प्राणी पुण्यापुण्यतरो फलं।। 339 ।।

सधर्म वर्ज्जितो जन्तुहीनो जातिकुलेन च।

रूपसौभाग्य रहितो धनधान्य विवर्ज्जितः।। 340 ।।

विद्याहीनो यषोहीनो बललाभ गुणोझितः।

सौरभ्यसुखलेषादि विभागीण कदा भवेत्। 341 ।।

पटुतांगे कुले जन्म विद्यावान् धनवान् सदा।

भोगभाग् गुण संयुक्तो देवपूजन तत्परः।। 342 ।।

दयालः सर्वजीवेषु सर्वसत्व हितावहः।

अक्रोधीस्यादमाची च सधर्मात् जायते नरः।। 343 ।।

धर्माधर्म फलं सम्यक् ज्ञात्वा तत्व विदुः सदा।

धर्ममतिः सदा कार्या पापं दूरेण वर्ज्जयेत्।। 344 ।।

यदिपूर्व भवोप्युक्तो नायाति स्मृति गोचरं।

सर्वलोक समक्षं वा प्रत्ययं तु करोम्यहं।। 345 ।।

विप्रोमया निगदितो यो पूर्वं प्रवराभिधः।

दृष्टेरनंतरं सोपिगतः क्षेत्रस्य भूमिकां।। 346 ।।

सर्वंहलोपकरणं ददर्ष पतितं भुवि।

इतस्ततः प्रचंडेन क्षिप्तवा तेन सर्वतः।। 347 ।।

अर्द्धभुक्त्वां च रज्जुं वै दृष्टं तेन द्विजेनतु।

अग्रेगोमायु युगलं पतितं गत जीवितं।। 348 ।।

श्रृगाल युगलं दृष्ट्वा मृत्वा तु पतितं भुवि।

ततोनिघृण चित्तोसौ क्रोधेनैव प्रपूरितः।। 349 ।।

तयार्भछडिके कृत्वा नीत्वा गेहं निजं ततः।

स्थापिते चैव तत्रैव वध्वा तु मेडकोपरि।। 350 ।।

अद्यापिते हि वर्त्तते तत्रैव स्थित तद्वयं।

चास्यमूकस्य भवने गत्वा पश्यतु कौतुकं।। 351 ।।

योसौ प्रवर नामासीद्भुक्तो विप्रकुलस्य च।

कृत्वा नाना विधं यज्ञ जप होम परायणा।। 352 ।।

आयुरंतेथसो मृत्वा मोहपाष वषीकृतः।

निजपुत्रस्य पुत्रो भूद्वध्वोदर समुद्भवः।। 353 ।।

बालमात्रोपि दृष्ट्वासौ गेहं भूमिनिजां तदा।

स्मृत्वा पुरातन भवं विषसादपरं हृदि।। 354 ।।

चिन्तां कर्त्तुं तदालग्नः कि करोमि हताषकः।

मोहपाषवषेनाहं प्राप्ताः पुत्रस्य पुत्रतां।। 355 ।।

निजपुत्रस्य तातं हि वधुषाया मातरं तथा।

एतद्वयं कथं ब्रूमि पापाहं पाप संभवः।। 356 ।।

वक्तुमेवं तु मे लज्जा वर्त्तते हृदि साम्प्रतं।

जातः कर्त्त विषेषेण किं करोमि वदामि किं।। 357 ।।

एवं विचिन्त्यमानस्य बुद्धिरेका समुद्‌गता।

इत्थं करोमि सत्यचैलज्जातो भविष्यति।। 358 ।।

मूकीवभूव मनसा संचित्येति द्विजोत्तमः।

कालेन यौवनं प्रायमूकोसौ नैव जल्पति।। 359 ।।

विवादं चावयोः श्रुत्वा लोकैः सह समागतः।

सभायां संस्थितष्चात्र त्वयं पश्यति कौतुकं।। 360 ।।

समक्षं सर्वलोकानां सोपि मूकोद्विजस्तदा।

आकारितोथ मुनिना दयापूरित चेतसा।। 361 ।।

प्रवरस्य चरोमित्वामत्रागच्छ द्विजोत्तम।

मुंच मौनं वृथानीतं ज्ञान तया त्वया।। 362 ।।

समासास्य वधूस्त्वं वचनैरमृतोपमैः।

मातृत्वमेति तनयापितावै पुत्रतां व्रजेत्।। 363 ।।

नाथोपि कर्म करतामि नतामेति सोप्यहो।

स्नुषा पुत्री भवेत् नूनं पुत्रीमाता तथा पुनः।। 364 ।।

धनवान निर्द्धनोलोके निर्द्धनोधनवांस्तथा।

विश्वानु भवेत् देवो देवोपिष्वानु नतां व्रजेत्।। 365 ।।

एवं संसार वैचित्रयं ज्ञात्वा कर्म वषानुगं।

न हर्षो न विषादोपि कर्त्तव्यो धीमता पुनः।। 366 ।।

धर्ममेकं तु कर्त्तव्यं सर्वत्र सुखकारणं।

भवभीते विधाय कुरु त्वं साम्प्रतं वृषं।। 367 ।।

येनान्य जन्मनि युतर्नपष्यसि भघौंयावहं।

दुःखं पापफलोद्भूतं बन्धुव्यत्ययमानसं ।। कारकं।। 368 ।।

इत्थंमुनेर्वचः श्रुत्वाभि निंघै च पुनः पुनः।

वाष्पां वुविं वनिकर चक्षुर्भ्यां पातयत् तदा।। 369 ।।

मूकोवदत् मुनिं नत्वा कृत्वा च विनयं महत्।

करौद्वौमुकुली कृत्य भूमि विन्यस्तमस्तकः।। 370 ।।

कामकुंजर सिंहाभ शृणु साधु षिरोमणि।

भवनिस्तारिणी दीक्षां सत्वरं देहि मे प्रभो।। 371 ।।

संसारेण नमेकार्यं न च बन्धुजनेन च।

कलत्र पुत्र मित्रेष्च न धान्यैर्नोधनादिभिः।। 372 ।।

संसार सुरवतो नूनं निर्विन्नोस्मि विभोरहं।

दीक्षां यछकृपां कृत्वा संसारावास वारिणीं।। 373 ।।

दीक्षोद्यतं समालोक्य मुनीन्द्रोपिवभानतं।

पूर्वं निज कुटम्बस्य मिलत्व वचनात् मम।। 374।।

दृष्ट्वा समागतं तत्र कुटंबेतंतनिजं तदा।

कथं प्रतारिता वत्स मिलितोमुनिवाक्येन गुरोर्वाक्यं न लंघयेत्।। 375 ।।

मिलितो जल्पिते तस्मिन् कुटुम्बं रुदितं तदा।

कथं प्रतारिता वत्स नीत्वा मौनं त्वयात् विदं।। 376 ।।

मूको जगाद तत्रैवक्षतद्यं सज्जनैः मम।

पुरादुनिष्टितं यच्चप्रमादाद्विहितं ननु।। 377 ।।

दीक्षां गृहामि जैनेन्दी संसारारि विनाषिनी।

संसारे व्यत्पयो नूनं सर्वेषां प्राणधारिणां।। 378 ।।

भुक्ते प्राणी निजं कर्मपुरायत् च विनिर्मितं।

एकाकी जायते जीवो मृयते च तथा विधा।। 379 ।।

एवं ज्ञात्वा न कर्त्तव्यो मोह संसार वर्द्धकः।

अतएव गृहीष्यामि दीक्षां दिगम्बरीं ध्रुवं।। 380 ।।

क्षमयित्वा कुटुम्बं स्वं नत्वा पादौ गुरोः पुनः।

व्रजतं ग्राहसोत्कष्टं गुरु वाक्यानुगः सुधीः।। 381।

नीत दीक्षांच तं दृष्ट्वा सर्वेलोकाः सभासदः।

सम्यक्त्व मापुर परेगृहं धर्मं पुरे पुनः।। 382 ।।

महाव्रतनि केचित् शीलं केचित् देष व्रतानिवै।

जिन पूजादिक केचित् शीलं केचित् प्रयेदिरो।। 383 ।।

त्थं धर्मरतो जावल्लोकोपि सकलोपि च।

तावद् सज्जनैः नत्वा कौतुकाविष्टमानसैः ।। 384 ।।

भस्त्रिका युगलं विप्रगेहानीय सत्वरं ।

दर्षितं सर्वलोकानां ज्ञान प्रत्यय कारकं।। 385 ।।

आनीतेभस्त्रिके दृष्ट्वा जातौ तव वर्ज्जितो।

विलक्षौ दीन वदनो गत गर्वोकलौष्भितौ।। 386 ।।

धिकारमाप्य लोकेभ्यो वनतो गृहमापतुः।

दृष्ट्वा सुतौ समाजातौ पितरौ क्रोध पूरितौ।। 387 ।।

सकोपं प्रोचतुस्त्वैवं रे रे पुत्र पापौ कुपुत्रकौ।

हारयित्वा समासायातौ मुखमार्दतामिह।। 388 ।।

अस्माभिर्द्रविनं दृष्ट्वा दत्वा बहु शास्त्रं तु पाठितौ।

हारापितौ तथाप्यैवं दिग्पटेन वने युवां।। 389 ।।

भवतां तु निमित्तेहि यत् दत्तं द्रविणं मया।

तत्सर्वं विफलं जातं रे रे मूढौ कुलक्षणौ।। 390 ।।

मयातु वारितौ पूर्वं गच्छन्तौ तु वने युवां।

गत्वात्रहायित्वावे समायातौ कथं पुरे।। 391 ।।

शास्त्रेणापि च नो शक्तौ जेतुं तान् मुनि नायकान्।

शस्त्रेणापि कथं मूढौ भवद्भयां न जितौ वृथा।। 392 ।।

पित्रोतद्वचन श्रुत्वा मिथहक्षौद्विजात्मजौ।

चिन्तां कर्त्तुं तदा लग्नौ दीनौदुःख भरालसौ।। 393 ।।

आवयोर्जन्म तं पूर्वं पित्रास्तदपि साम्प्रतं।

अतोरात्रौ वने गत्वा निहन्वस्तान् दिगम्बरान्।। 394 ।।

गत्वा गुरु समीपेथ नत्वात् पादपंकजं।

जगाद विनयं विभ्र श्रृणुनाथ वचोमम।। 395 ।।

मयापि विप्रपुत्राभ्यां विवादोद्य कृतो विभो।

कृपाकृत्वा ममाख्यामिहि प्रायष्चित्तं यथोचित।। 396 ।।

गुरुणापि षिरोधूत्वा प्रोक्तं तं मुनि पुंगवं।

विनृपकं कृतं वत्स मुनीनां नाष कारणं।। 397 ।।

अद्यरात्रौ समागत्य विप्र पुत्रौ दुरासयौ।

सर्वेषां मुनीन्द्राणां च मरणं तं करिष्यतः।। 398 ।।

नष्टमान तया जातौ विलक्षौ पापमानसौ।

निर्भिस्थितौतुपितृभ्यां हन्तुकामो खलौषठौ।। 399 ।।

एवं गुरौर्वचा श्रुत्वा जातः कंपित मानसः।

मुनीनां मरणादेवं तस्य दुःखं नचापरं।। 400 ।।

जगाम मुनि मुख्यं सश्रृणुनाथ कृपानिधे।

मुनिसंधस्य रक्षार्थं मुषीयं वद मे विभो।। 401।।

ममापराध दोषेण मुनीनां मरणं यदि।

तदा किं जीवितव्येन मरणेनाथाऽधोगतीं।। 402 ।।

गुरुणापि तदा प्रोक्तं उपायं श्रृणु वत्सकः।

यत्र देषे कृतोवादः तत्र गच्छ निषागमे।। 403 ।।

क्षेत्रपालसमीपेहि याचयित्वा पदद्वयं।

सन्यासं सावधिनीत्वा तिष्टत्वं ध्यान संयुतः।। 404 ।।

तत्रागत्य च तौ विप्रौ दृष्ट्वा त्वां कृतदुर्न्नयं।

स्थास्यतः कृतक्रोधौहि हन्तु कामोतवैव हि।। 405 ।।

तदातु मुनिसंघस्य रक्षा भवति निष्चिता।

इथं गुरोर्वच श्रुत्वा जातो सौहर्ष पूरितः।। 406 ।।

नमस्कृत्य गुरोपादौक्षम इत्वापुनः पुनः।

समस्तं मुनि संघेन क्षमायामास भक्तितः।। 407 ।।

निषल्यं क्षमितं कृत्वा प्रोचे सत्य कि सन्मुनिः।

प्रातर्चोवे मिलिष्यामिक्षे नागम्यते यदि।। 408 ।।

इत्युक्त्वा निर्गतो योगी तत्रयातः क्षणादसौ।

यत्रस्थाने कृतो वादः सन्ध्यायावसरे तदा।। 409 ।।

नित्यकर्म निजं कृत्वा याचयित्वा पद द्वयं।

सन्यासं साविधिं नीत्वा स्थितो ध्यानेन सन्मुनिः।। 410 ।।

यावत् तत्र स्थितो योगी ध्यान युक्तो समीदमी।

यावनिषासमायाति तावद्गहं स्थितौ च तौ।। 411 ।।

निशायां निर्गतो गेहाशस्त्र हस्तौ तु भ्रातरौ।

विधयित्वा पटीकद्यां वामागेचाषि धेनुकां।। 412 ।।

वामकर्णो परिष्टात् च कृत्वा यूटकबन्धकं।

पुरातौ निर्गतो वाह्ये क्रोधारुण नीरीक्षणौ।। 413 ।।

जग्म तु स्तुवनं भ्रूवं यत्रासौ मुनि पुंगवः।

तावत् तत्र समायातौ द्विजौतौ दुष्टमानसौ।। 414 ।।

तयोस्तत्र गता दृष्टिर्यत्रासौ मुनि पुंगवः।

तत्रस्थं तं मुनि दृष्ट्वा प्रमोदं परमं गतौ।। 415 ।।

यमेव दर्षने सिधियदय दृष्टि गोचरं।

प्राप्तोऽधुना महाषत्रुरादौहिंस्यौ यमेवहि।। 416 ।।

विमृष्यैवं समायातौ तं प्रदेषं तु वाडवौ।

निष्चलाङ्ग मुनिं दृष्ट्वा प्रोचतु स्तंमुनिष्वरं।। 417 ।।

रे रे दुष्ट महापापाय कृतं विदुषां पुरः।

वादस्य समयेस्माकं मन्यायमधुना स्मर।। 418 ।।

ज्यैष्ठो भ्रातानुजं प्राह जह्येनं सत्वरं रिपु।

निजखङ्गप्रहारेण भवावः सुखिनौ ध्रुवं।। 419 ।।

इत्युक्तेप्यनुजं प्राह श्रृणु ज्यैष्ठ वचोमम।

पूर्वंमुने तृणेढित्वं मयातदनुहन्यते।। 420 ।।

परस्परं विवादो हियातस्तावत्रयोरपि।

एकः प्रोचे कथं हन्मिपापस्यात् मुनिघातजं।। 421 ।।

द्वितीयोपि तदा प्रोचे कथंहन्मि मुनीष्वरं।

मम स्यात् पातकं नूनं मुनिघातसमुद्भवं।। 422।।

चिरं कृत्वा विवादं तौ निज शास्त्रवलेन च ।

ज्ञानवान शत्रुरेवास्तु न मूर्खोहितकारकः।। 423 ।।

विमृष्यैवं चिरं चित्ते विप्रौ तौ क्रोध पूरितौ।

मुनेस्तु पार्ष्वयो गत्वा युगपद्धं तु मुद्यतौ।। 424 ।।

बध्वातु भृकुटीं भीमां:रुक्षनेत्रौ दुरासयौ।

कृतान्त सदृषौ पापौ दुष्ट चेष्टौ कृपोष्भितौ ।। 425 ।।

ऊध्वी कृत्य प्रहारौ तौ संस्थिगावत् मुनिं प्रति।

रमामनौवने तावत् यक्षाधीषो समागतः।। 426 ।।

युगयद्धंतु कामौतौ दृष्टोयक्षेण चाडवौ।

तदा तु चिन्तितं चित्ते कृपया विष्ट चेतसा।। 427 ।।

अपराध विनिमुक्तं मुनीन्द्र ध्यान संयुतं।

पापौ दुष्टाषयौ नीचौ कथं हन्तु समुद्यतौ।। 428 ।।

समानः शत्रुमित्रेषु सर्वसत्व हितं करं।

हन्यते पापचेपोभिः कथं योगीष्वरौ नरौ।। 429 ।।

एवं विधस्य साधोष्चेत् रक्षणं न करोम्यहं।

तदामेव न पालत्वं वृथा भवति निष्चितं।। 430 ।।

पापयोस्त्वैन यौर्नूनं शतखंडं करोभ्यहं।

इति मत्वा समायातः तत्रासौ यत्रतौ स्थितौ।। 431 ।।

द्वष्ट्वा तौ चिन्तितं तेन हन्तुं नैवाधुना चितं।

तयोर्हनने नूनमयषः स्याज्जनाग्रतः।। 432।।

प्रभाते तु जनाः सर्वे दृष्ट्वा मरणमेतयोः।

कथंयिष्यन्ति मुनिनाथनिहितौ वाडवौ स्वयं।। 433 ।।

एवं विधेपवादे हि जाते वा रक्षितेन किं।

सर्वथैवापवादोत्ररक्षणीयो विवेकिभिः।। 434 ।।

सूर्योदये तु संजाते मारयामि हठादिमौ।

सर्वलोकसमक्षं हि भूपतष्च पुरोध्रुवं।। 435 ।।

इति मत्वा तदा नेनस्तं भितौ तौ तु वाडवौ।

स्तम्भयित्वा गतं स्थानं निजं वै क्षेत्रपालकः।। 436 ।।

ततः सूर्योदये जाते सर्वोपि नगरीजनाः।

एतौ तथा विद्यौ दृष्ट्वा वेगात् तत्र समागतः।। 437 ।।

सर्वत्रनगरेताव सुद्विरेवं विधा भवत्।

नरनारीजनाः सर्वे कौतुकात् तत्र चागताः।। 438 ।।

तथाविधौतु तौ दृष्ट्वा निन्दितौ नगरी जनैः।

रे रे पापौ दुराचारौ किमारब्धमसुन्दरं।। 439 ।।

कल्येतु वारितं वादे शास्त्रस्य विदुषां पुरः।

विलक्षौवाधुनाहन्तुमुद्यतौ पापिनौ कथं।। 440 ।।

एवजनमुखा श्रुत्वा भूपालोपि कलकलं।

किमेतत्पुर बाह्येपि श्रूयते चरवो महान्।। 441 ।।

तत्रापि केन चित्प्रोक्तं शृणुनाथ नराधिप।

कल्येतु विप्रपुत्राभ्यां विवादो मुनिना कृतः।। 442 ।।

तदा तु हारितं ताभ्यां समक्षं विदुषां वने।

विलक्षौ तु पुरं गत्वा रात्रौ चात्र समागतौ।। 443 ।।

हन्तुकामौ मुनीन्द्रस्य वनाधीषेनस्तम्भितौ।

इति श्रुत्वा समायातो राजापि स्वजनान्वितः।। 444।।

तत्र सर्वजनैः प्रोक्तं दृष्ट्वोन्वातासि कौचतौ।

सर्वसत्व हितोयोगी धर्मकर्मधुरन्धरः।। 445 ।।

धर्मोधुनास्तु शरणं जिनेन्द्रवदनोद्गतः।

यत्रैव सर्वसत्वानां दया भवति निष्चिता।। 446 ।।

लोकेस्तयोर्गृहेगत्वा निरुक्तं पितरौ प्रति।

वने गत्वा तु पुत्राभ्यां यत् कृतं भवतोरपि।। 447 ।।

भविष्यति श्रुतं तत् च जगत् निंद्यकरं परं।

पितृभ्यां तु ततः प्रोक्तुं पुत्राभ्यां किं विनिर्मितं ।। 448 ।।

लोकैः तत्र ततः प्रोक्तुं शृणतः पुत्रचेष्टितं।

शठौ दुष्टौ वने गत्वा मुनेर्हन्तु समुद्यतौ।। 449 ।।

तावत् च वनपालेन कीलितौ पापिनौ वने।

पुत्रौस्थितौ तथा श्रुत्वा गतौ तौ पितरौ वने।। 450 ।।

दृष्ट्वा तौस्तंभितौ पुत्रौ जातौ दुःखभरालसै।

वाष्पांबुबिन्दुनिकरं मुंचतास्रु निरन्तरं।। 451 ।।

हा हा सुतौ कथं प्राप्तौ विवस्थां दुःखदायिनीं।

साधोक्तमांबुज युगमित्युक्त्वा पतितौ च तौ।। 452 ।।

प्रोचतुर्मुनिनाथं तं श्रृणुनाथ दयापरः।

प्रयछ पुत्र भिक्षां नौत्वं तु जीवदयावह।। 453 ।।

उपकारिषु यः साधुसाधुत्वे तस्य को गुणः।

अपकारिषु यः साधुः ससाधुः सद्‌भःच्यते।। 454 ।।

एवं तौ पितरौ यावत्यरिदेवनसंयुतौ।

वर्त्तते तत्र कुर्वानौ तावद्ध्यानं मुमोचसः।। 455 ।।

योगं व्यक्त्वाऽथ योगीन्द्रो दृष्ट्वा तौस्तंभितौ द्विजो।

विस्मित्य कृपयाविष्टो जगादैवं वचोवरं।। 456 ।।

य प्रातिहार्यमकरोत् यक्षणाथो दयापरः।

सचात्रप्रकटी भूय विप्रौ यक्षणमुंचतु।। 457 ।।

तावत् च प्रकटो जातो यक्षाधीषोपि पुण्यतः।

दंडहस्तोयतिं प्राहयषि तिष्ट महामुने।। 458 ।।

किमस्ति चिंतयानाथ कार्यं चात्र तवानयोः।

युक्तं निचारियितुं ते यदि हस्मि निरर्थकं।। 459 ।।

निवेदनाथलोकानां रूद्धौरात्रा विमोमया।

माभूत्तचात्रभगवन् जनानामपवादता।। 460 ।।

हन्तास्मि साम्प्रतं नाथमदांधौवाडवौ ध्रुवं।

इत्युक्त्वा वनपालौसौ नूनं हन्तुं समुद्यतः।।461 ।।

रे रे पाप महीपाल तव राज्ये कथं शठौ।

द्विजावेतौ मुनीषस्य मारणाय समुद्यतौ।। 462 ।।

राजा जगाद हे यक्ष ममशुद्धिं विनाद्विजौ।

मारणाय मुनींद्रस्य प्रवृतौ पाप चेतसौ।। 463 ।।

भवेत् चेदं मया ज्ञातं तदा मे दूषणं ननु।

मुनिर्यक्षं जगावेवं न जानाति नरेष्वरं।। 464 ।।

अतः एव हि दोर्षोत्र न मनागपि भूपते।

इत्थं तस्य मुनेः श्रुत्वा यक्षो वाक्यं हितावहं।। 465 ।।

वलित्वा भूपतेः पार्ष्वात् दण्डनीत्वा च तौ प्रति।

चलितः क्रोध संयुक्तो हननायाति वेगतः।। 466 ।।

तावत् च मुनिना तत्र प्रोक्तं यक्षेष्वरं प्रति।

नैव युक्तं तवैवात्रमदर्थ वाडवा विभौ।। 467 ।।

वयं तु यतयो नूनं उपसर्ग सहासदा ।

अस्माकं शासने प्रोक्तमुपससर्ग जयस्तपः।। 468 ।।

उपसर्गे मुनीन्द्राणां कर्माराति विनाषनः।

कथं पाप यक्षो नुनमुपसर्गजयं विना।। 469 ।।

यक्षाधीषः ततः प्रोचे श्रुत्वा वाक्यं मुनेरिदं।

श्रृणुनाथ दयापाल कर्म शत्रु निकंदकः।। 470 ।।

मायापराधमुक्तानां विनाषः क्रियते यदि।

निवार्योहं तदानाथ नान्यथा तव युज्यते।। 471 ।।

त्वं कुरुष्व निजां चिन्ता मन्य चिन्तां विवर्ज्जय।

एतौहन्मि दुराचारौ पापिनौ मुनि हिंसकौ।। 472 ।।

मुनीन्द्रोपि ततः प्रोचे दृष्ट्वा तं हननोद्यतं।

श्रृणु यक्षमहाराज चान्यत्कार्यमिहास्ति यत्।। 473 ।।

एतौ तु नेमिनाथस्य तीर्थे कृष्णशरीरजौ।

भूत्वाकर्मक्षयं कृत्वा मोक्षं तुयास्यतो ध्रुवं।। 474 ।।

अतएव विनाषोहि युज्जते नानयोस्तव।

इत्थं श्रुत्वा मुनेः वाक्यं प्रणम्य मुनिपुंगवं।। 475 ।।

विप्रद्वयं ततो मुक्त्वा समक्षं भूपतेस्तदा।

अदृष्यो यक्षनाथो कृत्वा धर्मप्रभावनां।। 476 ।।

सकौतुको जनस्तत्र वभूव भू भुजा सह।

धर्मप्रभावनां दृष्ट्वा कस्य हर्षो न जायते। 477 ।।

ततो विप्रस्य तनयौ नत्वा तं मुनि पुंगवं।

प्रोचतुर्वचनं रम्यं विनयेन पुरस्थितौ।। 478 ।।

क्षमस्व भो कृपानाथ दुष्कृतं कृतनावयोः।

त्वादृषः साधुलोकोहि किं बालाय प्रकुप्यते।। 479 ।।

मुनिर्जगाद हे वत्सौ मयाक्षांति कृतासदा।

कृत्स्नस्य जगतो नूनमधुना क्रियते कथं।। 480 ।।

स्वकर्मवषगोलोको न दोषः कस्यचित् क्वचित्।

यस्य दुःखं पुरायनदत्तं तेनात्र दीयते।। 481 ।।

उपकारः कृतोयस्य पुराजन्मनि जन्तुना।

तेन तस्योपकारोपि क्रियते नान्यथा ध्रुवं।। 482 ।।

अनर्थकारणं कर्मपुराजन्मनियत्कृतं।

सुखेदुःखे जयेलाभे कारणं कर्म सम्भवं ।। 483 ।।

इतिमत्वा तु जीवेन दोषो ग्राह्यो न कस्यचित्।

भवद्भ्यां कृतं किंचित् मम विप्रावनर्थकं।। 484 ।।

भवद्भ्यां तु विषादोहि कर्त्तव्यानमनागति।

इत्यादि साधु वचनात् बोध प्राप्तौ द्विजौतदा।। 485 ।।

प्रोचतुर्वचनं रम्यं श्रृणु नाथ कृपा निधे।

धर्मगेह महास्तम्भः शरीरं वर्त्तते तव।। 486 ।।

आवाभ्यां ते शरीरस्य विनाषष्चिंतितः कथं।

धर्मसाधनभूतस्य कारणेन विना विभो।। 487 ।।

किंचित् कथय हे नाथ व्रतं पुण्यं जपस्तपः।

येनयाति क्षयं पापं तव घातसमुद्भवं।। 488 ।।

मुनिर्जगाद हे वत्सौ श्रूणुतां धर्म कारणं।

पापं वृक्षकुठारं यद् बीजं धर्म महातरो।। 489 ।।

सम्यक्त्वां मलनिर्मुक्तं निःषंकादिगुणैयुतं।

पंचधाणुव्रतं प्रोक्तमहिंसापूर्णकं हि यत्।। 490 ।।

षिक्षाव्रत चतुर्द्धेति त्रिविधं तु गुणव्रतं।

एवं द्वादषभेदैष्च श्राद्धानां तु व्रतं मतं।। 491 ।।

रात्रौतु भोजनं त्याज्यं त्याज्यं वासर मैथुनं।

जिनपूजादि षट्कर्म कर्त्तव्यं चतुरै नरैः।। 492 ।।

मद्यमांसादिकं त्याज्यं सर्वातीचारवर्जितं।

आस्थानादिकमेवात्र कंदमूलादिकं तथा।। 493 ।।

पुष्पादि सकलं त्याज्यं शासनेयच्च दूषितं।

पुष्पितं विदलं धान्यं निंद्यं पापकरंपरं।। 494 ।।

परोपकारणं यत् च कर्त्तव्यता सदापरनिंदा।

संसारात् तारणेतं त्रिधाज्यत्पजेत्।। 495 ।।

धर्ममेवं विधं प्रोक्तं दषधाजिनषासने।

तदेव भव्यजीवानां संसारात् तारणेक्षमं।। 496 ।।

इत्थं ज्ञात्वा निजेचित्ते भवद्भ्यां धर्मकारणं।

सर्वपाप विनाषाया कर्त्तव्यो धर्म संग्रहः।

विप्रौमुनेर्वचः श्रुत्वा पितृभ्यां सहितौ तदा।

चक्राते संग्रहं तस्य जैनधर्मस्य भक्तितः।। 498 ।।

सम्यक्त्वा परमं प्राप्य निर्मलं जिन भाषितं।

पितृ मातृ युतौ तौहि तुष्ट चित्तौव भूवतः।। 499 ।।

धर्मरत्नं समासाद्य कस्य तुष्टिर्नजायते।

अमृतेतु तथापीते संतोषः सर्वजन्तुषुः।। 500 ।।

निंद्यमानौ जनैः कष्चित् कैष्चित् संस्नूयमानकौ।

मुनिं नत्वा पुरंयाता युक्तबन्धुसमाकुलं।। 501 ।।

जिनेन्द्रचरणांभोज रजसापूतमस्तकौ।

जिनधर्म समाषक्तौ तिष्ठतुः सुखतोगृहे।। 502 ।।

जिनधर्ममहोत्साहे जिनचैत्यालये तथा।

गुरुणां वन्दनादौ च तावेव प्रथमौपुरे।। 503 ।।

अनेन विधिना काले तयोर्याति निरन्तरे।

मिथ्यात्व कर्मवषगौ जातौ तौ पितरौ पुनः।। 504 ।।

कियानपि गते काले पितृ युग्मं सुतौ प्रति।

अवोचदित्थं हे पुत्रौ श्रृणुतां वाक्य मावयोः।। 505 ।।

वेदमार्गरिपुं धर्मकर्त्तुं युक्तं न साम्प्रतं।

तदाकार्य विषेषात् च गृहीतां जिनभाषितं।। 506 ।।

जाल्पितं नैव पुत्राभ्यां श्रुत्वा वाक्यं तयोरिति।

गुरुद्वयममार्गेहिरतं ज्ञातं तथैव च।। 507 ।।

किं कुर्वः कस्यवाब्रूचः पित्रोः पापमयंमनः।

जातं तथैव तौ दुःखादितियोषं समाश्रितौ।। 508 ।।

देषव्रतानि संपाल्य सम्यकत्वं च विधानतः।

चतुर्विधाय संघाय दत्वा दानं चतुर्विधं।। 509 ।।

जिनेन्द्रभवनेष्वे च कृत्वा पूजां मनोहरां।

सन्यासमाप्यविधिना स्वर्गं तौ वाडवौगतौ।। 510 ।।

तत्रोपपादषयेन षिलायां तौ समुद्धतौ।

गीतनृत्यादिकं दृष्ट्वा सुरांगनाजनैः कृतं।। 511 ।।

विस्मितौ किमिति प्राप्तौ जयजयारमद्भुतं।

सैधर्मेदिविसंजातं विन्द्रोपेन्द्रो सपुण्यतः।। 512 ।।

स्मृत्वा पुरातनं पुण्यं श्रीजिनेन्द्रमुखोद्गतं।

शय्याविमान प्रमुखं तयोः सुखमनेकधा।। 513 ।।

जातं तु स्वर्गलोके हि तयोः पुण्यफलेनहि।

मंदभाग्ये ननौलेभिं सुखं स्वर्गसमुद्भवं ।। 514 ।।

तावेव द्विजपुंगवौ जिनमतं संपालयंतौ मुदा

सम्यक्त्वं सुविचारद्धमैव सततं चित्ते दधौता वुभौ।। 515 ।।

स्वायंप्रागभवमेव निष्चलतया संस्मर्य मानौ वृषात्।

सौधर्मे सुखमासतुः निरुपमं तौ पल्यपंचस्थितिं।। 516 ।।

धर्मादेवसमीहितं निरुपमं संप्राप्यते प्राणभीरुपंकांति ।

भरं मतिं सुविपुलां प्रागल्भ्यमुज्जागरं।। 517 ।।

नैर्मल्यं नितरां समृद्धिमाधिकां लोकत्रये विश्रुतां।

सर्ववस्तु सुखेन पुण्यवषतः सोमैवश्रुभ्रंयषः।। 518 ।।

***इतिश्रीप्रघुम्नचरिते श्रीसोमकीर्त्याचार्यविरचिते नारदमहाविदेहगमन, प्रद्युम्नपूर्वभवप्रश्न, अग्निभूति वायुभूति स्वर्गगमनोनाम**

षष्टमः सर्गः*

चतुर्थोऽध्यायः

सप्तमसर्गः

अस्त्यत्र भारते क्षेत्रे विषयः कौषलाभिधः।
स्वच्छासरः समाकीर्णः स्वर्गलोक इवापरः।। 1 ।।
चम्पकाषोकपुन्नागनारिगवकुलाः कुलाः।
वाटिका यत्र राजन्ते पुष्पप्रकरशोभिताः।। 2 ।।
वापिका यत्रसन्नीरैः पूरिताः पंकजावृताः।
स्वर्णसोपानराजीभिः वर्त्तते श्री विभासुराः।। 3 ।।
श्रियंमानसकासारसन्निभां धारयंति याः।
सरांषि यत्र राजन्ते ससारसनिः Üवनैः।। 4 ।।
सरितः प्रसरन्नीरं पूरपूरित विग्रहाः।
गम्भीरावर्त्त संयुक्ताः शोभन्ते बुद्धिवल्लभाः।। 5 ।।
मेद्यवद्गुहिरैणीरणादैः संपुरितांतराः।
दानलब्धपाराष्च विभ्राजन्ते महोज्ज्वला।। 6 ।।
पुंड्रेनक्षुवाट संकीर्णा राजन्ते यत्र भूमयः।
स्थाने स्थाने सदानल्य शोभाभरविभासुराः।। 7 ।।
कुक्कुटोत्पात संलक्षा यत्र ग्रामामनोरमा।
धनधान्य समाकीर्णः परोपद्रव वर्ज्जिता।। 8 ।।
यत्र स्वप्नेपि दुष्काला श्रूयतेन हि जातुचित्।
सप्ते तयो न लोकेषु न चौरापद्रवस्तथा।। 9 ।।
पराभवोथकस्यापि कोपि कर्त्तुं क्षमो नहि।
नातं को व्याधिजो यत्र श्रूयतेकर्णगोचरः।। 10 ।।
धनदैवधनाकीर्णः संकीर्णः पुण्य कर्मभिः।
न्यायनिष्टो गुणैर्ज्येष्टा यत्र वासीजनो भृषं।। 11 ।।
अयोध्यानामत ख्यातापुरीस्वर्ग गरीसमा।

देवताय तनैर्युक्ता राजते यत्र सुन्दराः।। 12 ।।
या नित्यं सर्व शत्रूणां दुर्गमादुर्गयोगतः।
निर्मिता धनदेवेनासौ ना भेय जननोत्सवे। । 13 ।।
पुण्यवद्भिर्जनैर्याहि पूरिताभाति सर्वतः।
नदृष्यते नरः कोपि पापकर्म समन्वितः।। 14 ।।
सुव्रन्तो निष्कलंकष्च कलावान क्षय वर्ज्जितः।
दौषाकरो न यत्रास्ति पूर्णचन्द्र समोजनः।। 15 ।।
गीतनृत्यकलाकेलिलीलाविभ्रमभासुराः।
कामिन्यः कमनीयां गायत्र सन्ति गृहे गृहे।। 16 ।।
षट्कर्म निरता यत्र पूजाः सन्ति विचक्षणाः।
त्यागिणो गुणिनःसूरा जिनधर्मेरता सदा।। 17 ।।
उत्पत्तिस्तत्र संजाता जिनानां चक्रवर्त्तिनां।
तस्याः का वर्णना नूनमुत्सवस्तुसुरैः कृतः।। 18 ।।
तत्रारिंजयनामासीदन्वर्थः पृथिवीपत्तिः।
शत्रुराषि निहतायः प्रपाता शरणार्थिनां।। 19 ।।
करीणां तु सहस्राणि सन्ति तस्यापिनेकषः।
तुरंगमरथानां हि संख्या जानामि नोध्रुवं।। 20 ।।
सेवकाः कुलसम्भूताः सक्ताभक्ता कुलागताः।
सन्ति तस्य नरेन्द्रस्य वैरिवंषविनाषकाः।। 21 ।।
गुणलक्षणसम्पूर्णो धनेन धनदोपमः।
प्रजाया पालने दक्षो दोषराषिविवर्ज्जितः।। 22 ।।
यस्य दानं समालोक्य लज्जिताः कल्पपादपाः।
तथा गता यथाद्यापिनायान्ति क्षिति मंडले।। 23 ।।
स्त्रीणां नेत्रे हरष्चौरः कामसन्निभविभ्रमः।
बुभुजे मेदनीं सम्यक् प्रजा पालन पंडितः।। 24 ।।
तस्य प्रियं वदानामा प्रियाचागुणषालिनी।
शचीवसुरनाथस्य रोहिनीव कलावतः।। 25 ।।
भर्त्तु भक्ता वृषेरक्ता संषक्ता प्रेम कर्मणि।
सती गुण समकीर्णा सर्वलक्षण संयुता।। 26 ।।

एवं विधास्य भूपस्य परमामृत भाषिणी।
लावण्यलक्षणोपेता वर्त्तते प्राणवल्लभा।। 27 ।।
तत्रैव तु नगर्यां हि श्रेष्ठी धर्म विषारदः।
समुद्रदत्तनामासीत् पुण्यवान् श्रावकोत्तमः।। 28 ।।
शुद्धवंष समुद्भूतो गुणशीलालयो महान्।
शंकादि दोष निर्मुक्तो रत्न त्रय विभूषितः।। 29 ।।
षट्कर्म पालने दक्षो जिन पूजा पुरन्दरः।
त्रिपंचाषक्तियोपेतो दषधाधर्म संयुतः।। 30 ।।
देषव्रते समाषक्तो मिथ्यात्वादिविवर्जितः।
त्रिषुपात्रेषु यो नित्यं दानं यच्छन्ति सर्वदा।। 31 ।।
श्रावकाचार चतुरो जिनागम परायणाः
देवषास्त्र गुरुणां हि परं भक्तो दयान्वितः। । 32 ।।
तस्यासीत् भामिनीरम्या सर्व लक्षण संयुताः।।
प्रसिद्धाहारिणी नामा लावण्य जलदीर्घिको।। 33 ।।
सद्वंषे तु समुद्भूता सद्गुणैः विनयानता।
कामकोदंड यष्टिर्वास्वामि चित्त विभेदिनी।। 34 ।।
देवषक्तगुरौ भक्ता शीलसम्यक्त्व संयुता।
पतिव्रता सदाचारा विषुद्धा हि कुलद्वये।। 35 ।।
ईद्वष्या रामयायुक्तो भुंक्ते श्रेष्ठी सुखं परं।
गतं कालं न जानाति निगग्नः सुखसागरे।। 36 ।।
तयोः पुत्रार्थिनौ जातौ स्वर्गा देत्य सुरात्तमौ।
सूत्रकंठ चरौतौ हि भुक्त्वायुः पुण्य सम्भवं।। 37 ।।
जिन धर्म प्रभावेन स्वजनांबुज भास्करौ।
पुत्र जन्मनि कालेतु पितृभ्यामुत्सवकृतः।। 38 ।।
दत्वं दानं तथार्थिभ्यो मानिताः स्वजनानिजाः।
जिनालयेषु पूजां च चक्रे श्रेष्ठी सुभक्तितः।। 39 ।।
अभयाख्यं वरं दानं दापितं नगरे तदा।
कृतोधनानुसारेण षट्दिनानि समुत्सवः।। 40 ।।
सप्तमे दिवसे प्राप्ते मिलित्वाखिलं सज्जनैः।

तयोर्न्नाम विधिस्तत्र चक्रिरे विधि पूर्वकं।। 41 ।।
आद्यः श्रीमणिभद्राख्यो द्वितीय पूर्णभद्रकः।
सोमवत्सौम्यवदनौव वृधाते दिने दिने।। 42 ।।

वर्षेतु प×चमे प्राप्ते नीत्वा तौ जिन मंदिरे।

देवश्रुत गु:न् भक्त्या पूजयित्वा विधानतः।। 43 ।।
पित्रातु पठनं दत्तौ जैनोपाध्यायकाय च।
पठितौ श्री जिनागारे पूर्वपुण्य प्रभावतः।। 44 ।।
अनेकानि तु शास्त्राणि पुराणानि जिनागमं।
सिद्धान्तं चापि पठितौ कलालक्षणसंयुतौ।। 45 ।।
पठितौ तौ पिता वीक्ष्य वर्षे षोडषमेतथा।
यौवनं तु परं प्राप्तौ स्वजनानन्ददायिकं।। 46 ।।
स्वकुलोचित्त सम्बधौकृत दारं परिग्रहौ।
कृत्वा तु प्रमदं प्राप्तः पित्रो रे तत् चकारणं।। 47 ।।
धर्मार्थिकामभागेषु रक्तौ जातौ निरन्तरं।
गतं कालं न जानतौ निमग्नौ सुखसागरे।। 48 ।।
एकदाप्रमदोद्याने समायातो मुनीष्वरः।
महेन्द्रसूरिनामेति प्रसिद्धः क्षिति मंडले।। 49 ।।
यतिवर्गेण संयुक्तो न युक्तो दोषसम्पदा।
संज्ञानत्रय सम्पन्नो नानागम विषारदः।। 50 ।।
तस्मिन् मुनौ समायाते वनं जातं मनोहरं।
सत्पुष्पप्रकराकीर्णं फलपल्लवराजितं।। 51 ।।
सर्वत्रऋतु कुसुमाकीर्णं भ्रमत् भ्रमर संकुलं।
दत्तार्धमिव संजातं श्रीमहेन्द्र समागमे।। 52 ।।
नंदिनी व्याघ्रतो तेष्च मार्जारी हंस बालकैः।
सारंगीसिंह पुत्रैष्च मयूरैः पन्नगैस्तथा।। 53 ।।
अन्येपिजन्तवः सर्वे दृष्टिजात समुद्भवं।
त्यक्त्वा वैरं मुनेः संगाद्रमिरे प्रमपूरिताः।। 54 ।।
वनस्यपालेकोहिसोपि तत्र समागतः।
सर्वेसमयमुल्लंघ्य फलिता वन पादपा।। 55 ।।

दृष्ट्वा तु विस्मयं प्राप्य चिन्तयामास मानसे।

शुभाषुभं तु किं भाव्यं विपरीतं हि दृष्यते।। 56 ।।

एवं चिन्तातुरः सोपि जातो हर्षेण पूरितः।

ज्ञातं तस्यैव माहात्म्यं वने विस्मयकारकं।। 57 ।।

सर्वर्त्तुषु समुद्भूतं नीत्वा पुष्पफलादिकं।

नृपालयं जगामासौ वनपालस्त्वरान्वितः।। 58 ।।

प्रणम्य भूपतिं दूरात् प्रतीहारे निवेदितः।

अग्रेभेटनकमुक्त्वा जगाद विनयान्वितः।। 59 ।।

श्रृणु नाथ वने रम्ये मत्त कौकिलकूजिते।

समागतो महासाधुः संयम श्री विभूषितः।। 60 ।।

तस्यागमन मात्रेण चिरं नन्द नराधिप।

वनपालोदितं श्रुत्वा राजा हर्षमुपागतः।। 61 ।।

तां दिषं तु समुत्थाय सप्तपदानि च ।

प्रणनाम महीपालो परोषिविनयान्वितः।। 62 ।।

तं प×चाग प्रसादेन षोडषा भरणैस्तथा।

संतोष्पिवनपालं हि प्रेषयत्पुण्यनोदितः।। 63 ।।

आनन्दभेरिनादेन बोधयत्सकलं जनं।

लोकोपि तं रवं श्रुत्वा जातोहर्षेण संयुतः।। 64 ।।

पूजोपकरणे नामा प्रतोल्यां भूपतेस्तदा।

समायातोखिलो लोको जिनभक्त्या वषीकृतः।। 65 ।।

समागतं जनं ज्ञात्वा परिवार समन्वितः।

गजा:ढ नृपो भूत्वा जगाम वन्दितुं मुनिं।। 66 ।।

गच्छन्तं भूपतिं दृष्ट्वा सर्वोपि नगरी जनः।

जगाम वन्दितुं भक्त्या जिनधर्म परायणः।। 67 ।।

राजावनं समासाद्य दृष्ट्वा तं मुनि पुंगवं।

राजचिÉ निराचक्रे मुनि भक्ति भरालसः। 68

त्रिः परीत्यनमीषानं गु:भक्त्यादि पूर्वकं।

प×चांगतुनमष्चक्रे मुनि भक्ति भरालसः।। 69 ।।

यथा स्थानं निविष्ठेषु भव्यलोकेषु भूपतिः।

प्रपच्छ च मुनिं भक्त्या कारणं बन्ध मोक्षयोः।। 70 ।।

कर्मणा केन बंधः स्यात् केन मोक्षोति दुर्ल्लभः।

तत्सर्वं कृपया नाथ ममात्र वक्तुमर्हसि।। 71 ।।

मुनिः जगाद हे भूप श्रूणु सर्वं समासतः।

येन जीवस्यबन्धः स्यात् येन वा मोक्षसम्भवः।। 72 ।।

मिथ्या त्वा विरती योगात्प्रमादो बन्ध कारणं।

कषायास्क्त जिनैः प्रोक्ताः प×चविंषति संख्यका। 73 ।।

अश्रद्धानां तु तत्वानां पदार्थानां तथैवच।

मिथ्यात्वायोगतो नूनं कारणं बन्धसम्भवं।। 74 ।।

तन्मिथ्यात्वं द्विधाप्रोक्तं जिनेन्द्रै ज्ञानलोचनैः।

स्वभावात् च तथैका तातदेव बन्धकारणं।। 75 ।।

संशयादिक भेदेन मिथ्यात्वकर्मयोगतः।

पापश्रवस्य सम्बन्धात् बन्धः प्रोक्तोजिनोत्तमैः।। 76 ।।

तथा प्रकृति युक्तानां अष्टानामपि कर्मणां।

बन्धयोगेन बन्धः स्याद् शुभाश्रवयोगतः।। 77 ।।

1. बन्धकारणं– मिथ्यात्व, अविरत, प्रमाद, कषाय, योग

2. मिथ्यात्व– निसर्गज (अगृहीतमिथ्यात्व) गृहीतमिथ्यात्व

गृहीतमित्थात्व– एकान्त, विपरीत, संषय, विनय, अज्ञान मिथ्यात्व।

संक्षेयतोपि बोधव्या मिथ्यात्वस्य महीपते।

परिणाम कृतासंख्या विकल्प त्रिषु धीमता।। 78 ।।

तथा विरतयष्चात्र द्वादषैव नराधिप।

योगाः प×चदषाः ख्याता प्रमादाष्चापितत्प्रमा।। 79 ।।

बन्धस्य कारणं सर्वे त्वं जाना हि महीपते।

अधुना कथ्यते ते हि कारण मोक्ष सम्भव।। 80 ।।

विष्णेषः क्रियतेयच्च जीवस्यापथकर्मणः।

दर्षनज्ञानचारित्र त्रयं तस्यापि कारणं।। 81 ।।

जीवादिसप्ततत्वानां श्रद्धानं दर्षनं मतं

दर्षनेन विना मोक्षो न भूतो न भविष्यति।। 82 ।।

शुक्लाध्यानेन योगेन कर्मणां क्रियते क्षयः।

पृथकात्मा पृथककर्म चिन्तनीयः पुनः पुनः।। 83 ।।

निसर्गाधिगमाज्जातं तत्सर्वं दर्षनं द्विध।

क्षयात् चोपषमाज्जातं कर्मणामुभयात् तथा।। 84।।

प्रत्येकं द्वितयंत्रेधा कथितं श्रीजिनेष्वरै।

पदार्थानां नवानां तु सम्यग्ज्ञानं जिनामगात्।। 85 ।।

मतिः श्रुतावधिष्वेतिमनः पर्यय केवलं।

समुत्पत्तिः क्तज्ञानां कर्मणां हि क्षयाद्भवेत्।। 86 ।।

त्रयोदषविधं भूप चारित्रं तु जिनैर्मतं।

गृहीतेत्वथ चारित्र कर्त्तव्यं प्राणिभिर्ध्रुवं।। 87 ।।

दर्षनज्ञान चारित्रैर्मोक्ष मार्गोनिवेदितः।

श्रद्धवाचैवतत्वानां सम्यक् दर्षन भाषितं।। 88 ।।

अन्यषरीर मन्योहं चिन्तनीयोनिषंनृभिः।

कायप्रमाणमात्मानं व्यौमरूपं निरंजनं।। 89 ।।

नित्यं विनाष निर्मुक्तं जराजन्म विवर्ज्जितं।

निष्कलंक निराबाधं निर्गुणं गुण संयुतं।। 90 ।।

कर्म प्रकृतिनिर्मुक्तं ध्यायेज्जीवं सदाहृदि।

तदाकर्मक्षयोनूनं भविष्यति सुनिष्चयः।। 91 ।।

कर्मक्षयेथ संजाते मोक्षोवैजिनभाषितः।

इति सर्वं समासेनविद्धि भूप जिनोदितं।। 92 ।।

तथा पृष्टं समाख्यातं कारणं बन्ध मोक्षयोः।

बन्धेन जायते जीवः श्वसेतुघोर वेदने।। 93 ।।

मोक्षात् मोक्षपदं याति शाष्वतं भयवर्ज्जितं।

जराजन्म वियोगादि रोग शोक विवर्ज्जितः।। 94 ।।

इत्थं संक्षेपतः सर्वं कथयित्वा मुनीष्वरः।

योषं जग्राह शुद्धात्मासंतोहि मितं भाषिणः।। 95

श्रुत्वा वाक्यं मुनेः तस्य तोषं गत्वा नराधिप।
प्रत्याह भूपतिः पीतः कृत्वा तु कर सम्पुटं।। 96 ।।
श्रृणुनाथ कृपाधार सर्व भूत हितावह।
मयापृष्टं त्वया ख्यातं ज्ञातं संसार चेष्टितं।। 97 ।।
प्रीतिस्तु भंगुरानाथ संसारे सार वर्ज्जिते।
देहारोग शतापूर्णो विषयाविषसन्निभाः।। 98 ।।
योवनं भंगुरं लोके संयोगाः स्वप्न सन्निभाः।
सुखं दुःख समाक्रान्तं जीवितं शरदभ्रवत्।। 99 ।।
भोगाः संसारिणां नाथ किं पाकफलसन्निभाः।
संपदोपि मयाज्ञाताः करिकर्णसमाविभो।। 100 ।।
चिन्तयित्वा भवांभोधे निर्विन्नोस्मि महामुने।
दीक्षां तु ने तु कामोहं तव पाद प्रसादतः।। 101 ।।
तत्प्रसादाधुनानाथ कृपां कुरु ममोपरि।
संसार वारिणीं दीक्षां देहि देहि विभोमम।। 102 ।।
भूप वाक्यं समाकर्ण्य प्रोवाचेदं मुनीष्वरः।
भव्यं चित्ते समाध्यातं दीक्षा ग्रहण कारणं।। 103 ।।
न तु भाग्य विहीनानां दीक्षा जैनेष्वरी नृप।
दीक्षया प्राप्यते मोक्षः स्वर्गदीनां तु का कथा।। 104 ।।
इति ज्ञात्वा त्वया ग्राह्यादीक्षादैगंबरी वरा।
मुनि वाक्येन भूपोऽसौ ददौ राज्यं निजेसुते।। 105 ।।
भूपो भूपतिभिः सार्द्धं सर्व सत्वहिता वहां।
दीक्षां जग्राह जैनेन्द्रीं स्वर्गमोक्ष निबंधिनीं।। 106 ।।
तद्वृत्तं तु समालोक्य श्रुत्वा धर्मं गुरुदितं।
वैराग्येन समाक्रान्तो जातः श्रेष्ठी विचक्षण।। 107 ।।
निवेष्यात्मपदेपुत्रोज्ञात संसार संकथा
सर्वसंग विनिर्मुक्तो जातो सौ मुनिपुंगवः।। 108 ।।
अत्रांतरे मुनिं नत्वा श्रेष्ठी पुत्रो विचक्षणौ।
प्रपच्छनुर्गृहस्थानां धर्मं सर्वहितावहं।। 109 ।।
साम्प्रतं नैव शक्तौनौदीक्षं नेतुं जिनोदितां ।

गृहस्थानां समाख्याहि धर्मं कल्पनगोपमं।। 110 ।।
मुनिनाथो जगावेवं कथयामि समासतः।
श्रृणुतः त्वे कचित्तेन भवन्तौ विहितादरौ।। 111 ।।
यस्तु संसार कूपेहि पतन्तं प्राणधारिणं।
धारयत्पति वेगेना तस्माद्धर्मो निगद्यते।। 112 ।।
आत्मवत्सर्व भ्रतानां पर द्रव्येषु लोष्ठ वत्।
मातृवत्परदारेषु यः पश्यति स धर्म भाक्।। 113 ।।
सधर्मो द्विविधः प्रोक्तः सागरेतर भेदतः।
ततस्तपस्विनामाद्यस्ततोन्यद् गृहमेधिनां।। 114 ।।
गृहस्थानां तु धर्मं हि कथयामि तवग्रतः।
सम्यग्दर्षन प्रवंतु व्रतषीलादि संयुतं।। 115 ।।
चतुर्विधाय संघाय दानं देयं च तु विधं।
मिथ्यात्वां सर्वथा त्याज्यं सम्यक्त्वस्य विनाषकं।। 116 ।।
अष्टौमूल गुणायेहि प्रोक्तो श्री जिननायकैः।
तेषां त्यागः सदाकर्यः श्रावकाचार निर्मलैः।। 117 ।।
निन्दां नैवांगिनां कार्यायातु दुर्गतिकारिणी।
नैव विष्वासघातं हि कर्त्तव्यं पाप कारणं।। 118 ।।
उपवासः सदाकार्यो नूनं पर्व चतुष्टये।
अष्ठांगं पाल्यते वत्सौ सम्यकत्वं शषितिर्मलं।। 119 ।।
मिथ्या त्वं संयोगेण मूलतोपि विनष्यति।
निष्ट धर्मस्तु दुःप्रायो रत्नं रत्नाकरे यथा।। 120 ।।
मिथ्या त्वं सर्वथा त्याज्यं ग्राह्यं सम्यक्त्वमुत्तमं।
मिथ्यात्वान्नर को नूनं सम्यक्त्वात् स्वर्गमेवहि।। 121 ।।
नाक सौख्यं गुणै युक्तं सर्वेन्द्रिय सुखप्रदं।
देव देव्यादि संसेव्यं प्राप्यते धर्मतो ध्रुवं।। 122 ।।
भीमेरणांगणे धर्मो दुर्भेद कवचायते।
नाव्यते हि तथा धर्मो सागरे दुस्तरे नृणां।। 123 ।।
धर्मः कल्प द्रुमोलोके धर्मष्चिन्तामती नृणां।
धर्मकामदुधाधेनु धर्म धर्माष्चिन्तित वस्तुदः।। 124 ।।

धर्मः पाथेयवान् पांथोनैव भव्योवसीदति।
संसारे भ्रममाणोसौ सर्वत्रापि सुखी भवेत्।। 125 ।।
ग्रहाभूत पिषाचादि शाकिन्यः पन्नगादय।
पराभवन्ति नो नूनं धर्म संसक्तमानसं।। 126 ।।
तीर्थकृत चक्रवर्त्ति त्वं बल केषवतां तथा।
भूपत्वं मंत्यदेहत्वं सर्वं धर्मात्समाप्यते।। 127 ।।
सप्तभूमि समायुक्ताः प्रासादात् च मनोरमाः।
गजाष्वास्पंदनाश्वेति धर्माषक्ता लभंति हि।। 128 ।।
कामिन्यः सुन्दराकाराः सत्पुत्राः सत्सहोदराः।
धनधान्यदि संयुक्तं सभ्यते धर्म सेवनात्।। 129 ।।
सागरस्यांतरेस्थं यद्यच्च देषान्तरे स्थितं।
तत्त धर्म प्रभावेन निजगेहे समाप्यते।। 130 ।।
नास्ति धर्म समोबन्धुः नास्ति मित्रं ततः परं।
स्वामी च तत्परो नास्ति तद्धर्मेक्रियतां मनः।। 131 ।।
इति तौ श्रेष्ठिपुत्रौ हि श्रुत्वा धर्ममयीं कथां।
नत्वापादौ मुनीन्द्रस्य हर्ष पूरित मानसौ। 132 ।।
सम्यकत्व भ्रषितं धर्मं द्वादषव्रत संयुतं।
नीतं ताभ्यां तु हर्षेण मुनीन्द्रस्य प्रसादतः।। 133 ।।
नत्वामुनिं गृहं यातौ श्रेष्ठिपुत्रौ विचक्षणौ।
धर्मध्यान समायुक्तौ स्थितौ जीव दयान्वितौ।। 134 ।।
जिनेन्द्र भवनेष्वेव महिमां श्री जिनोदितां।
कुर्वानावुत्तमां प्रजामष्टधाभाव संयुतौ।। 135 ।।
सत्पात्रेषु प्रयच्छंतौ दानं चैवचतुर्विधं।
धर्मार्थकाम संषक्तौ नाषक्तौ पापकर्मणि।। 136 ।।
भुंजानौ विपुलान् भौगान् लीलयाधर्म सम्भवान्।
न जग्मतुर्गतं कालं सुख सागर मध्य गौ।। 137 ।।
कियन् कालेगते तत्र स्थितयोष्च तपोध्रुवं।
अन्यदातुवने योगी समायातो जिनोदितः।। 138 ।।
तत्रतौ वंदितुं धाधुं चलितौ भ्रातरौ वरौ।

धर्मवासनया युक्तौ पूजा द्रव्य समन्वितौ।। 139 ।।
तावन् मार्गे तु मिलितौ निकृष्टाकार वेष्टितः।
शुनीसमेत चांडालो देवयोगात्तगौस्तदा।। 140 ।।
तथाविधेपि दृष्टे हि तयोः प्रीतिरभूत्परा।
अन्तरात्मापरं ज्ञानी जानाति च शुभाषुभं।। 141 ।।
शुनीचांडालयोष्चापि मनः स्नेह भरालसा।
जातं तु दर्षनादेवतयो सुश्रेष्ठिपुत्रयो।। 142 ।।
परस्परं परं जातातेषां प्रीतिस्तदोद्भता।
अन्योन्यलिंगिनं चित्ते चिंतितं अतिमोहतः।। 143 ।।
चत्वारोपिगतास्तावत् मुनिपार्ष्वैतिवेगतः।
श्रेष्ठि पुत्रौ गुरुं नत्वा निचैष्टौ श्रद्धयान्वितौ।। 144 ।।
प्रोचतुस्तौ मुनिं भक्त्या श्रृणुनाथ कृपानिधे।
शुनी चांडालयोः प्रीतिरावयो किमुहेतुका।। 145 ।।
कथय् स्वप्रसादेन मोहस्यैवतु कारणं।
मुनिर्जगाव हे वत्सौ श्रृणुतामेक मानसौ।। 146 ।।
कारणैन विना कार्यं जायते न कदाचन।
भवतां पितरौ वत्सा चेतौवैप्तव जन्मनि।। 147 ।।
अतएवै तयोर्ज्जाता प्रीतिस्तु युवयोरपि।
अन्तरात्मा ध्रुवं ज्ञानी वर्त्तते सर्व देहिनां।। 148 ।।
मुनिर्वाक्य समाकर्ण्य प्रोचतु वैष्यपुत्रकौ।
कथं वा पितरौ जातौ पुराजन्मनि हे विभो।। 149 ।।
मुनिः प्रोचे वरं वाक्यं श्रूयतां श्रेष्ठि पुत्रकौ।
यथा जातौ पुरावेतौ पितरौ युवयोरिमौ।। 150 ।।
शालीग्रामे तु संभूतौ वाडवस्य कुलेवरे।
अग्निला सोमषर्मेति वेद विद्या विचक्षणौ। 151 ।।
प्रतिग्रहा प्रवित्ताढ्यौ यज्ञकर्म परायणौ।
द्वैष्ठारौजिन धर्मस्य हिंसा नंदित मानसौ।। 152 ।।
तयौः पुत्रौतु संज्ञातावेतौ वै तृतीये भवे।
अग्निभूतिः तयोराद्यो द्वितीयो वायुभूतिकः।। 153 ।।

मन्वानौ जाति दर्पेण जगज्जीण नृणोपमं।
जिनधर्मं तु पितृभ्यां नीतं कार्यवषादिति।। 154 ।।
लब्धा धर्मं जिनेन्द्रौक्तं त्यक्तं तं पाप कर्मभः।
मृत्वा जातौ तु सौ स्वभ्रेपितरौ भवतोरपि।। 155 ।।
पंचपल्यानि तत्रैव भुक्त्वा दुःखं दुरस्तरं।
ताडनं पीलनं चापि भेदनं छेदनं तथा।। 156 ।।
प्रथमे नरके दुःखं प्राप्यतौ पाप कर्मतः।
निर्गतौ कालयोगेन कोषलायां समुद्गतौ।। 157 ।।
माता यत्र शुनीजाता चांडालोयं पितामच।
मिथ्यात्व कर्म योगेन जिनधर्मस्य निंदया।। 158 ।।
कुर्वाणौ भवतोः प्रीति जन्मांतर समुद्भवां ।
सारमेष्वपचष्चापिता विदानीं बभूव तु।। 159 ।।
जिनधर्म तिरस्कार कालकूट विषद्रुमः।
सिक्तोमिथ्यात्व तोयेन फलत्ये वा शुभं फलं।। 160 ।।
भवन्तौ जिनधर्मं तु पालयित्वा गतौदिवं ।
भुक्त्वा स्वर्ग समुद्भूतम् सुखमत्रागतौ युवां।। 161 ।।
जातौ वां श्रेष्ठि पुत्रौहि जिनधर्म प्रभावतः।
पुण्यापुण्यफलं वत्सौ ज्ञातव्यं मानसेखिलं।। 162 ।।
इति निष्चिंत्य सम्बन्धां मुनिवाक्येन तौ तदा।
दापयामातुर्सधर्म स्नेह पाष वषीकृतौ।। 163 ।।
जिनधर्मं मुनेः पार्ष्वे ताभ्यां तु दापितं तदा।
गृहीतं तद्वरं धर्मं श्वपचेन तया मम।। 164 ।।
धर्मं नीत्वापि चांडालो जगाद मुनि पुंगवां।
त्वत्प्रसादान्मयाज्ञातं पुराजन्म नियत्कृतं।। 165 ।।
क्व वा जन्म द्विजातीनां क्व मातंगा शुचिं कुलं।
इति संचित्य शोकोमे मनसाम्पति निष्चितं ।। 166 ।।
शोकरोग भयाक्रान्तं मृत्युजन्म जरामयं।
संसारावो न संसारं तथा कुरु विभो पुनः।। 167 ।।
इत्युक्ते मुनिनादत्तं सम्यक्त्वं गुण भूषितं।

निःशंकादि समायुक्तं द्वादषव्रत भूषितं।। 168 ।।
नीत्वा तौ हर्षतः सर्व सन्यस्य विधि पूर्वकं।
मासेनैवपि चांडालो मृत्वा यान्ति शुरालये।। 169 ।।
जातोनन्दीष्वरे द्वीपे विबुधो देव वन्दितः।
पंचपल्योपमायुषा जिनधर्म प्रभावक।। 170 ।।
दिनानि सप्त सन्यस्य सारमे भाव संयुता।
मृत्वा तत्र नृपस्यैव पुत्रीं जाता मनोहरा।। 171 ।।
पठिता शास्त्रमनेकेन भेदेनापि संयुतं।
योवनं तु परं प्राप्ता सर्वावयव सुन्दरा।। 172 ।।
एकदा यौवने तस्या रुपं दृष्ट्वा नराधिपः।
निः शैषानपि भूपालामाहूय लेख हारिभिः।। 173 ।।
तस्याः स्वयं वरे चक्रे महोत्सव पुरस्सरं।
समागता तदा कन्या श्रृंगोरण मया सह।। 174 ।।
तावत् नन्दीष्वरो देवो गच्छन् क्वपि जिनालये।
दृष्टं स्वयंवरं तेन कन्यायाः भूभुजाकृतं।। 175 ।।
तत्रागत्य च तां दृष्ट्वा ज्ञातं पूर्वभवं तदा।
बुध्वातां तु निजां जायां विस्मयेन जगाविति।। 176 ।।
स्थित्वा प्रच्छं नवृत्यासौ कन्ये किं भवपूर्वक।
विस्मृतं तव तत् दुःखं यच्च मोह समुद्भवं।। 177 ।।
अधुना पाणिग्रहणं किमारब्धं निरर्थकं।
संसार कारणं नूनं भोगः संसार वर्द्धकं।। 178 ।।
द्विजन्मयानुभूतं किं यच्चष्वभ्रसमुद्भवं।
शुनीचांडालयोगोत्थ विस्मृतं ते हि किं खले।। 179 ।।
तस्यामरस्यवाक्येन प्रबुद्धा सातुकन्यका।
वैराग्यं परमं प्राप्ये चलिता सा तु तत्क्षणात्।। 180 ।।
चलित्वा तु वने गत्वा वैराग्येण विभूषिता।
श्रुतसागर पार्ष्वे सा दीक्षां जग्राह निर्मलां।। 181 ।।
चलितां कन्यकां दृष्ट्वा सर्वेतेपि महीभृतः।
विस्मयं परमं प्राप्ताः किमत्र सहसा जनि।। 182 ।।

ज्ञातं तु भूभुजां नैनं वृत्तं पु=यास्तदैवहि।

सम्बोध्ये वचतां कन्यां सुरस्थानं निजं गतः।। 183 ।।

अर्ज्जिकाया महा दीक्षां पालयित्वा चिरं वरां।

स्त्रीलिंगं च निराकृत्यं दिविदेवो बभूवसा।। 184 ।।

जिनधर्म प्रभवेन किं किं न चाप्यते नृभिः।

इति ज्ञात्वा सदा कार्यो धर्मो वै जिनभषितः।। 185 ।।

कथा प्रसंग योगेन चरित्रं पितरोस्तयोः।

मयाप्रोक्तं समासेन पूर्ववृत्तं निरुपते।। 186 ।।

श्रेष्ठि पुत्रौ मुनिं नत्वा प्रमोदात् स्वगृहं गतौ।

जिनधर्मं समाराध्य पूजयित्वा जिनेष्वरान्। 187 ।।
सम्यक्त्वं पालयित्वा तौ नीत्वा सन्यासमुत्तमं।
निधनं प्राप्यतौ जातौ स्वर्ग सौधर्म नामनि।। 188 ।।

ऊपपादिक वृत्या तावुत्पन्नो त्रिदषालये।

यथाकाषेपरं मेघाः समीराष्च यथा पुनः।। 189 ।।

इन्द्रचापं यथाकाषे विद्युतोपि तथा पुनः ।

पूर्णवेहा यथा चामी भवन्ति सहसा पुनः।। 190 ।।

तथैव सहसा देवादि विगत्वासु पुण्यतः।

अकस्मात् च भवंत्यवे पूर्णगात्राः सुरालये।। 191 ।।

तत्रैव दिवि देवीभिः समागत्याति वेगतः।

आरार्त्तिकादिभिः पूर्वं पूजया पूज्यते ध्रुवं।। 192 ।।

वस्त्राभरण दानैष्च देव देवी कदम्बकैः।

सेविमानाः सदानूनं दिव्यवाहन संयुताः।। 193 ।।

सर्वलक्षण संपूर्णाः सर्वाभरण भूषिताः।

विमान वाहनारुढादिविदेवा भवंत्यमी।। 194 ।।

सुकृतस्य प्रभावेन जायन्ते त्रिदषालये।

चैत्यालये जिनेन्द्रानां कुर्वन्तो महिमावरां।। 195 ।।

सुरांगणामुखां भोज मधुपाना समानतां।

भजन्ति सर्वदा तेहि सौख्य सागर मध्यगाः।। 196 ।।

नव यौवन संपूर्णा वलीपलित वर्ज्जिताः।

धातुभिः सप्ताभि हीनाः तृप्तदेहाः सुधाषनैः।। 197 ।।
एवं नाना विधैः सौख्यैर्भौगैः नाना वधैः तथा।
न जानन्ति गतं कालं पूर्व पुण्य प्रभावतः।। 198 ।।
पुण्यात् स्वर्गे तथा मुक्तौ नृलोके भूभुजादिजं।
प्राणी सौख्यमवाप्नोति नूनं सम्यक्तव संयुतः।। 199 ।।
पुण्यात्प्राणी भवति नितरां कामरुपेण तुल्यः
प्राज्यराज्यं निरुपमगुणं प्राज्ञतास्वल्यता च।
कीर्न्तिः कोतिर्विपुल विलसतू शौर्यता भाग्यराषेः
किं किं तेषां भुवनतलयेः पदार्थो सर्वमेव।। 200 ।।

*** इतिश्री प्रद्युम्नचरित्रे श्रीसोमकीर्त्याचार्यविरचिते प्रद्युम्न तृतीयभवमणिभद्र, पूर्णभद्र, भववर्णनोनाम धर्माधर्म श्रवसौधर्म गमनो नाम सप्तमसर्गः***

अष्टमसर्गः

अर्थपूर्वं समाख्याता वर्णिता चातुरामया।
तस्यां श्री कोषलाभिख्यां सेवितायां सुरैरपि।। 01 ।।
पÁनाथ इति ख्यातो भूपः तत्र मनोहरः।
प्रतापतिर्ज्जितारातिः कीर्त्तिव्याप्त दिगंतरः।। 02।।
यथा स्वर्गेनराधीषः पातालेन्नगाधिपः।।
प्राज्यं राज्यं करोत्यत्र न्यायपालित भूतलः।। 03 ।।
तस्यासीत्सुन्दराकारा श्यामामंथरगामिनी।
नवयौवनसम्पन्ना सर्वावयवसुन्दरा।। 04 ।।
शचीवसुरराजस्य यथेषस्यपनगात्मजा।
प्रिया हि धारिणीनाम चेत्र श्चोरण तत्पराः।। 05 ।।
तसार्द्धं नराधीषष्चक्रे राज्यं मनोहरं।
यथा भागं भाथा सौख्यं पूर्वपुण्यप्रभावतः।। 06 ।।
कुर्वाणे तु तथा राज्यं भूपाले हि तया समं
मुतयुग्मं परं जातं च्युत्वा च त्रिदषालयात्।। 07 ।।
तस्याः कुक्षि समुद्भुतं सर्वलक्षण संयुतं।

पूर्वपुण्यभावेन लभ्यते चिन्तितं खलु।। 08 ।।
अद्योमधुरिति ख्यातो द्वितीयाः कैटभाभिधः।
महोत्सवोनरेन्द्रेण कृतः पुत्र समुद्‌भवे।। 09 ।।
रुपयौवन सम्पूर्णो सर्वलक्षण लक्षतौजातौ।
तौ यौवनारम्भे सर्वावयम सुन्दरौ।। 10 ।।
भूपतिर्योग्य सम्बन्धैः कुलरूपगुणोचितैः।
विलोक्यकन्यके रम्ये चक्रे पाणिग्रहं तयोः।। 11 ।।
एकदा भूपतिः तौ तु पुत्रौ वीक्ष्य मनोहरौ।
नवयौवन सम्पन्नौ चिन्तयामास मानसे।। 12 ।।
दुःप्राप्यं मानुषं जन्म कुलं चापि मनोहरं।
तत्रापि राज्यता नूनं दुस्प्राप्य प्राणिभिः ध्रुवं।। 13 ।।
पुत्रपौत्रसमायोगो राजाष्वस्यंदनादयः।
प्रतापः सूर्यताचापि प्राप्यते न कदाचन।। 14 ।।
जैनोधर्मस्तु तत्रापि पुण्य हीनैर्नलभ्यते।
तत्सर्वं हि मया प्राप्तं सौख्यं पुत्रादि संभवं।। 15 ।।
यद्यद्विलोक्यते नूनं संसारे प्राणधारिणां।
तत्सर्वं पुण्ययोगेन माया लब्धं मनोहरं।। 16 ।।
ममाधुनोचितं कर्त्तुं आत्मनो हितकारणं।
ये नाथ ते ध्रुवं मुक्तिः शाष्वतायुषकारिणी।। 17 ।।
विमृष्यैवं चिरं चित्ते दत्वा राज्यं सुतेग्रजे।
कैटभे युवराज्यं च सर्व सामन्त साक्षिकं।। 18 ।।
स्वश्रिये पदवीं सोपियतीनां शीलधारिणां।
गुरुणां चरणौ प्राप्य कृत्वालोचं सुभक्तितः।। 19 ।।
बहुभीराजपुत्रैष्च वैराग्य परिभूषितैः।
सहस्त्रणैव रमाणां त्यक्त्वा सर्व परिग्रहं।। 20 ।।
चक्राते परमं राज्यं कुमारौतौ क्रमागतं।
चन्द्राः क्वाविव लोकस्य यच्छन्तौ सौख्यमुत्तमं।। 21 ।।
प्रतापसूर्य वीर्यादि सद्‌गुणैः समलंकृतौ।
सखेव भृत्यलोकस्य प्रयातौ शरणार्थिनां।। 22 ।।

शत्रूणां चैव मित्राणां भूधराधिपमस्तके।
कृतपादौ विरेजाते प्रतापाक्रांत विष्टयौ।। 23 ।।
स्थितोन्यदा सभामध्ये राजा सामन्तमध्यगः।
कोलाहलं पुरस्यान्ते शुश्रुवान् सहसा मधुः।। 24 ।।
प्रपच्छ प्रतिहारं स किमेतद्विकलकलं।
अद्यप्रभृतिनो नूनं पुरे देषे श्रुतं मया।। 25 ।।
प्रतीहारोथ भूपालं जगाद विनयान्वित।
करयोः संपुटीकृत्य शृणुनाथ वचोमम।। 26 ।।
भूप भूपोस्ति भूपालो योदुर्ग बल संयुतः।
तेन विध्वंस्यते देषः त्वदीयः सर्वमेवहि।। 27 ।।
पशूनां तु मनुष्याणां धृत्वासोयाति प्रत्यहं।
ज्वालयित्वापरं देषं धाटीयोगेन भूपते।। 28 ।।
कदाचिद् गम्यते तस्य पृष्ठतोपि महाबलैः।
तदासौ दुर्गमाश्रित्य स्थित्वा गर्ज्जति निर्भयः।। 29 ।।
अयोध्यायाः पुरस्यापि सर्वं गृह्लाति बाह्यतः।
अतएव जवजनोनाथ कृतं कलं महत्।। 30 ।।
प्रतीहारवचः श्रुत्वा सभामध्ये महीपतिः।
प्रज्वालकोपदावेन भ्रूभंग कुटिलाननः।। 31 ।।
जगाद च कुलामात्यान् भो भो शृण्वन्तुमद्वच।
एतावत्दिनपर्यन्तं कथितं नो कथं मम।। 32 ।।
जगुरेव तदामात्याः शृणु भूप महीपते।
पापो दुर्गवलं प्राप्य दुर्ज्जयः सर्व भूभुजां।। 33 ।।
अस्माकम् पालनीयोसि बाल्यावस्था त्वं महीमते।
मधुराजा तदा पूर्वे वाक्यं शृण्वन्तु मामकं।। 34 ।।
नवीनः सविता किं तु नैषं नाषं तिनोत्तमः।
अतएव कथं नोक्तं भवदि्भः बुद्धि वर्ज्जितैः।। 35 ।।
मया भूरि बलेनामा गन्तव्यं तत्पुरे ध्रुवं।
विनाषयामि तत् दुर्गं घातयामिरिपुं शठं।। 36 ।।
इत्युक्त्वा पुनरपूर्वे मेलयं तु महद्बलं।

रणभेदी निनादेन मेलितं प्रबलं बलं।। 37 ।।
प्रचचाल महीपाल ततोपि बल संयुतः।
दन्तिदन्त समूहेन पापयन् पादपानुबहून।। 38 ।।
मार्गां श्वविषमी कुर्वेष्चक्रि चक्र समूहकैः।
वाजिनां खुरघातैष्च खण्डयन् पृथिवीधरान्।। 39 ।।
अग्रतोऽपिजलं येषां सैन्यकानाम गाधकं।
पृष्ठतोपि ततोः तेषां जातं पंकमयं तदा।।40 ।।
ये ये प्रदेषा विषमाजातास्ते ते समाः परं।
समस्तु विषमाता याति सैन्येथ मार्गजाः।। 41 ।।
प्रयाणक वषान्नूनं भूपो यातः पुरांति के ।
पुराधीषोथ संप्राप्तः श्रुत्वायातं नराधिपं।। 42 ।।
दृढ़भक्ति समायुक्तो योऽसौ हेमरथाह्वयं।
प्रणाम परमं चक्रे भूतले न्यूस्तमस्तकः।। 43 ।।
मधुनापि समालिंग्य प्रोक्तोऽसौ कुषलादिकं।
ततस्तं विनयात् नत्वा जगौ हेमरथोनृपः।। 44 ।।
प्रसादं कुरु हे नाथ सेवकोपरिचाधुना।
कुरुवेस्म पवित्रं मे रेणुना पादपÁयोः।। 45 ।।
मत्पुरे दिनमेकं हि तिष्ठ तिष्ठ कृपानिधे।
दृष्यतां सेवकस्यैव विभूतिं परमादरात्।। 46 ।।
आदरस्य विषेषेण तोषं याति न को नरः।
प्रतिपन्नं भू भुजा तत चागमनं तत्पुरं प्रति।। 47 ।।
मानितं भू भुजा ज्ञात्वा कनकाख्यरथोनृप।
अग्रतष्चलितो पूर्वं कर्त्तुं शोभां निजेपुरे।। 48 ।।
गत्वानिजपुरे सोपि शोभां चक्रे मनोहरां।
ध्वजैस्तु तोरणैष्चापि पुष्पाणां प्रकरेण च।। 49 ।।
वाजित्राणां निनादैष्च बन्दिनां जयजयारवैः।
महोत्सवेन चक्रेसौ प्रवेषमधु भूपतिः।। 50 ।।
निजेगृहे ततो नीत्वा कृत्वा रत्न चतुष्ककं।
स्थापयामास तत्रैव जात रूपस्य विष्टरे।। 51 ।।

तावत् हेमरथः प्रोचेराज्ञीं चन्द्रप्रभां प्रति।
देवि भूपं स्वयं गत्वा वर्द्धापय मृगेक्षणे।। 52 ।।
इंदुप्रभानृपं प्रोचे श्रृणुनाथ वचोमम।
दर्षनीयं न भूपानां यद्यद्वस्तु मनोहरां।। 53 ।।
तस्मिन् द्वष्टे हि भूपानां चेतष्चलिति निष्चितं।
अतोन्यां भामिनीं नीत्वा वर्द्धापय नराधिपं।। 54 ।।
राजाजगाद तां नारीं श्रृणुदेवि विचक्षणे।
त्वादृष्योस्यैव भूपस्य दास्यो वै वहवो गृहे।। 55 ।।
त्वयाचित्ते निजेभ्रान्तिः नैवकार्या शुभानने।
त्वयैवहि समागत्य वर्द्धाप्यो भूपतिः स्वयं।। 56 ।।
नृपाग्रह वषेना सौ नीत्वा स्थालं मनोहरं।
दध्येक्षतैः समायुक्तं पूरितां मौक्तिकैःवरैः।। 57 ।।
हेमस्पंदन वाक्येन नीत्वा श्रृंगारमुत्तमं।
राज्ञी तत्र समायाता यत्रासौमधु भूपति ।। 58 ।।
वर्द्धापयत् नराधीषं राज्ञी पत्या समं तदा।
विनयेन परं भक्त्या तन्दुलैः मोक्तिकैस्थास्ते।। 59 ।।
मधुर्विलोकयामास राज्ञीमिंदुप्रभां वरां।
सर्वलक्षणसंयुक्तां सर्वावयवसुन्दरां।। 60 ।।
चन्द्रप्रभां समालोक्य स्थितामग्रे मनोहरां।
मन्मथस्य च बाणौघैर्वेद्धो मधुमहीपतिः।। 61 ।।
चिन्तयामास चित्ते सौ किमेषा सागरात्मजा।
किमेषाषक्रपत्नी वा किमेषा शम्भुवल्लभा।। 62 ।।
रोहिणाचाथ चन्द्रस्य कामस्यरमणी रतिः।
यषसः कीर्त्तिरेवात्र किमेषा किं भवेदिह।। 63 ।।
किं लोकोक्तिरियं लोके चन्द्रः सागरसंभवः।
अस्याः कपोलदेषोत्थ स्वेद बिन्दुरयं ध्रुवं।। 64 ।।
चन्द्रेण कमलैष्चापि गजकुम्भैः तथैवहि।
मृगीभिष्च मरालीभिः वैधसा साधु निर्मिता।। 65 ।।
कथं वा निर्मिता विधाता सादृष्येन विवर्जिता।

यस्यारुपं च सौन्दर्य न भूतं न भविष्यतिः।। 66 ।।
बिद्धोमन्मथ बाणोधैः भूपालस्तंभितोभवत्।
मुनिवछलितोचात्र मुनिरेवं विचिंतयेत्।। 67 ।।
तस्यैव सफलं जन्मतस्यैव जीवितं प्रमा।
कृतार्थो भूतले सौ हि तस्य भाग्यादयो ननु।। 68 ।।
तस्यैवात्र महत्पुण्यं यत्कृतं तु पुरातनं।
यस्य गेहे मनोज्ञेयं वर्त्तते प्राणवल्लभा।। 69 ।।
इतिचिन्तयतस्तस्य वर्द्धाप्य स्वामिना सह।
तस्य चित्तं तु सा हृत्वा जगाम निजमन्दिरं।। 70 ।।
मुषिता छलतो वापि शून्यवच्च तदा भवत्।
तस्याविरह दुःखेन जाताष्चिन्ता तुरोमधुः।। 71 ।।
तत्र शय्यां समासाद्य पतित्वा सौ स्थिता नृपः।
न भुंजते न शेते सौ नैव जल्पति दुःखतः।। 72 ।।
तस्यैव तु मधोराज्ञः तत्रामात्याः समाययौ।
तेन दृष्ट्वाथसो ज्ञातो गुप्त वृत्या स्थितोपिहि।। 73 ।।
जगाद भूपतिं स्नेहात् कथं नाथे दृष्यं मनः।
पूर्ववन्निज भूषापि कथं नाथ धृता विभो।। 74 ।।
पूर्ववत् चेष्टितं भूप दृष्यते नैव साम्प्रतं।
किं वा दुष्ट रिपुः सोहि व्यथतैतव चेतसि।। 75 ।।
माकृथाः त्वं वृथा खेदं चित्ते च रिपु सम्भवं।
तवाग्रतो जयामीह क्षणे नैव शठं रिपुं।। 76 ।।
त्वयाम्लानमुखेजाते विभोषत्रुभयादिह।
चिन्तयिष्यन्ति सुभटाः कारणं निजमानसे।। 77 ।।
इत्यामात्यात्य वचः श्रुत्वा जगाद मधु भूपतिः।
आमात्य श्रृणु वाक्यं मे न तु दुःखं रिपूद्भवं।। 78 ।।
आमात्योपि ततः प्रोचे तर्हि किं कारणं विभो।
येन त्वं चिन्तया क्रान्तो वर्त्तते दुःखपूरितः। 79 ।।
राजामात्यं तदा प्राह श्रृणुमित्र षिरोमणे।
ममहेमरथस्यैव जायाया दुःखमत्कटं।। 80 ।।

यदा मया तु सादृष्टा रूपयौवन भूषिता।
तदादिमन्मथैनेह पीड्यते मम मानसं।। 81 ।।
इति भूपवचः श्रुत्वा जगाद सचिवाग्रणीः।
विरुपकं त्वयानाथ चिन्तितं निजमानसे।। 82 ।।
उभयत्र विरुद्धं हि निंद्यं कार्यं विचिंतितं।
अनेन चिंतितेनापि तवस्यादयषोध्रुवं।। 83 ।।
भटानां निवहोराजन व्यग्रचित्ते भविष्यति।
मनसापि न कर्त्तव्यं कार्यं विलोकनिंदितं।। 84 ।।
अथामात्यवचः श्रुत्वा मधुः वाक्यं जगाविदं।
अनयातु विनामात्य जीवाम्पेकक्षणं नहि।। 85 ।।
यैन केनाप्युपायेन प्राप्नोपि तां तथा कुरु।
यदि मे जीवितव्येन चेत्तवास्ति प्रयोजनं।। 86 ।।
राज्येनापि धनेनापि सैन्येनापि बलेन च।
विनानयानमेकार्यं सर्वस्वेनापि विद्यते।। 87 ।।
भूपं तत्र रतं ज्ञात्वा चिन्तयित्वा पुनः पुनः।
जगावेवं महीपालं धृत्वा कार्यं दृढं हृदि।। 88 ।।
समाधाय निजं चेतः शृणु वाक्यं विभोमम।
अधुनामु×चतां चिन्तां तस्याः प्रेम समुद्भवां।। 89 ।।
नृपाः श्रुत्वा तु तां चिन्तां पररामा समुद्भवां।
व्यग्रचित्ता भविष्यन्ति गमिष्यन्ति गृहं निजं।। 90 ।।
व्यग्रचित्ताः त्वया साद्धं समेष्यन्ति तदा तु किं।
अत एव त्वया मन्त्रो रक्षणीयो निजे हृदि।। 91 ।।
पश्चात्त विषितं कार्यं करिष्यामि न संषयं।
पूर्वं देहि रिपून् जेतु सामन्तानां बलेन हि।। 92 ।।
जितेवैरिणि सर्वं ते भविष्यन्ति न संषयं।
इति भूपोवचः श्रुत्वा का सचिवस्य मनोहरं।। 93 ।।
निजेचित्ते तदा धृत्वा कार्यसिद्धिं जगौ नृपः।
अवष्यं तु त्वया कार्यं कर्त्तव्यं सर्वथामम।। 94 ।।
अत्र मे देहि वाक्यं ते ततः स्वस्थोभवाम्यहं।

मन्त्रिणापि निजं वाक्यं दत्तं वै भूपतेस्तदा।। 95 ।।
स्वस्थो बभूव भूपाल श्रुत्वा वाक्यं मनोहरं।
सर्वसैन्येन संयुक्तो प्रोद्यतोगमनाय च।। 96 ।।
सचिवस्यो पराधेन चचाल नृपतिस्ततः।
हेमरथेन संयुक्तो युक्तः सैन्याखिलेन च।। 97 ।।
पातयत् नग शृंगाणि शोषयन् सरितः तथा।
किं वा सम्प्रापयन् शोपि विपनानां विषेषतः।। 98 ।।
अनेन विधिना सोपि सैन्येन महता युतः।
निषीथेथ समागत्य वेष्ठयाम्य स सत्पुरं।। 99 ।।
वाजित्राणां तु निर्धोषैः पुरे कलकलोभवत्।
लोकाः समाकुला जाता भयवेपित मूर्त्तयः।। 100 ।।
राजा कलकलं श्रुत्वा जगाद सचिवं प्रति।
कोलाहलं पुरेकोयं श्रुयतेनागरैः कृतः।। 101 ।।
सचिवोपिनृपं प्रोचे श्रुणु भीम नरेष्वर।
मधुराजा समायातः सैन्येन महतायुत।। 102 ।।
भीमोपि सचिवं प्रोचे मधुवाक्यं तु मावद्।
नास्तिकोपि नरो लोकेयस्त्वा याति ममोपरि।। 103 ।।
दृष्टं श्रृतं तदाकेन सिंहोपरि मृगावली।
कृतान्तो परिजीवाष्च पन्नगागरूडोपरि।। 104 ।।
आमात्योपि नृपं प्रोचे सत्यं नाथ ममागतः।
मधुभूपोपि सैन्येन वेष्ठयित्वा पुरं स्थिरः।। 105 ।।
प्रतोली तु पुरस्यैव दत्ता लौकैः भयातुरैः।
बहिःगर्ज्जति सैन्येन मधु भूपो बलान्वित।। 106 ।।
श्रुत्वा जगाद भीमोपि सचिवं गर्वसंयुतः।
नदेयामे पुरस्यैव प्रतोली पुरवासिभिः।। 107 ।।
वराके तु समायाते प्रतोली दीयते कथं।
युद्धं चाहं करिष्यामि बहिर्निसृत्यवेगतः।। 108 ।।
इत्युक्त्वा निर्ययोवेगात् सैन्येन महतायुतः।
भीमोपि सौवेग संयुक्तो पुरीबाह्यप्रचंडवाक्।। 109 ।।

निर्गतं तं नृपं दृष्ट्वाचाः तुरंगबलान्वितं।
सामत्तस्थौ महीपालो मधु संज्ञोमहावली।। 110 ।।
समुत्थितौ महासैन्यौ कर्त्तुं युद्धं तदौत्कटौ।
सुसन्नद्धौ महाटोपौ वीरौ शूरौमदोद्धतौ।। 111 ।।
वाजित्राणां तु निर्घोषैः बन्दिनां जय निःस्वनैः।
रथोघानां तु चीत्कारैः वाजिनां चापि हे षितै।। 112 ।।
वृंहितैः करिणानां हि भटानां चाट्टहासकैः।
धनुषांचापि विस्फालैः कर्णाभ्यां श्रूयतेनहि।। 113 ।।
कातराणां करात् तत्र पपाता युद्ध संचयं।
शूराणां तु शरीरै भूत तथा पुलक संचयः।। 114 ।।
चक्राते परमं युद्धं सैन्यौतौ वै वलोद्धतौ।
अन्योन्यं वलानोत्यातैः वधघातादिनिस्तथा।। 115 ।।
खड्गैः कुंतैस्तथा बाणैः शरैष्चकैष्चमुद्गरैः।
करपत्रैष्च नाराचेः भिन्दिपालैर्कषै ईलैः।। 116 ।।
शक्तिभिर्मुषलैः चैव भल्लकैष्चासि धेनुभिः।
लष्ठि मुष्ठि प्रहारैष्च जातं युद्धं तदोत्कटं।। 117 ।।
उल्लसत् चट्लै रम्यैः तरंगै रेव राजिभिः।
प्रस्फुरद्विमलैः शुभ्रैः फलैष्चामर संभवै।। 118 ।।
शस्त्राहत गजानां च निवहैरेवपर्वतैः।
तेषां कुम्भ स्थलाज्जातैः मोक्तिकै रेव मौक्तिकैः।। 119 ।।
पतिनां भटौघानां रत्नैः मुकुट सम्भवैः।
पतितैः गजपादौ घौस्तैरेवमकरैस्तथा।। 120 ।।
वाजिपाद मयैमत्स्यैः भट मस्तक कच्छपैः।
भटांत्रमालि सेवालै रुधिरोधै जलोत्करैः।। 121 ।।
एभिः तत्र पदार्थैष्च जातं सैन्य महार्णवं।
तत्रार्णव समेसैन्ये भटानां संक्षयो भवत्।। 122 ।।
पंचभिः कुलकं एवं विधे महत्युद्धे विजित्य भीम पार्थिव।
बंबध देव योगेण शत्रुं मधु महीपतेः।। 123 ।।
कृत्वा निजवषे शत्रुं सम्प्राप्य जयनिस्वनं।

अन्यदेषे तु मुक्तोऽसौ मधुना भीमभूपतिः।। 124 ।।
मुक्त्वात्र निज सामंतान् शक्तान् मुक्तान् कुलागतान्।
कृतार्थो मधुभूपालो जगामस्वां पुरीं प्रतिः।। 125 ।।
नानादेषोद्भवा भूपानानो उपायन संयुताः।
मार्गचागत्य मिलिता पुण्यान् मधु महीभुजः।। 126 ।।
स्थापितास्ते स्वदेषेषु कृत्वाबै निजषासने।
तदा तु सचिवं प्राहस्मरन् पूर्वकथान्तरं।। 127 ।।
मयावट पुरेवष्यं गन्तव्यं तु बलेन च ।
यत्रसावर्त्तते देवी ममचित्त हरापरा।। 128 ।।
तदा तु मन्त्रिणा ध्यातं विस्मृतं भूपतेर्नहि।
किं करोमि नृपोनूनं मोहार्त्तस्तां स्त्रियं प्रतिः।। 129 ।।
आमात्योऽसौ नृपं प्राह सत्यं वटपुरे विभो।
रुपैन्येनामा गमिष्यामिष्विंतां चेत्तसिमाकृथा।। 130 ।।
सचिवोथा जगावेवं सैन्याग्रगामिनं प्रति।
हित्वावटपुरं दूरे गन्तव्यं अयोध्यां प्रति।। 131 ।।
इत्युक्ते सकलं नीत्वा सैन्यं भूप समन्वितं।
रात्रौ हि त्वातु तन्मार्गं सा ययौ कोषलां पुरीं।। 132 ।।
आगच्छन्तं नृपं श्रुत्वा पुरी लोकास्तदाखिलाः।
पुर्याः शोभां परां चक्रः तोरणादि सुकेतनैः।। 133 ।।
आपनानि च सर्वाणि भूषितान्यखिलान्य च।
पुष्पैराच्छादितामार्गा भूपस्या गमने जनै।। 134 ।।
उपायनैष्च विविधैः सन्मुखो हि जनोखिलः।
मिलितस्तस्य भूपस्य जयलक्ष्मायुतस्यहि।। 135 ।।
तदा भूपतिना ज्ञात्वा पुरीया कोषला ननु।
विषमादं परं चित्ते चक्रेसौचाति दुर्ज्जयं।। 136 ।।
उन्मतोऽसौ जनैः युक्तो जगाद सचिवं प्रति।
किमेतच्च त्वयामूढकृतं दुष्चरितुं मम।। 137 ।।
येनवटपुरं हि नत्वा चात्रानीतो दुरात्मना।
वंचितोसि महापाप त्वया वितथ वादिना।। 138 ।।

सैन्याग्रिमं समाहूय जगाद सचिवाग्रणीः।
कथं त्वया समानीतं मार्गं त्यक्त्वा बलंनिजं।। 139 ।।
सैन्याग्रणीः ततः प्राह श्रृणु स्वामिन् वचौमम।
सर्वर्यामंधकारेण मार्गोज्ञातो मयानहि।। 140 ।।
अजानता मयानाथ सैन्यानीतमिहाधुना।
क्षमस्व दुर्णयं मेहियत् चाज्ञान वषाकृतं।। 141 ।।
महोत्सवेन भूपो सौ चिन्ताव्याकुल मानसः।
जयशब्देन संयुक्तो विवेषनिजमन्दिरं।। 142 ।।
समागतं नृपं दृष्ट्वा स्त्रियौपि प्रमुदान्विता।
गीतनृत्यादिकं चक्रुः महोत्सव पुरस्सरं।। 143 ।।
मंगलानां शतानीह चक्रुस्ता वरयोषितः।।
तत्सर्वं रुथिनान्यस्य शून्यस्य भूपते ध्रुवं।। 144 ।।
आसनानि विभूषाष्च शयनान्यस्सनान्यथ।
पानानिविविधानीह गंधमाल्यादिकानि चं।। 145 ।।
नवयौवन सम्पूर्णा सर्वलक्षण लक्षिताः।
हावभाव विलासादि विभ्रमैः परिमंडिताः।। 146 ।।
उन्नतैः कुचक्रुंभैष्च नम्रास्ता विनयान्विताः।
सर्वमेतत् नृपस्या भूद्विष तुल्यं वियोगतः।। 147 ।।
आमात्योथ नृपस्या तेन आयातीह कदाचना।
उपालंभ भयात् नूनं गेहे तिष्टति सर्वदा।। 148 ।।
चिंताया नृपतिर्ज्जातो दुर्बलो रोगपीडितः।
क्वचित् न लभते सैख्यं कामज्वर समाकुलाः।। 149 ।।
अत्रान्तरे समायातो वसन्तोरितु नायकः।
कुर्वन्निच नरेन्द्रस्य क्षते क्षारस्य सेचने।। 150 ।।

प्रकटानु वनं जाता माकंदानां तु म×जरी

पुष्पतास्तु कदम्बानां श्रेणयोवै वने वने।। 151 ।।
अषोका वकुलाष्चापि ये ये हि तरूजातयः।
पुष्पतास्क्त यथा योग्यं वसन्त समयेवरे।। 152 ।।
सरोजानि तडागेषु सेवितानि मधुव्रतैः।

छात्रतुल्या विराजंते जिगीर्षोर्मन्मथस्य च।। 153 ।।
कोकिला कूजितं यत् च सएवमरूजध्वनिः।
भ्रमराणां तु झंकारास्ता एवं गीतनिस्वनाः।। 154 ।।
मलयाचल संबंधी मरुदेव गुरुः स्मृतः।।
ते नैव नर्त्तिताः सर्वाः राजा ते वनराजयः ।। 155 ।।
न तत्र तरवो तेहियेचिताः कुसुमैः नहि।
तानि पुष्णाणि नाभूवन् सेवतानि न षट्पदैः ।। 156 ।।
एवं विधे वसंतेपि व्याप्यमाने शुवस्तलं।
राजाकामस्य बाणेधैः सर्वैरेवहिताडितः।। 157 ।।
तारहार समूहैष्वघनसारैः सरोजकैः
कदलीदव वातैष्चताल वृतैः तथैवहि।। 158 ।।
चन्दनैष्चन्द्रज्योत्स्नाभिरन्यैः शीतोपचारकैः।
तापो न चास्य भूपस्य गतोयत् न शतैरपि।। 159 ।।
ऊषधानि विचिषणि सरोजानि तथैवचा।
कातर्तिरह तप्तस्य किं किं न विषतांगतं।। 160 ।।
विरहानलतापेन सततं भूपतौः तदा।
परिवार जनः सर्वषोकेन पीडितो भवत्।। 161 ।।
तथापि नागतो मन्त्री पार्ष्व तस्य महीभृतः।
जलं चान्नं मुमोचासौ भूपति परिहार्दितः ।। 162 ।।
एकदाथ महीपालो मुक्तो भूमौ निजैः जनैः।
केनापि कथितं तस्य वृतान्त सचिवस्यहि।। 163 ।।
तत् वृतान्तं समाकर्ण्य मन्त्री तत्र समागतः।
यत्रासौ भूपतिः सुप्तो वर्त्तते दुःख विक्लवः।। 164 ।।
नमस्कृत्य महीपालमग्रेसौ सचिवाग्रणी।
निविष्टो विनयाद्यार्वत्तावद् दृष्टो महीभृताः ।। 165 ।।
कंठे धृत्वा तु बाहुभ्यां जगाद सचिव नृपः।
समाधिस्ते कथं वत्समृतेमयि भविष्यतिः।। 166 ।।
चिन्तां कर्त्तुं तदा लग्नो मंत्रिमुख्यो विचक्षणः।
किं करोभि क्व गच्छामि क्व पृच्छामि वदामि किं।। 167 ।।

यदि हेमरथस्यैव प्रियामिंदुप्रभाछल्यां।
अनयामि यदा नूनं मया शस्यान्महीपतेः।। 168 ।।
नानयामिच तां तन्वी नवयौवन भूषितां।
तदा स्यात् भरणं वास्य भूमिपष्यन संषयः।। 169 ।।
उभयत्र विरुद्धं हि कार्यं किं तु करोम्यहं।
चिरमेवं विमृष्यासौ चिंतयामि सचीपरं ।। 170 ।।
सर्वेथैव मया कार्यं कार्यं वास्यमहीभृतः ।
अस्मिन् विनष्टे सर्वंहि ममकार्यं विनष्यति।। 171 ।।
येन केनापि उपायेन सा नेतव्या मया ध्रुवं ।
विमृष्यैवं चिरं भूपं जगाद सचिवाग्रणीः ।। 172 ।।
स्वस्थो भव महीपाल त्यजदुःखं निजं विभो।
आनयामि च तां नूनं नव मानसवासिनीं।। 173 ।।
एतावद्दिनपर्यतं विमृष्टं तु मया ह्रदि।
विमृष्यति महीपालो राज्ञी हेमरस्यहि।। 174 ।।
न विस्मृता त्वयानाथ सा तथापि मृगेक्षणा।।
तया विना महद् विध्नं दृष्यते तव साम्प्रतं।। 175 ।।
विमृष्टं तु मया चित्ते कार्यं कार्यं महीभृतः।
यषो वा यष एवास्तु सहिष्ये सर्वमेवहि।। 176 ।।
परं स्वस्थतयानाथ स्थातव्यं च त्वया ध्रुवं।
कार्यं स्वस्थतया नूनं सर्वं भवति शोभनां।। 177 ।।
तेन वाक्येन सन्तुष्टो जातो राजा स्व मानसे।
दुःखं तु सकलं त्यक्तं यच्च विरहं संभवं।। 178 ।।
आमात्योपि विचित्यैवं कार्यं सिद्ध महीपतेः।।
सर्वत्र विष्टपे दूतान् विससर्ज्ज विचक्षण।। 179 ।।
ययेसंत महीपाला महीभूपस्य शासने स ।
कलत्रैष्च तैः सर्वै रागन्तव्यं तु वेगतः।। 180 ।।
रमिष्यति ध्रुवं राजा वसन्तं सुमहोत्सवं ।
नारीभिष्च वने गत्वास कलत्रैर्नराधिपैः ।। 181 ।।
शासनं नृप चन्द्रस्य कृत्वा षिरसि भूमिपाः ।।

सकलत्राः समायाताः सर्वेहर्ष समन्विताः।। 182 ।।
ततो हेमरथस्यापि दूतस्तेन विसर्ज्जितः।
पत्रं तु परमं नीत्वा प्रेमाक्षर समन्वितं।। 183 ।।
वाचयित्वा स्वयं लेखं ततो हेमरथो नृपः।
प्रमुदं परम गत्वा जायायैतन्निवेदयत्।। 184 ।।
पश्य पश्य प्रिये नूनं पत्रं मधु महीभृता।
मम भक्त्याति तुष्टेन प्रेषितं प्रेम पूर्वकं।। 185 ।।
वाचयस्व स्वयं देवि पत्रं नीत्वा निजेकरे।
तयातुवाचितं तत् च प्रेषितं मधु भूभुजा।। 186 ।।
किं किं तु लिखितं तत्र कथ्यते तत् च साम्प्रतं।
अयोध्याया महीपेन प्रेषितं मधुनादरात्।। 187 ।।
श्रीमद् वटपुरे रम्ये हेमचक्रांग भू भुजां।
कुशलप्रष्न पूर्वं तु कृत्वादौ प्रोच्यतेधुना।। 188 ।।
तवभक्त्यास्मि तुष्टोहं त्वं मे मित्रं न संषयः।
त्व तुल्यो वैमदीये तु राज्ये ना वर्त्ततेपरः।। 189 ।।
यत् च राज्यं मदीयं हि जानीहि तत्तवैवहि।
अन्तरं नैव कर्त्तव्यं त्वयात्रैव मया सह।। 190 ।।
एवं ज्ञात्वा निजे चित्ते धृत्वा प्रीतिं ममोपरि।
आगन्तव्यं त्वया वष्यं सार्द्धनीत्वा निजां प्रियां ।। 191 ।।
वसन्तस्य वरां क्रीड़ां वने गत्वा महोत्सवैः ।।
मासमेकं करिष्यामि राजपुत्रैः समंमुदा।। 192 ।।
तदर्थं तु समायाताः सकलत्रा महीभृतः ।
नीत्वा त्व इन्दुप्रभां नारीमागन्तव्यं त्वया ध्रुवं।। 193 ।।
इन्दुप्रभा नृपं प्रोचे श्रृणुनाथ वचोमम।
अत्यादरोपिनोयुक्तो भूपानां सेवकं प्रति।। 194 ।।
अतएव त्वया नाथ गन्तव्यं मां विना विभो।
हरिष्यति ध्रुवं राजा दृष्ट्वातु मां समागतां ।। 195 ।।
राजाजगाद हे मूढे किं वा जल्यसिगर्हितं।
त्व तुल्यास्य भूपस्य सन्तिदास्यः सहस्त्रषः ।। 196 ।।

तदा जगाद सा पत्नी राजानं तु विचक्षणाः ।
ज्ञास्यसि त्वं महीपाल यद्यत्तवभविष्यति।। 197 ।।
राजा प्राचे वचः स्मित्वा भव्यं भद्रे भविष्यति।
आगन्तव्यं मयासार्द्धं त्वयावष्यं मृगेक्षणे।। 198 ।।
महीपालोपि तां नीत्वा परिवार समन्वितः।
जगाम वेग युक्तो सौषकुनैर्वारितोप्यतः।। 199 ।।
समागतं नृपं ज्ञात्वा स्वयं मधु महीपतिः।
सन्मुखं परिवारेण जगाम विनयान्वितः।। 200 ।।
स्नेहैनाति समालिंग्य कुषलप्रष्न पूर्वकं।
मुस्थान के तस्य निवासस्य गृहं ददौ। 201
तोषयामास तं भूपः सन्मानैर्भाजनादिभिः।
अपरेषां तु सर्वेषां सन्मानं प्रददौ नृपः ।। 202 ।।
समायातैस्तु भूपालैर्वनं श्रृंगारयत् नृपः।
वचनाय महीपानां मायया किं न साध्यते।। 203 ।।
मत्त कोकिल नादेन झंकृतैष्च मधुकृतां।
कृत शौभं पुरायत् च वासितं पुष्परेणुभिः ।। 204

कृतकै र्भूधरै रम्यं सिन्दूरादि समुद्भवैः।
सुगन्ध रजसा कीं संकीर्णं वन सम्पदा।। 205 ।।
हरिचन्दन पंकेन कपूरै कुंकुमादिभिः।
सुगन्ध वस्तु पूर्णानां दीर्घिकानां शतैर्युतं।। 206 ।
तोरणैर्विविधैर्युक्तं क्षौमका×चन सम्भवैः।
एवं नाना विधैर्भेदै र्भूषितं वनमुत्तमं।। 207 ।।
श्रृंगारित वनं श्रृत्वा राजास्वान्तः पुरान्वितः।
भूपालै सकलत्रैष्च जगाम क्रीडितं मुदा।। 208 ।।
लतानां पल्लवै रम्यैः पुष्पानां पतनैस्तथा।

झंकृतैर्मधुकाराणां कोकिलानां तु निः स्वनैः।। 209 ।।

मंजरीभिः समायुक्तैः सहकारैर्बद्ध कुडलैः।

वनं भूपे समायाते दन्तार्धमि वचाभवत्।। 210 ।।

वने मधु महीपाल क्रीडां चक्रे मनोहरां।

भृत्वा तु जलयन्त्राणां जलैः कुंकमवासितैः।। 211 ।।

वारांगणा समूहेनरममाणोपि भूपतिः।

मनागपि सुखं लेन भूपोपि विराहार्द्धितः।। 212 ।।

अन्ये ये ये महीपाला नाराभिः सहितावने।

क्रीडां विविध भेदैष्च चक्रुस्तेवै मनोहरां।। 213 ।।

मासमेकं नरेन्द्रोऽसौ वसन्तसमयेवरे।

वने क्रीडां परां चक्रे र्सवरोधजनोभृषं।। 214 ।।

रमित्वा तु वने राजा महोत्सव समन्वितः।

पुरमध्येसमागत्य सौस्किृतो निजमन्दिरे।। 215 ।।

राजकंपरितोष्यासौ वस्त्र वाहन भूषणैः।

सकलत्रं विषेषेण विसर्ज्जित अतिवेगतः।। 216 ।।

ततो हेमरथं प्राह श्रृणु मित्र वचो मम।

साम्प्रतं युवयोःयोग्यं भूषणं वर्त्तते नहि।। 217 ।।

व्रजत्व मधुना वत्स निजेदेषेतिवेगतः।

विनासयंति देषे वै रिपवो नायकोष्णितं।। 218 ।।

त्वया संतोषितो वत्स त्व ग्रामेहं समागतः।

अधुना युवयोः योग्यं ददामि भूषणादिकं।। 219 ।।

इन्दुप्रभाभिधां राज्ञीं मुक्त्वा याहि नरेष्वर।

पृष्टतः प्रेषयामीति दत्वा भूषणमुत्तमे ।। 220 ।।

त्वत्तुल्यं त्वत्प्रियातुल्यं भूषणं साम्प्रतं नहि।

कुर्वन्तु हेमकरास्तु योग्यान्याभरणानि च।। 221 ।।

तथास्त्विति भनित्वासौ नमस्कृत्य नरेष्वरं।

निजनारी समीपोसौ ययौ हेमरथो नृपः।। 222 ।।

जगाद वल्लभां भूपः श्रृणुदेवि वचोमम।

गच्छामि स्वपुरेचाहं भुक्त्वा त्वां चात्र वल्लभे।। 223 ।।

सौविदलैस्तथा वृद्धैः समंमुक्त्वा व्रजाम्यहं।

आगन्तव्यं त्वया देवि नीत्वा वैभूषणादिकं।। 224 ।।

प्रेषितोस्मिनृपेनाहं स्थापितासि च त्वं प्रिये।

मधुनाप्रेम युक्तेन भक्त्या तुष्ठेन पूर्वया।। 225 ।।

अतएवात्र तिष्ठत्वं देविचातोव्रजाम्यहं।

इति भूप वचः श्रुत्वा राज्ञी दुःखातुराजगौ ।। 226 ।।

तव भाग्य वषेनात्र प्रेरितोसिनराधिपः।

मु×चयित्वा तु मां शून्यामेको याति गृहे निजे।। 227 ।।

जानिहित्वं निजे चित्ते स्थापितास्मिगृहे निजे।

कृत्वात्राहं कलत्रं हि नृपेण मधुनाधुना।। 228 ।।

भूपो जगाद हे मूढ़े माकृथेति वचोह्रदि।

मधोर्नो ताद्वषं चित्तं यादृषं वर्त्तते तव।। 229 ।।

प्रीतिमान् मधुभूपोसौ वर्त्तते मयि सांप्रतं।

विःपकं तु चेतोस्यनैव दृष्ट मया प्रिये।। 230 ।।

अतएव सुखं धृत्वा तिष्ठात्र चिंतयोष्भिता।

आगन्तव्यं त्वया शीघ्रं ममैवपृष्टतः प्रिये।। 231 ।।

तयोक्तं श्रृणु हे नाथ ज्ञास्यसि त्वं स्वयं ह्रदि।

मधोच्च तव प्रीतेष्चफलैर्व्यक्तिः भविष्यति।। 232 ।।

वारितोपि तया चैवं बहुधा वचनेः वरैः।

मुक्त्वात्विंदुप्रभां नारीं ययौ हेमरथोनृपः।। 233 ।।

शकुनैर्वार्य मानोपि प्रययौमूढ़धीर्नृपः।

अवश्यंभावि भावानां प्रतीकारो न विद्यते।। 234 ।।

गतेहेमरथे भूपे यज्जातं तन्निगद्यते।

मधुराजा जगावेवं मन्त्रिणं प्रतिमोहतः।। 235 ।।

आनीयता द्रुतं वत्स प्रेयषीं प्राणवल्लभां।

ततोमन्त्री नृपः प्रोचे तिष्ठ तिष्ठ क्षणं विभो।। 236 ।।

यावत् रात्रिः समायाति तावत्तिष्ठ महीपते।

तेन वाक्येन तुष्टोसौसुखं तस्थौ महीपतिः।। 237 ।।

अन्तरेत्रदिनेषोपि वीक्ष्यभूपं सुदुःखितः।

मन्दं मन्दं यथा वस्थं कृपया तस्य भूपतेः।। 238 ।।

चक्रवाकमय युग्मं वियोगं चापिलम्भयन्

संकोचयन् सरोजानां पोषयन् कामिनां तथा।। 239 ।।

पष्चिमाषां तथा रक्तां कुर्वंष्चास्तं ययौरविः।

सन्ध्यातु प×चवर्णां हि दध्रेरागं नभों गणे।। 240 ।।

यच्चसूर्य भयान् नष्टं प्रविष्ठं गिरिगâरो।

निसृतं तच्च निःषंकं कालं प्राप्य निजं तमः।। 241 ।।

निम्नं तथोन्नतं चैवचलं वाप्यचलं तथा।

प्रा×चलं विषमं चात्रवर्णं नाना विधं परं।। 242 ।।

सर्वं समं तदा जातमंधकार समुद्‌ठमे।

यथातिनिंदितेभूपे सदृषं तु शुभाषुभं।। 243 ।।

आकाशे प्रकटो जातस्ततोवैतारका गणः।

इन्द्रनीलमनैर्भूम्यां मालतो प्रकरो यथा। 244 ।।

केतकी कुसुमाकार निजपांडुर ज्योत्स्नया।

धवलं भूतलं कुर्वनुदयाय निषाकरः।। 245 ।।

बाध्यमानं जगद्वीक्ष्य तमसाचन्द्र भूमिपः।

वाणानिव किरणौ धानु विससर्ज्जहितावहः।। 246 ।।

निषायाः प्रथमे यामेधौते विष्वेथ ज्योत्स्नया।

आमात्य वचसा भूपोदूतीं तिप्राहिनोन्निजा।। 247 ।।

हेमरथम्य जायाया समीपं दूतिका च सा।

गत्वा कृत प्रणामं च जगाद वचनं वरं।। 248 ।।

सावधानतया देवि वाक्यं श्रृणुमदीयकं।

मधुना भूमिपालेन यदुक्तं सुन्दरं वचः।। 249 ।।

कल्थयस्वात्र तद्वाक्यं यच्च भूपतिनोदितं।

इत्युक्ते दूतिका प्रोचे विनयेन समन्विता।। 250 ।।

मार्गात् च तव नाथेन दूतोवैप्रेषितोधुना।

समीपं मधुभूपस्य प्रेम पूरित चेतसा।। 251 ।।

प्रेषणीया त्वया नाथ मज्जाया मम पृष्ठतः।

भूषयित्वा तु श्रृंगारैर्यदि स्नेहोममोपरि।। 252 ।।

तेनवाक्येन राजापि त्वामाकारयति ध्रुवं।

दास्यति निजनारीणां भूषणानि महीपति।। 253 ।।

तव नाथ समीपे हि प्रभाते प्रेषयिष्यति।

आगच्छ त्वं द्रुतं वत्से सोधगृहं महभृतः।। 254 ।।

तेन वाक्येन सा चित्ते चिन्तां कर्त्तुं समुद्यता।

यदि गेहं गमिष्यामि मधु भूपस्य साम्प्रतं।। 255 ।।

करिष्यति कलत्रं हि माम् भूपोनात्र संषयः।

नो गमिष्ये यदा भूपस्तदा क्रोधं करिष्यति।। 256 ।।

निस्वस्य च मृगाक्षी सा सौ विदल्लैः समन्विता।

जगाम च तया सार्द्धं तस्य भूपस्य मन्दिरं।। 257 ।।

तावत् च सप्तमीं भूमिमारुह्यनृपति स्थितः।

स्थापयित्वा त्वधोभागे तस्याः यस्यिजनं च तं।। 258 ।।

इन्दुप्रभां भिधां देवीं निनायोपरिभूमिकां।

मेलयित्वा नृपस्यैव जगाम दूतिका गृहं।। 259 ।।

एकान्ते तु स्थितं भूपं दृष्ट्वा राज्ञी विचक्षणा।

चिन्तया कुलिता जाता कम्पमान शरीरिका।। 260 ।।

न किंचिद्वचनं प्रोचे लज्जयातं महीपतिं।

षिज्योपरि नृपस्तावत्निन्येतां स्वकरेण हि।। 261 ।।

नीत्वा तां सुन्दरां देवीं चाटूभिः वचनैः शुभैः।

परिहास कथाभिष्च प्रोचे वासौ निचक्षणः।। 262 ।।

सौम्यतां भज देवि त्वं प्रसन्ना भव साम्प्रतं।

क्रियते वा त्वया नूनं हर्ष स्थाने कथं शुचः।। 263 ।।

यस्तुहेमरथोराजा ममैवानुचरः स च।

नीचतां तु निराकृत्य जाता मे प्राण वल्लभा।। 264 ।।

अतएव त्वयानन्दः कर्त्तव्यो निजमानसे।

श्रुत्वा भूप वचसापि प्रोवाचैव महीपतिं।। 265 ।।

इदंत्वया महीपाल प्रारब्धं विष्व निन्दितं।

केनक्वापि कदा दृष्टा वाटी भक्षति कर्करी।। 266 ।।

परंरामा जगत् निंद्या त्याज्या नूनं मनीषिभिः।

वंच्योनैव कुलस्त्रीभिः निजनाथः कदाचनः।। 267।।

एवं नाना विधैर्वाक्ये र्वोधितोपि महीपतिः।

मन्मथस्य शरैर्विद्धौलग्नोरन्तुं तु तां तदा।। 268 ।।

कूजितैर्हसितैष्चापि चुंवितैविःतैरतैः।

रे मे भूपतिना देवी लोचनां चतनिरिक्षणैः।। 269 ।।

वलानैः क्व नितैष्वासौ हाव भावै मनोहरैः।

गीतनृत्य कथाभिष्च रंजयामास भूपति।। 270 ।।

सुरतोत्सवरागैष्च गाथा दोहा कथादिभिः।

विनोदैर्विविधैः कृत्वा रेमे तां भामिनीं नृपः।। 271 ।।

स्थापिता सा निजं गेहं मोहाद्भूपतिनामुदा।

प्राप्यतां मनसोभीष्टां मेनेराज्य तु सार्थकं।। 272 ।।

चन्दना गुःपंकोधै वासिते दीर्घिकाजलि।

तया समं परां चक्रे राजा क्रीडां मनोहरां।। 273 ।।

नानावनविहारैष्च दोलांदोलनकैस्तथा।

रे मे तया समं भूपदा वनादि विधानतः।। 274 ।।

जग्मतुर्नगतं कालं निमग्नौ सुख सागरे।

कृताग्र महिषी तेन मधुनेन्दुप्रभाभिधा।। 275 ।।

अथये मन्त्रिणो मुक्त्वास्तेन हेमरथेनहि।

सौविदल्लौस्तथातैष्च गत्वा वट पुरे द्रुतं।। 276 ।।

हेमरथ नरेद्राय तद् वृत्तान्तं निरूपितं।

श्रुत्वा हेमरथो राजा दूता तां प्राणवल्लभां।। 277 ।।

मूर्छय कुलितो भूत्वा पपात क्षितिमंडले

लोकैः शीतोपचारैष्च बोधितोऽसौक्षणे नहि।। 278 ।।

संज्ञामाप्य नृपश्वासौ क्रोधेना:णलोचनः।

जगाद सचिवानेवं सज्जातां सज्जतां बलं।। 279 ।।

वात्वायोध्यां पुरीं शीघ्रं जित्वामधु नराधिपं।

आनयामीह वेगेन नूनं मे प्राणवल्लभां।। 280 ।।

तदामात्यादिभि प्रोक्तं नैव गन्तुं प्रयुज्यते।

मधुभूपोति बलवान् त्वयाजेत्वं न शक्यते।। 281 ।।

आमात्यानां वचः श्रुत्वा भूपेन हृदि चिंतितं।

सत्य मधुमहीपालो दुःसाध्यो मम सर्वथा।। 282 ।।

संचिंत्यैवं चिरं चित्ते दिर्घ निष्वस्य दुःखतः।

कामग्रह वसेनासौ विकलो भून्नराधिपः।। 283 ।।

शून्योवैसतेष्वेरं समोहंयाति मन्दिरं।

सभायां पुःनरागत्य स्वयं गायति रोदति।। 284 ।।

किंचित् चिन्तति चित्ते सौपुनर्याति गृहान्तरे।

गवाक्षं पुनरा:ह्य शून्यं पश्यति सर्वतः।। 285 ।।

प्रियाहीनं गृहं दृष्ट्वा मुक्तकंठे :रोदसः।

हा प्रिये दयितेहेति हा हा मे प्राणवल्लभे।। 286 ।।

मत्प्रसादवषेनैव त्वं हृता तेन पापिना।

किं करोमि क्व गच्छामि कं पृष्टवामि वदामि किं।। 287 ।।

एवं नानाविधैर्वाक्यैः कदाचित् विलपंत्यसौ।

एकाकी पुरमध्येतु भ्रमते गार्ग्पयोगतः।। 288 ।।

दुष्टकाम पिषाचेन विवषा भ्रमतिमेदिनीं।

त्यक्त्वा राज्यं निजं सर्वं एकाकी षिषुभिःवृतः।। 289 ।।

हा प्रियेति कृता रावो वनेतुःवरेतथा।

वस्त्रवेषविहीनोसौ नित्यं भ्रमति मूढ़धीः।। 290 ।।

धूलिधूसर गात्रोसौ कोलकेषो गतत्विषः।

जीर्णवस्त्र समूहस्य स्कन्धे धारित कंथकः।। 291

प्रतिपुरं प्रतिरथ्यं च भ्रमन्मार्ग्रवषादषौ ।

कोसलां देवयोगेन समायातोति मोहितः।। 292 ।।

तत्रनारीकन्दवं सो दृष्ट्वा धावति सत्वरं।

हे हे इन्दुप्रभे तिष्ठ तिष्ठेति कृतरावकः।। 293 ।।

तावत् नारीजनैः सोपि ताड्यते पाषाणादिभिः।

पलायते पुनदूरं कृता कृन्दोतिवेगतः।। 294 ।।

धावतननुजनं कृन्दं ताड्यते सौ जनैर्जनैः।

प्रतिपुरं प्रतिरथ्यं भ्रमत्येवं नराधिपः।। 295 ।।

वल्लभामा द्वयन्नुच्चै :Ppju~ धावयन् यदा।

गवाक्ष्य स्थितया तावदृष्टोधात्रिकयाप्यसौ। 296 ।।

हेमरथं नराधीषमुपलक्ष्य तथा विधं।

तद् दुःखेन शमाक्रान्ता विलापमकरोद्भृषं।। 297 ।।

तामकांडे समालोक्य कुर्वंतीपरिदेवनं।

जगाविं दुप्रभाचैवं तस्या दुःखेनदुःखिता।। 298 ।।

कथय स्व द्रुतंमात परिभूतासि केन वा।

प्रस्तावेन विना नूनं रोदनं क्रियते कथं।। 299 ।।

जगाद धात्रिकां चैवं न किंचत् कारणं परं।

अत्याग्रहं चकारासौ राज्ञीचैवां य पुनः।। 300 ।।

कथयामास वृन्तान्तं गद्गद स्वरभाषिणी।

त्वद् वियोगेन संज्ञातं गर्गं हेमरथं नृपं।। 301 ।।

अवस्थया समाकीर्णं षिषुभिः परिवेष्टतं।

दृष्ट्वा तु :दितं वत्से तस्य दुःखेन पीडिता।। 302 ।।

राज्ञी चाश्रुतपूर्णं सा श्रुत्वा वाक्यं तयोदितं।

जगादकोप सम्पूर्णा युक्त मुक्तं न चाम्बिके।। 303 ।।

ईदृष्यं कटुकं वाक्यं मम दुःख विधायकं।

युज्यते तव वक्तुं किं विस्मृतं स्मर्यतेकथम्।। 304 ।।

यादृषी दासिका नूनं तादृषेवनचान्यथा।

अन्यथा विस्मृतं दुःखं स्मार्यते वा कथं खले।। 305 ।।

मातस्तुल्यासि मे नूनं तादृषेवनचान्यथा।

अन्यथा हितवानिष्टं महत् च क्रियते मया।। 306 ।।

पार्वनेदुमुखो नूनं तरलाक्षः सुंदराकृतिः।

दीर्घातिपीवर भुजो :पेण जित मन्मथः।। 307 ।।

अन्यैर्भूपतिभिः तस्यादेषः षिरसिधार्यते।

एवं विधोहि मे भर्त्ता त्वयावै निंद्यते कथं।। 308 ।।

एवं दुर्वचनं राज्ञी जल्यंनीतु यदा श्रुता।

तदाधात्रि कया चित्ते चिंचितं कारणं परं।। 309 ।।

इयं चाग्रेपि मे नूनं तापं तुदुवै करिष्यति ।

तस्मात्संदेह नाषाय दर्षयामि नृपंचतं।। 310 ।।

चिन्तयित्वा तु तां प्राह धात्रिका चतुरावचः।

दर्षयामिधुना वत्से पर्तिते सुंदराकृतिम्।। 311 ।।

प्रोक्तं हि इन्दुप्रभया दर्षयत्वं ममांक्किे।

एतास्मिन्नंतरे चा सौगवाक्ष्यधः समागतः।। 312 ।।

तावद्धात्रिकाया तस्या दर्षितोसौकुवेषभाक्।

उपलक्षय वत्से त्वं गत्यालक्षण चेष्टितैः।। 313 ।।

लक्षणैष्चेष्टितैर्ज्ञातस्तथा हेमरथो नृपः।

हा प्रिये दयिते हेतिकृता क्रन्दः पदे पदे।। 314 ।।

एवं विधं च ते दृष्ट्वा राज्ञी शोकभराकुला।

चिन्तां कर्त्तुं तदालग्नात दुःखेनातिदुःखिताः।। 315 ।।

धिक्ये तु जीवितं नूनं पापाहं पापपूरिता।

मद्वियोगवषेनायं जातो दुःखी नराधिपः।। 316 ।।

मयातु भुज्यते सौख्यं मधुना सहसांप्रतं।

धिगावतारो नारीणां सदा पर वषात्मनां।। 317 ।।

एवं चिंता कुलायावद्राज्ञी वासगृहे स्थिता।

तावत्तत्र समायातो भूपालोमधुसंज्ञिकः ।। 318 ।।

सन्मुखं मा समुत्थाय दृढ़ दुःखेन दुखिता।

कराभ्यां करकं नीत्वा ददावाचमनंवरं।। 319 ।।

पूर्वं वत्कृतके नैव स्नेहगौरवसंयुतां।

तां च नीत्वा नरेन्द्रोपि सौधस्यः षिखरं गतः।। 320 ।।

तत्रासौ शारदीषोभां वीक्ष्यमानो महीपतिः।

देव्या सह स्थितो याचत्तावदन्यत् कथान्तरम्।। 321 ।।

दृढ़बद्धं नरं नीत्वा चंडकर्म्मातिवेगतः।

आगत्य भूपतिं नत्वा प्रोवाच वचनं वरं।। 322 ।।

श्रृणु देव महाराज पुरुषोयं यौवनान्वितः।

पररामा निषेवीतु समानीतस्त्वदंतिकम्।। 323 ।।

अस्यदोषाऽनुमानेनवदंडं नराधिपः।

इत्युक्त्वा चंडकर्म्मापि तूष्णीं कृत्वा स्थितो यदा।। 324 ।।

नरेन्द्रोपि तथा प्रोचे कोपसथन्न मानसः।

चंडकर्म्मन् द्रुतं गत्वा शूलिकारोपणं कुरू।। 325 ।।

न तु दोषवर्त्तां वार्त्ता नृपाणामग्रतः कथं।

पापाद्वैभीत चिन्तानां क्रियते च विवेकिभिः।। 326 ।।

देवीभूपवचः श्रुत्वा गूढ़ कोपेन संयुता।

जगाद विनयं कृत्वा श्रृणुनाथ वचो मम।। 327 ।।

अयं तु रूपसंयुक्तो यौवनेन समन्वितः।

कथं वा हन्यते नाथ किमनेन कृतं विभो।। 328 ।।

राजापि कामिनीं प्राह श्रृणु देवी विचक्षणे।

अनेन पररामाया गमनं पापिना कृतं।। 329 ।।

तस्माद्वैचाऽस्य पापस्य वधैव नचापरं।

ततोराज्ञी नृपं प्राह स्मित्वाति विनयेन च ।। 330 ।।

गमनेपररामायाः किमत्र पातकं विभो।

रूपयौवन सम्पन्नो ये नायं हन्यते नरः।। 331 ।।

विस्मृव्यापि निजं कर्मं राजाथ भामिनी जगौ।

श्रृणु देवि महाभाग्ये नास्ति पापमतः परं।। 332 ।।

पुनः इन्दुप्रभा प्रोचे चात्र पापं न दृष्यते।

शास्त्र मार्ग वषात् राजा प्रोवाच वचनं पुनः।। 333 ।।

परस्त्री गमने नूनं देवद्रव्यस्य भक्षणे।

सप्तमं नरकं यांति प्राणिनोनात्र संषयः।। 334 ।।

एकतः सर्वपायानि परसमा तथैकतः।

इति वाक्य वषाद्देविं नास्ति पापमतः परं।। 335 ।।

इहलोकेअपयषः परत्रनरकं ध्रुवं।

नृपादिभ्यो वधं दंडं पररामाततस्त्यजेत्।। 336 ।।

भुक्तोच्छिष्टावुधै निंद्य धनधान्य विनाषिनी।

पापखानिः कलेर्मूलं पररामा परित्यजेत्।। 337 ।।

एवं भूपवचः श्रुत्वा राज्ञी वाक्यं जगोपरं।

परस्त्री हरणेनाथ पातकं यदि विद्यते।। 338 ।।

तदा त्वया कथं नाथ दूताहं परभामिनी।

पुण्यापुण्य विचारं च यदि जानासि भूयते।। 339 ।।

न त्वया परिणीताहमनूढाया चितानहि।

मत्पितौर्मंदिरंगत्वा हृताहं तु विभोकथं।। 340 ।।

तदा मधुमहीपाल श्रुत्वावैंदुप्रभंवच।

वैराग्यं परमं गत्वा चिन्तयामासमंनसे।। 341 ।।

ययौ निंद्यकरं कर्मं मया पापेन किं कृतम्।

हरणं पररामाया नैव युक्त सुधर्मिणां।। 342 ।।

जानन्नप्यखिलं कर्म धर्माधर्मादिकं फलम्।

पापमोह वषेनैव प्राप्तोहं अन्धनाकथं।। 343 ।।

नासत्यसत्यतमेति नाधर्मंधर्मतां तथा।

अतएव हिनोकार्यंकार्यं निंद्यं सुधीमता।। 344 ।।

निंद्यद्वारेण संभूतं निंध स्थाने व्यवस्थितं।

मातुरूदरालं संवृद्धं निंद्यद्वारेण निश्रृतम्।। 345 ।।

सप्तधातुमयं नूनं चर्म बद्धास्थिजालकम्।

तत् शरीरं परं दृष्ट्वा मोहोवै क्रियते कथम्।। 346 ।।

इद्रजालसमं सर्वं संसारस्य विचेष्टितं।

जानन्नपि कथं मूढ़ो मोहमेतिकथं नरः।। 347 ।।

मदीयेभवने किं न सन्ति रामामनोरमाः।

पररामाभिलाषं किं कृतं पापवतामया।। 348 ।।

यादृषं तु कृतं कर्मं फल प्राप्तं तु तादृषं।

वाप्यते यादृषं बींज भुज्यते तादृषं ननु।। 349 ।।

रूपयौवन सम्पन्नाः पीनोन्नत पयोधराः।

मनश्चोरण कारिण्यः किं न सन्ति प्रियामम।। 350 ।।

येनेदं कुत्सितं कर्मं कृतं मोहवषान्मया।

नरकनेत्ता मोहोमोहः संसार कारणम्।। 351।।

धनं धान्यं तथा नारी यौवनं विषया बलं।

बान्धवाःपुत्र मित्राणि न स्थिरं जीवितं तथा। 352 ।।

एवं वैराग्यमापन्नः संसारसार वर्ज्जितं।

चिंतय निद्य चित्तेसौ भोग सौख्यपराङ्दुःखः।। 353 ।।

मोचयित्वा नरं तं तु यावद्गेहे स्थितो निजे।

तावत् तत्र समायाता आहारार्थं मुनीष्वरः।। 354 ।।

राजमन्दिरमायातं दृष्ट्वा तं मुनिनायकं।

राजा तया समं वेगात् सन्मुखं तु ययौ मुदा।। 355 ।।

त्रिः परीत्यमयाभक्त्या तिष्ठ तिष्ठेति सद्वचः।

जगाद वचनं राजा प्राश्रुकं वर्त्तते जलं।। 356 ।।

मुनेस्त्वाचमनं दत्वा निवेष्यै वा शने शुभे।

प्रक्षाल्यचरणौ भावाद्वचंदेचरणोदकं।। 357 ।।

पादयोःअर्चनं कृत्वा वन्दनां तु तथैवच।

मनसा वचसा नत्वा चक्रे शुद्धिं नराधिपः।। 358।।

तयोविंदुप्रभा भार्य सार्द्धं श्रीमुनयेमुदा।

प्रत्याख्यानस्य मुक्तिं च कृत्वा दानं ददौ नृपः।। 359 ।।

भक्त्या परमयायुक्ताः प्रकारैर्नवभिस्तथा।

पुण्यस्योपार्ज्जनं चक्रे तया सह नराधिपः।। 360 ।।

अन्तराय विनिर्मुक्तो मुनिना पराणे कृते।

अक्षयं दानमित्युक्त्वादत्ताषीर्वादः मुनिना तदा।। 361 ।।

तेन दान फलेनैव चित्रपंचकमापस।

भावेन क्रियते यच्चतत्सर्वं सफलं भवेत्।। 362 ।।

मुनिन्द्रोपितमाहारं नीत्वा चासोवनेगतः।

ध्यानाध्ययन संयुक्तो निर्मम सर्व वस्तुषु।। 363 ।।

तत्रैव ध्यानयोगेन कृत्वा घातिक्षयं महत्।

सुरासुरानुतं दिव्यं केवलं ज्ञानमापसः।। 364 ।।

तं निषम्य महीपालो वनपाल मुरवातुक्तं।

आनंदभेरी नादेन बोधयित्वाखिलं जनं।। 365

भावेन राजमारूह्य जगाम वंदितुं मुनिं।

पौरलोकौष्च संयुक्तस्तथा परिजनान्वितः।। 366 ।।

राजचिन्हं परित्यक्त्वा दृष्ट्वाथ दूरतो मुनिं।

वेगान्नागात्समुत्तीर्यन नाम मुनिनायकम्।। 367 ।।

धर्मवृद्धिः मुनीन्द्रेण दत्तास्मै भूमिपालतु।

भूतले विनयेनैव निविष्टो मधु भूपति।। 368 ।।

करकु×जल संयोज्य प्रपच्छ पृथिवीपतिः।

जिनधर्मं समाख्याहि कृपां कृत्वा ममोपरि।। 369 ।।

मुनीन्द्रोपि ततः प्रोचे शृणु भूप महीपते।

जिनस्य दषधा धर्मं कथयामि समासतः।। 370 ।।

यस्य धर्म प्रभावेन स्वर्ग मोक्ष समुद्भवम्।

सुखं न भुविनां दूरे का कथाचापरस्य हि।। 371 ।।

सम्यक्त्वा पूर्वकं धर्मं द्वादषैव व्रतानि च।

एतत् सर्वे महाभक्त्या पालनीयं मनीषिभिः।। 372 ।।

ज्ञात्वां संसारयं वृत्तमसारं दुःखदायिनं।

जिनेन्द्र वदनोद्भूतं कर्त्तव्यं धर्म सर्वथा।। 373 ।।

धनं धान्यं तथा कोषो रत्नानि विविधानि च।

नारीपुत्रकुटम्बौधान साराण्ययरण्यपि। 374 ।।

जातरूपधराणां हि पदवीं परमांश्रितः।

याचाग्रमहिषी तस्य तया दीक्षा समाश्रिता।। 375 ।।

श्रुत्वैवं मधुपालो वै वैराग्यं परमं गतः।

निजाग्रजे सुते राज्यं नियोज्य विधिपूर्वकं।। 376 ।।

भूपानुजो भुवि ख्यातोयः कैटभ समाह्वयं।

जिनेन्द्रस्य व्रतं तेनगृहीतं जाययासमम्।। 377 ।।

उभाभ्यां तु परिभ्रष्टा तदात्विंदुप्रभाभिधा।

तया दीक्षा जिनेन्द्रस्य गृहीता चाति भक्तितः।। 378 ।।

चक्रुरुग्रं तस्तेपि वैराग्या ह्दचेतसः।

पेठुः शास्त्राणि जैनानि गुरुभक्ति परायणः।। 379 ।।

शास्त्र सागर पारं ते संप्राप्यपुर पुण्यतः।

समाधिमृतयो भूत्वा जाताः सर्वे सुरालये।। 380 ।।

इन्दुप्रभाभिधाया हि सा गत्वात्रिदषालये।

भुक्त्वा पुरातनं पुण्यं अच्युत्वामलिन कर्मतः।। 381।।

विजयार्द्ध गिरौ रम्ये नगरे गिरिपत्तने हरि।

नाम महीपोस्ति तस्य हरिवतीप्रिया ।। 382 ।।

ततोच्युतो सुखं भुक्त्वा मधुभूपसमंतु सा।

आयुरंतेथच्युत्वा भूत्तस्य भूपस्य देहजा।। 383 ।।

मेघकूट पुरे रम्येकालसंवर भूपति।

तस्य जाया तु सा जाता नाम्नाया कनकस्रजा।। 384 ।।

यस्तुमधु महीपालो गतौवैषोडषेदिवि।

भुक्त्वा सुखानि दिव्यानिष्ठुत्वा साचायुषः क्षये।। 385।।

द्वारावत्यां हरेर्ज्जातो रुक्मिण्यास्तनु संभवः।

पूर्व पुण्यानुभावैन यादवानां कुलेवरे।। 386 ।।

यस्तु कैटभ को नाम तत्रास्ति तस्य चानुजः।

हरेस्तनुस्तुसौभावी जाम्बवत्यं गर्भ संभव।। 387 ।।

यस्तु हेमरथो राजा ह्रति जायोति दुःखतः।

मृत्वा भ्रांत्वा चिरं कालं संसारं दुःख सागरे।। 388 ।।

नीचयोनिषुवं भूम्य तपत्वासौ कुतपष्चिरं।

धूमकेतुर्रिति विख्यातो बभूवासुरनायकः।। 389 ।।

सचैकदा विमानस्थो वभ्रमन्निजलीलया।

दैवयोगात्समायाते निषिथे द्वारिकोपरि।। 390 ।।

बालकोपरिगच्छन्तं विमानं चास्यखीलितं।

कुज्ञानेन तु संज्ञातं वृत्तान्तं तेनचाखिलं।। 391 ।।

ज्ञात्वाजहेथ दैत्योसौ जाया हरण कोपतः।

वैरं केनापि कर्त्तव्यं नैवातः कारणात् नृपः।। 392 ।।

वैरं दुःखाकरं लोके वैरं धर्म विनाषकं।

वैरेण जंतवोयांति रौरवेघारेवेदने।। 393 ।।

एवं वैरस्य सम्बन्धं ज्ञात्वा जीवैर्विचक्षणैः।

वैरं हि सर्वथा त्याज्यं वैरं संसार कारणम्।। 394 ।।

जैनोदितं वचः श्रुत्वा सर्वेचक्रधरादयः।

परस्परं तदाचक्रुः शांतितेसर्व जन्तुभिः।। 395 ।।

श्रुत्वा वाक्यं जिनेन्द्रस्य नारदो हर्षपूरितः।

तीर्थराजं नमस्कृत्य करकोषाद्विनिर्गतः।। 396।।

विजयार्द्ध नगे वेगात् गत्वा प्रेमानुबन्धतः।

मेघकूटपरं प्राप्य बालका लोकनेच्छया।। 397 ।।

कालसंवर नामास्ति तत्र राजा मनोहरः।

सभान्तरे ततस्तस्य संप्राप्तो नारदोमुनिः।। 398 ।।

तेनापि नारदं दृष्ट्वा सहसोत्थायाति भक्तितः।।

अर्घपाद्यादि दानैष्च मानितोसौ पुनः पुनः।। 399 ।।

आषीर्वादं ततो दत्वा निविष्टो विष्टरेवरे।

प्रेमानुबंधनीं वार्त्तां चक्रे चासौनृपेन चः।। 400 ।।

तत्रस्थित्वा क्षणंचासौ नृपं प्रोचेवचोवरं।

आलोकितुं ते सोद्धांतं ममेच्छा वर्त्तते नृपः।। 401 ।।

राजा जगाद हे स्वामिन् गम्यतां गम्यतां द्रुतं।

पवित्रयगृहं नाथस्व पाद पÁरेणुना।। 402 ।।

इत्युक्ते राज भवनं जगाम वेगतोमुनिः।

रुक्मिण्या तनु भूतस्य प्रमोदादी क्षणेच्छया।। 403 ।।

समागतं मुनिं दृष्ट्वा राज्ञी सा कनकस्रजा।

अर्घपाद्यादिकं चक्रे भक्त्या त्वांसनपूर्वकं।। 404 ।।

क्षणंस्थित्वा मुनिं प्राह राज्ञीं नारद सन्मुनिः।

गूढ़गर्भ तया पुत्रः त्वया जातोमया श्रुतः।। 405 ।।

साजगाद च हे नाथ तव पाद प्रसादतः।

तद्दर्षय द्रुतं देवि सुतं ते मे सुखाकरं।। 406 ।।

यया पुत्रः समानीय पातितस्तस्य पादयो।

तेन दृष्ट्वाथ तं बालं माषीभिरभिनंदितम्।। 407 ।।

चिरंजीव चिरंनंद सुखी भव त्वमर्भकः।

पित्रोन्सुखाषिखा कृत्वा पूरनीया मनोरथाः।। 408 ।।

भव्योयं देवि पुत्रस्ते भव्य लक्षण संयुतः।

त्वया जायोति पुण्येन चिरंजीवी भव त्वयं।। 409 ।।

इत्युक्त्वा तं समालोक्य बालं वेगाद्विनिर्गतः।

नारदो द्वारिकां प्राप्य रुक्मिणी सदनं ययौ।। 410 ।।

मिलित्वा चातिहर्षेण पूर्वं तु मधु सूदनं।

रुक्मिण्यग्रततः प्रोक्तं श्री सीमंधर भाषितं।। 411 ।।

स्थानं भवांतराणीह वयो रुपं च लक्षणान्।

तदा गमन कालोऽपि चिÉानि तत् समागमे।। 412 ।।

समागमं समं लाभैर्विद्याभ्यां तु तथैवचः।

सर्वं जिनोदितं तस्यै कथयित्वाथ नारदः।। 413 ।।

हर्ष युक्तां तु वां कृत्वा रुक्मिणीं सुत वार्त्तया।

निजं यथोचितं स्थानं ययौ नारद सन्मुनि।। 414 ।।

पुत्रस्यागमनं श्रुत्वा रुक्मिणी प्रीतिमानसा।

स्थिता नारद वाक्येन संस्मरन्ती तदागमम्।। 415 ।।

इत्थं जीवो विविध गतिभिः सौख्य दुःखदि योगैः

नाना योनौ भ्रामति च सदाकर्मपाषेन बद्धः।

तस्तात् कार्यं स्वहित निरतैः स्वर्ग मोक्षस्य कर्त्ता

जैनोधर्मो विमल मतिभिः सोमवत् निर्मलोयः।। 416 ।।

***इत्याचार्यश्रीसोमकीर्त्तिविरचिते प्रद्युम्नचरिते प्रद्युम्नपूर्वभवकीर्त्तनोनाम**

अष्टम सर्गः। *

नवमसर्गः

अथ खेटगृहे रम्ये बालोसौ पूर्व पुण्यतः।

जतनेत्र मनोहारो ववृधेसोमवच्छनैः।। 01 ।।

नारीणां हि नराणां हि मन शांतस्करोभवत्।

कराच्चकरसंचारं प्राप्य सौभाग्य भूषितः।। 02 ।।

यथा यथाप्यसौबालो वृद्धिं याति नृपोगृहे।

रिद्धिं वृद्धिं धनं धान्यं वृद्धिं याति तथा तथा।। 03 ।।

मातुः प्राणिप्रियष्चाभू पस्याप्यति वल्लभः।

सौभाग्यं च प्रियत्वं च पूर्व पुण्य प्रभावतः।। 04 ।।

अनेन विधिना सोपि बालत्वमतिक्रम्य च ।

क्रमाद्दैयौवनं प्राप्य मन्मथो मानवर्ज्जितः।। 05 ।।

शस्त्र शास्त्र प्रवीनो भूत् कलागुण विषारदः।

महासाहस सम्पन्नो धीरोवीर गुणाग्रणीः।। 06 ।।

बलगर्व समायुक्ता महासाधन संयुताः।।

शत्रवोये समायांति भूपोपरि बलोद्धताः।। 07 ।।

जगाय मदनः सर्वान् स्वयं वध्यारणाजिरे।

कांदिसीका कृता वेगात्पुण्यतो जीयते ध्रुवं।। 08 ।।

आगतां स्व रिपून् जित्वा नीत्वा कीर्त्तिं तदोद्कलां ।

ययौदग्विजयं कर्त्तुं नीत्वा साधनमुत्तमम्। 09 ।।

ये ये शूरा रणेधीराः खेचराबलषालिनः।

तेषां देषे जगामासौ मदनो बल संयुतः।। 10 ।।

रिपूष्च सकलान् जित्वा कृत्वा दिग्विजयं तदा।

आजगाम महाभूत्वा मदनोसौ निजंपुरं।। 11 ।।

कालसंवरभूपेन श्रुत्वा जातं सुतोत्तमम्।

श्रृंगारितं महभूत्या पुरं विविध केतुभिः।। 12 ।।

महोत्सवेन नगरे प्रवेषस्तस्य कारितः।

मदनः पितरं दृष्ट्वान् नाम विनयेन च ।। 13 ।।

कालसंवरभूपोपि तनयं जयभूषितं।

दृष्ट्वा तु चिन्तयामास प्रमोद परिपूरितः।। 14 ।।

मयास्मैतु पुरादत्तं युवराज पदं वने।

ददामि साम्प्रतं तत्च सर्वलोक समक्षिक।। 15।।

सुमुहूर्त शुभेयोगे भूमिपानां कदम्बकं।

मेलयित्वा नृपः प्रोचे श्रृणुपुत्र वचोममः।। 16 ।।

यदा त्वं हि वने जातो जनन्या गूढ़गर्भया।

युवराज्यं मयातुभ्यं दत्तं तुष्टेन दर्षनान्।। 17 ।।

अधुना सर्वलोकानां समक्षं दीयते मया।

त्वं गृहान प्रमोदेन प्राप्यं वैभाग्य योगतः।। 18 ।।

गृहीतं युवराज्यं तु तातादेष विधायना।

मदनेन प्रमोदेन राज्यं स्यात् कस्य न प्रियं।। 19 ।।

वित्तीर्णं प्रचुरं वित्तं तदा चार्थिजनायवै।

बान्धवानां तथान्येषां पूरितास्तु मनोरथाः।। 20 ।।

मदनस्य तदा चाभूद्यषः सर्वत्रविष्टपे।

मनोभवमयी जाता कथा तत्र तुरेवरे।। 21 ।।

वर्तन्ते तस्य भूपस्य नारीणां शतपंचकम्।

जातास्ताभ्यस्तु प्रत्येकां पुत्रा विद्याविषारदाः।। 22 ।।

पुत्रास्ते निज मातृणां प्रत्यहं पदवन्दनम्।

प्रभात समये नूनं कुर्वन्ति विनया ह्वता।। 23 ।।

सर्वास्ता मातरः पुत्रान् प्रोचुः क्रोधन पूरिताः।

किं कुपुत्रैर्वृथा जातैर्भवf : शक्ति वर्ज्जितैः।। 24 ।।

एकेन तेन दुष्टेन जाति हीनेन पापिना।

नीतं तु भवतां राज्यं वृथा किं जीवितेनवः।। 25 ।।

सर्वेसंभूय वेगेण मारयं तु छलेनहि।

अस्मिन् स्थिते भवतां नन किंचिदपि वर्त्तते।। 26 ।।

मातृणां मानसो वार्त्तां ते सर्वेखगनंदनाः।

ज्ञात्वा तु निष्चयं चक्रुर्हतव्योस्माभिरेवहि।। 27।।

करिष्यामोवयं नूनं भव्यं तासां वचोड्डुतं।

इत्युक्त्वा चरणौ नत्वा मातृभ्यस्ते विनिर्गताः।। 28 ।।

सर्वे ते दुष्ट चित्तावैमार्यया मदनस्य च।

आगत्य मिलितास्तूर्ण भूत्वा तु प्रीति मानसाः।। 29 ।।

भोजने शयने चापि खाने पाने तथैव च।

स पातु विष सन्मिश्रं कृत्वा ते दुर्दुरात्मकाः।। 30 ।।

सर्वं विषमयं तस्य जातं चामृतवत् तदा।

पूर्व पुण्य प्रभावेन सर्वं सुखाकरं भवेत्।। 31 ।।

यदा ते चलितं किंचित् तस्यतैष्चाषुभंपरं।

तदा ते कुपिताः सर्वे समं=य निजमानसे।। 32 ।।

विजयार्द्धगिरेर्भूर्द्धिन वज्रदंष्ट्र पुरस्सराः।

तं निन्युर्वेगतो दुष्टा विष्वस्तं मदनं वरम्।। 33।।

तत्र गत्वातु तैर्दृष्टं जिनेन्द्र भवनं शुभम्।

ष्शरदभ्र समाकारं मुखत्रय विराजितं।। 34 ।।

सहस्त्र षिखरं रम्यं रत्न कांचनर्निर्मितम्।

तस्य मध्येतुतैर्गत्वा वंदितो जिननायकः।। 35 ।।

जिनेन्द्रः परयाभक्त्या वंदितो खेचरात्मजैः।

ततो बाह्ये विनिर्गत्य चैत्यद्वारे स्थिता यदा।। 36 ।।

तत्र स्थितैष्वतैर्दृष्टं गोपुरं षिखरे गिरेः।

तदावज्र मुखो भानृनू जगाद दुष्ट धीर्वचः।। 37 ।।

श्रुणुं तु भ्रातरः सर्वे मदीयंवचनं शुभं।

सौख्यदं राज्यदं चैव यदुक्तं पूर्वखेचरै।। 38 ।।

गोपुरस्यास्य मध्येहि गोविषेत्पुरुषोत्तमः।

सम्प्राप्यचिंतितार्थं सक्षेमेनाया वेगतः।। 39।।

वृद्धानां वर्त्तते वाक्यं खेचराणां कुलेनिजे।

यूयमत्रैव तिष्ठंतु तस्मात् गच्छाम्यहं द्रुतं।। 40 ।।

वज्रदंष्ट्र वचः श्रुत्वा जगाद मदनोवली।

गच्छामि तव वाक्येन यदिस्यात् च कृपामम।। 41 ।।

जगौ कुलिषदंष्टोपि मदनं कुटिलाषयः।

व्रजवत्स द्रुतं तत्र कथयामि तवात्रकिम्।। 42 ।।

तेन वाक्येन तुष्टोसौ मदनो कुटिलाषयः।

जगाम बलवान् शीघ्रं गोपुरं निजगेहवत्।। 43 ।।

अधिरुत्घातिवेगेण मध्ये गत्वा मनोभवः।

बुवापातंघनं कृत्वा पद्भ्यांधुं फणिकां ददौ।। 44 ।।

तेन शब्देन बुद्धो सौ तत्क्षणे भुजगासुरं।

जगाद क्रोध भारेण दीप्यमान शरीरकः।। 45 ।।

रे रे पाप दुराचारा रे रे वैमानुषाधम।

मम देव ममः स्थानमपवित्रं कथं कृतम्।। 46 ।।

त्वया किं न श्रुतं पूर्वं मदीयं भुवनेखिले।

विख्यातं जन वृंदस्य घातकं दृष्टिमात्रतः।। 47 ।।

प्रतारितोसिकेनापियेनात्रत्व समागतः।

तदासौमदनः प्रोचे श्रृणु वाक्यं सुरोधमः।। 48 ।।

किं गर्जसे वृथा मूढ कुरू युद्धं मयासह।

सूराणां कातराणां तु व्यक्तस्ते दर्षयाम्यहं।। 49 ।।

इत्युक्ते च वलेसोपि विवुधोमदनं प्रति।

परस्परं तु सौ सूरौचक्रतुर्युद्धमुत्कटं।। 50 ।।

वलानैस्तर्ज्जनैष्चापि चपेटा मुष्ठिभिस्तथा।

चिरं युद्धं कृतं तेन सुरेण बल शालिना।। 51 ।।

मदनेन जितो युद्धेयदासौ सुरनायकः।

तदापि पादयोः नत्वा जगाद मनंदेप्रति।। 52 ।।

श्रृणुनाथ महाभाग्यतवास्मि किंकरोध्रुवं।

त्वं मदीयोपि नाथोसि कृपां कुरू ममोपरि।। 53 ।।

सिंहासनं तदा दत्तं मदनस्य सुरेण च।

उपविष्य मदनः प्रोचे श्रृणुदै महाबलः।। 54 ।।

कोसित्वं वा किमर्थं वा स्थियोसि गिरिगàवरे।

तदा दैत्योपि तं प्रोचे विनयानत विग्रहः।। 55 ।।

श्रृणुनाथ वचो रम्यं मदीयं सत्य मिश्रितं।

चिरकालं स्थितो येन त्वदर्थं गिरिगâरे ।। 56 ।।

अत्रैव च गिरौनाथालंकारपुरमुत्तमं।

प्रसिद्धं भुवने यत् च समृद्धजन संकुलं।। 57 ।।

कनकनाभिरित्याख्यो नृपोभूद्गुण सागरः।

अनिलेति प्रियातस्य सतीव्रत धुरंधरा।। 58 ।।

सुखेन कुर्वतोराज्यं पतिपत्न्यौ यथेच्छया।

नविंदत गतं कालं निमग्नौरति सागरे।। 59 ।।

एकदात्रिदिवाच्युत्वातयोः पुत्रोति सुन्दरः।

हिरण्योनाभ संजातो गुणवांस्त्रिदषोयमः।। 60 ।।

राजा राज्यं चिरं कृत्वा सुखं भुक्त्वा निरन्तरम्।

च×चलां कमलां ज्ञात्वा योवनं क्षणभंगुरूं।। 61।।

विषयेषुविरक्तात्मा वैराग्येण विभूषितः।

पुत्रास्यापि निजं दत्वा राज्यं परिच्छदान्वितं।। 62 ।।

वनेगत्वातिभावेन पिहिताश्रवसन्निधिं।

प्राणिपत्यपरं भक्त्या दीक्षां दैगम्बरींश्रितः।। 63 ।।

कुलकं द्वादषांगानि चाधीत्य तपत्वाघोरतरं तपः।

केवल ज्ञानमुत्पाद्य कृत्वा घाति क्षयं महत्।। 64 ।।

भव्यराषीष्च संबोध्य मुक्ति श्री सदनं गतः।

सिद्धानामाश्रयं यत्र परातीतमुखालयं।। 65 ।।

हिरण्योनाम भूपोसौ चक्रे राज्यं निरन्तरं।

कंटकै रहितं रम्यं शत्रुभिः परिवर्ज्जितं।। 66 ।।

एकदासौनृपो पश्यत् प्रासादषिखरे स्थितः।

दैत्यराजं महासैन्यं विभूत्यापरयान्वितं।। 67 ।।

तं दैत्य सम्पदं दृष्ट्वा चिन्तयामास मानसे।

अनेनविधिना हीनं धिग्धिग्मे राज्य सम्पदं।। 68 ।।

साध्यामि परां विद्यां राज्य विभवदायिनीं।

चिन्तयित्वा चिरं चित्ते ददौ राज्यं निजोनुजे।। 69 ।।

स्वयं सिद्धवनं गत्वा तपस्तप्तुं समुद्यतः।

साधयामास सद्विद्यां गुरूणा प्रतिपादितां।। 70 ।।

रोहिण्याद्यथ सद्विद्यासाधयित्वा तु पुण्यतः।

प्रमोदं परमं प्राप्यसोत्सवैः मंदिरं गतः।। 71 ।।

अनुजेन तदा दत्तं चक्रे राज्यं निरंकुषः।

विद्याभिः साधितार्थं तु देवराज समं नृपः।। 72 ।।

चिरकालं सुखं भुक्त्वा कृत्वा राज्यं निरंकुषः।

असारंचापिसंसारं ज्ञात्वा वैराग्यमागतः।। 73 ।।

निजपुत्रस्य राज्यं स दत्वा सर्वधनान्वितं।

वैराग्येण च संप्राप्य नेमिनाथ सभान्तरं।। 74 ।।

नत्वा नेमिजिनं भक्त्या कृत्वा तु करकुड्मलं।

विलयेन जगाचेवं श्रृणुनाथ वचो मम।। 75 ।।

असारं खलु संसारं विभोज्ञातं मया ध्रुवं।

तस्मात् देह जगन्नाथ व्रत संसार नाषनं।। 76 ।।

इत्युक्ते नमिनाप्रोक्तं भव्यं चित्तेतु चिंतितं।

नत्वा भाग्यवतां पुंसा दीक्षास्याद्वी जिनोदि।। 77 ।।

दीक्षाग्रहण समये विद्यायाष्च गणोपितं।

जगाद विनयं कृत्वा निजकारणमुत्तमं।। 78 ।।

त्वया तु नीयते दीक्षा श्रीजिनेष्वर भाषितं।

वयं कथं भविष्यामि निनाथानाथ कथ्यतां।। 79 ।।

हिरण्योपि च तद्वाक्यं श्रुत्वा प्रोचे जिनेष्वरं।

कथय स्व विभो नूनं कथमेतद्भविष्यति।। 80 ।।

कोस्य विद्यागुणस्यैव भविष्यति विभोयतिः।

कथयस्व कृपां कृत्वा ममोपरि जिनेष्वर।। 81 ।।

नेमिनाथेन तत्रोक्तं शृणु वत्स वचोमम।

अस्य स्वामी तु यो भावी कथयामि तवाग्रतः।। 82 ।।

तीर्थे श्रीनेमिनाथस्य हरिवंष षिरोमणे।

द्वारिकायाः पति श्रीमान्विष्णुर्नामा भविष्यति।। 83 ।।

तस्य श्री रुक्मिणीनामा भामिनी गुण गामिनी।

तस्या जठर संभूतो मदनाख्यो महाबली।। 84 ।।

भविष्यति महापुण्या पुण्यवान् गुण भूषितः।

अस्य स्वामी तु सो भावी सम्येत्यमणिगोपुरे।। 85 ।।

बलवान् विक्रमीधीरो गंभीरो रुपवान् गुणी।

इति जैनं वचः श्रुत्वा हिरण्योमां जगाविति।। 86 ।।

गर्ववान् सबलोमानी समेत्यमनिगोपुरं।

संह्यतेथ युद्धायसवः स्वामी भविष्यति।। 87 ।।

मंत्रगणत्वया गत्वा स्थातव्यं तत्रगोपुरे।

इत्युक्त्वाथ हिरण्योसौ दीक्षां दैगंबरीश्रितः।। 88 ।।

पठित्वाथ तपस्तपत्वा केवल ज्ञानमप्यसः।

घातिकर्म क्षयं कृत्वा निर्वानं परमां गतिः।। 89 ।।

अत्रागत्य स्थितोहं वैरक्षयन् मंत्र मंडलं।

त्वदर्थे हे महाभाग तस्य वाक्य वषेन हि।। 90 ।।

मंत्रगणं गृहाणेन निंधिं कोषं तथैव च।

महान्कालो विभोजातो ममात्रैव स्थितस्य हि।। 91 ।।

मुकुटं रत्न निर्मानं तथैवाभरणानि च।

दत्वा संपूज्य मदनं जगौ मंत्रगणस्तथा।। 92 ।।

यस्तु श्रीनेमिनाथेन प्रोक्तुः स्वामीत्वामेवहि। – प्रथमोलाभः

तवास्मि किंकरोनाथ वद किं करवाणिति।। 93 ।।

इत्युक्तेमदनो भाणीतत्वं मदीयोसि निष्चितं।

यदात्वा कारयामि त्वां चागंतव्यं तदा त्वया।। 94 ।।

कालेक्षेपो यदा जातो मदनस्य गुफान्तरे।

तदावज्र मुखेनोक्तो भ्रातृप्रति प्रमोदितः।। 95 ।।

मदनो मरणं प्राप्तो दैत्येन निहतो ध्रुवं।

अधुनागम्यतेग्रेहे प्रमोदेनान्वितावयं।। 96 ।।

इत्युक्तोत्थायते मूढ़ा स्वगेह गमनायहि।

विलोकयंती च गुफां तैर्दृष्टोमदनस्तदा।। 97 ।।

भूषणैः परमैर्युक्तः पूजितः सुरसत्तमैः

एवं विधं च तं दृष्ट्वा जातास्ते गर्व वर्ज्जिता।। 98 ।।

मदनं मायया युक्ता मिलिताः खेचरात्मजाः।

तं तु कालगुहां नित्युर्मुग्धंपुर्ण बलान्वितं।। 99 ।।

गृहायादूरतः स्थित्वा जगौ वज्रमुखोनुजान्।

अविमृष्य गुहामेनांयो वै विषति धीरधीः।। 100 ।।

इष्टासिद्धिं समासाद्य समायाति सुखेनसः।

तस्मातिष्टं तु यूयं हि विषामि वेगतोप्यहं।। 101 ।।

इत्युक्ते मदनः प्रोचे श्रृणुभ्रातृवचो मम।

प्रेषयस्व ध्रुवं मह्यं कृपां कृत्वा ममोपरि।। 102 ।।

इत्युक्ते प्रेषितस्तेन मदनोमुग्धमानसः।

ययोवेगेन तत्रैव निजगेहं यथानरः।। 103 ।।

प्रविश्य मदनो वेगात् चकार भीमनिस्वनं।

वज्रयात समं रौद्रं चात्पालं कर्णयोः कटुः।। 104 ।।

एवं भीमं रवं श्रुत्वा तत्रस्थो राक्षसाधिपः।

वेगेन प्रकटो जाताः क्रोधारूण निरीक्षणः।। 105 ।।

रे रे पाप दुराचार निंद्यमानवकाधम।

पवित्रं मद्गृहं कस्माद्दपवित्रं कृतं त्वया।। 106 ।।

अद्यप्रभृति रे मूढ किं त्वायान श्रुतापुरा।

येनाद्यात्र समायातो गन्तुं यमनिकेतनं।। 107 ।।

तस्य तच्चवचः श्रुत्वा जगाद मदनोवली।

नीच किं जल्पिते नैव पुरूषार्थं नात्र लभ्यते।। 108 ।।

कुरूयुद्धं मया सार्द्धं यदितषक्तिरद्भुता।

वृथा किं दीयते गाली नीच नीच जनादृता।। 109 ।।

यदि त्वं शूर धीरोसि लंपटोसिरणे शठ।

तदात्रवेगतो युद्धं कुरू किं वै विलम्बसे।। 110 ।।

तेनवाक्येन क्रुद्धोसौ प्रबलो राक्षसाधिप।

मदनोपि तदा तं हि क्रोधेन सन्मुखं ययो।। 111।।

बलानैस्तर्ज्जनैस्तौ च चपेटानिष्च मुष्ठिभिः।

चक्रतुस्तु चिरं युद्धं क्रोधेन मदनासुरौ।। 112 ।।

अनेन विधेनायुध्वा मदनेन जितोसुरः।

पपातपादयोर्भक्त्या पूर्व पुण्य प्रभावतः।। 113 ।।

ददौचामर युगं विषतं तु समं वरं।

निर्मलं चातपत्रं हि पवित्रं वसुनंदकं।। 114 ।।

तरवारिं तथा रम्यां वस्त्राणि कुसुमानि च।

मदनायासुरोदत्वा जगाद वचनं वरं।। 115 ।।

तवास्मि किं करो नाथ त्वं मे प्रभुर्नसंषयः।

तं दैत्यं तत्र संस्थाप्य निर्गतो मदनोयावत्।। 116 ।।

आगच्छतं च तं दृष्ट्वा पूजितं दैत्यनायकैः।

सर्वेदीनमुखा जातास्ते वै खेचर नंदनाः।। 117 ।।

मिलिता मयया सर्वे मदनस्यतदाखिलाः। – द्वितीयोलाभः

पुनर्नाग गुहां निन्युर्मदनं मुग्ध मानसं।। 118 ।।

तस्यास्तुदूरतः स्थित्वा जगौ वज्रमुखं खगः।

योस्यां विषति वेगेन योवैप्राप्नोति चिंतितं।। 119 ।।

तस्माद्यूयं तथांत्रेव तिष्ठंतु हे ममानुजा।

यावन्नीत्वा समेष्यामि लाभं त्रिदष कल्पितं।। 120 ।।

तथैव मदनः प्रोचे भ्रातरं विनयानतः।

कृपया तव गच्छामि गुहायां लाभ हेतवे।। 121 ।।

तदा वज्रमुखः प्राहा तव किं कथ्यतेमया।

त्वदृषो न प्रियः कोपिं वर्त्तते मम साम्प्रतं।। 122 ।।

वत्स गच्छ द्रुतं तत्र नीत्वा लाभं मनोरमं।

आगच्छ जयसंयुक्तः पूर्वपुण्य प्रभावतः।। 123 ।।

मदनस्तस्य वाक्येन गतोसौ वेग वां स्ततः।

गत्वाहि पतिनासार्द्धं युद्धं कृत्वाति दुःसहं।। 124 ।।

ततोनागतितं च चकार स्व वंषवली।

अहिनाथोपि नत्वासौ तुष्टोदा दक्षिणां वरां।। 125 ।।

नागतल्पयुतां शय्यां वल्लकींमृदुविष्टरं।

पादपीठं मनोज्ञं च वस्त्राण्याभरणानि च ।। 126 ।।

गृहकारिकां तु विद्यां तथा सैन्यस्यराक्षिकां।

विद्याद्वयेन संयुक्तमेव मापमनोभवः।। 127 ।।

एवं तं स्ववषं कृत्वा तत्र मुक्त्वा मनोभवः।

अर्चितोथ समायातो भ्रातृणां तु समीपकं।। 128 ।।

इतिनागविधैर्लाभै युक्तं तं च मनोभवं।

दृष्ट्वाते भ्रातरः सर्वे मिलितामाययायुताः।। 129 ।।

ततस्तं वापिकां निन्पुर्भयदांसुर रक्षया। – तृतीयोलाभः

तस्यादूरतरं स्थित्वा जगौवज्रमुखः खगः।। 130 ।।

अस्यां करोति यः स्नानं शंकयां परिवर्ज्जितः।

शुभगोरूप संपन्नः सवैस्याज्जगतां पति।। 131 ।।

तदीयं वचनं श्रुत्वा शंकया रहितं सुधीः।

गत्वावेगेन मदनः पपात वापिकां बली।। 132 ।।

गजेन्द्र इव निःषंकममज्जं भयवर्ज्जितः।

कराभ्यां बलयुक्तोसौ जघानवापिका जलं।। 133 ।।

वापिकायाः पतिकुद्धोमरं प्रति समागतः।

ध्वनिं तोयस्य गंभीरं श्रुत्वामरुजघातवत्।। 134 ।।

आगत्य मदनं प्रोचे रे रे पाप नराधम।

पवित्र जल संपूर्णा सुरनाथस्य वापिका।। 135 ।।

पवित्रैः कमलैर्युक्ता त्वया तु पादघाततः।।

मनुष्येण सतानूनमपवित्रा कथं कृता।। 136 ।।

भुक्ष्ववेगेन हे पापत्वमन्यायतरोः फलं।

प्रेषयामि दुराचारं मृत्यवेयम मन्दिरे।। 137 ।।

इति दुष्ट वचः श्रुत्वा मदनः क्रोधपूरितः।

जगाद दैत्यराज नाथं शृणु दैत्यसुराधम।। 138 ।।

वृथा किं जल्यसे मूढ़ रणेव्यक्ति प्रदर्षये।

शूरोसिकृतकृत्योसि तर्हि तिष्ठ ममाग्रतः।। 139 ।।

तेन वाक्येन क्रुद्धोसौ युद्धं चक्रे तदोत्कटं।

महद्युद्धे ततो जाते मदनने सुरोजितः।। 140 ।।

घपत्य पादयोरस्य सुरोसौप्रजगौवचः।

तवाहं करोनाथ त्वं मे प्रभुर्नसंषयः।। 141 ।।

एवमुक्त्वा प्रपूज्याथ ददौ मकरध्वजं वरं।

तदादि मकर केतुः कामोभूद्भुवनखिले।। 142 ।।

नीत्वा लाभं समायातो दृष्टोसौमदनो यदा।

तदाते भ्रातरः सर्वे जाता क्लानमुखा क्षणान् ।। 143 ।।

मिलित्वामययातो तु निन्युर्मदनमन्यतः। — चतुर्थोलाभः

आग्निकुंडं ज्वलंतं वैदूरं स्थित्वा जगौस च ।। 144 ।।

श्रृण्वंतु भ्रातरः सर्वे मदीयं वचनं वरं।

वृद्धैर्विद्याधरैः प्रोक्तं सर्वेषां हित कारणं।। 145 ।।

अग्निकुंडे ज्वलंतंयो वेगाद्विषति मानवः।

चिंतितार्थं समासाद्य स स्यात् पृथिवीपति।। 146 ।।

तेन वाक्येन संतुष्टो जगाम मकरध्वजः।

वेगेन निर्विषंकोषवग्नि कुंडं प्रमोदतः।। 147 ।।

समीपं च समागत्य पपातासुरसेविते।

प्रौढेचाग्निमये कुंडे साहसैक रसान्वितः।। 148 ।।

ममर्द सर्वतस्तं च कुंडमग्निमंय हठात्।

वातत्तस्यासुरो वेगा क्रोधेन प्रकटोभवत्।। 149 ।।

युध्वाचिरं स्मरेणामाहारितं विबुधेन तु।

तुष्ठेन पादयोः नत्वा जल्पितं वचनं वरं।। 150 ।।

अग्निधौतं परं हैमं वस्त्र युग्मं मयार्पितं।

प्रद्युम्न त्वं गृहाणोदं कृपां कृत्वा ममोपरि।। 151 ।।

अद्य प्रभृति दासोस्मि त्वदीयोहं महाबल।

इत्युक्त्वा तत् च दत्वा वैमदनस्तेन विसर्ज्जितः।। 152 ।।

आगच्छन्तं च तं दृष्ट्वा पुनः कुद्धास्तथैव हि।

मेषाकारगिरिं गत्वा स्थित्वा ते दूरतोजगु।। 153 ।। – पंचमोलाभः

अत्रयोववचान् वीरो विषति शंकयोष्भितः।

चिंचितं लभते लाभमिति वृद्ध वचो ध्रुवं।। 154 ।।

वज्रदंष्ट्र वचः श्रुत्वा प्रहृष्टो मदनस्तदा।

नत्वास्य पादयुगलमुत्पपातिवेगतः।। 155 ।।

तयोर्मध्ये यदा यातो मदनोकुटिलाषयः।

तदा तं मिलितुं लग्नं दिव्यं श्रृंगद्वयं वलान्।। 156 ।।

कूर्पराभ्यां तु संताड्यमध्ये सौ मदनो बली।

ज्ञात्वा सुरमयीं मायां विवेष शंकयोष्भितः।। 157 ।।

तावत् च प्रकटो भूत्वा समायातो महासुरः।

तस्यापिकठिनैः वाक्यैः युद्धंचक्र मनोभवः।। 158 ।।

संयुध्य विबुधेनामाजितोऽसौबलषालिना।

करद्वयं तु संकोच्य जगादमनं सुरः।। 159 ।।

तावत्कीयोस्म्यहं नाथत्वंमेप्रभुर्नसंषयः।

इत्युक्त्वा कुंडलयुगं ददौ चास्मै मनोहरं।। 160 ।।

तत्नीत्वाथ समायातो मदनोसौबलभिर्यदा।

तदास्ते कुपिताः सर्वे जगुर्वज्रमुखाग्रजं।। 161 ।।

मारयामो वयं नूनमेनं दुष्टंवलान्वितं। – षष्ठमोलाभः

गत्वा सर्वत्र पापोयमायाति निधिभियुतः।। 162 ।।

पश्चात्स्यात् दुर्ज्जयो नूनं मधुना चेत् नमार्यते।

व्याधय शत्रवष्चापि लब्धमूलाहि दुर्ज्जया।। 163 ।।

ततो वज्रमुखः प्राहमाभवंत वत्सकाः परं।

अद्यापि मारणोपायाः सन्ति तस्य दषैव हि।। 164 ।।

तेषुस्यान्तमरणं चास्य नूनं लोभयुतस्य हि।

लोभवान् म्रियते जीवो निर्लोभः सुखमाप्नुयात्।। 165 ।।

इत्युक्त्वा मिलिताः तस्मै माययाकुटिलाषयाः।।

अग्रजस्य ततः पादौ पतितो मदनः सुधीः।। 166 ।।

ततस्ते मिलिताः सर्वे विजयार्द्धगिरिं वरं।

पश्यंत सर्वतोरम्यं नाना कौतुक संयुतं।। 167 ।।

सहकार तरुं दृष्ट्वा स्थित्वास्मात् दूरतः शठाः।

जगौ वज्रमुखो वाक्यं पापधीः कुटिलाषय।। 168 ।।

योस्यापि सहाकारस्य फलं भक्षति मानवः।

सदा स योवनो भूत्वा सौभाग्यं परमं भवेत्।। 169 ।।

श्रुत्वास्य वचनं वीरो जगादासौ तदाग्रजं।

त्वादेषेने गच्छामि तं वृक्षं चाति सुन्दरं।। 170 ।।

पृष्ट्वा तं भ्रातर वेगात् जगाम मदनोबली।

चटित्वा चास्य शाखायां कम्पयामास वेगतः।। 171 ।।

कपिरुपधरस्तावत् तत्रत्यसुर सत्तमः।

वक्रभ्रूरक्तनेत्रोसौ कुटिलोभीमरुप भाक्।। 172 ।।

तर्ज्जयन् विविधैः वाक्यैः मदनं क्रोध पूरितः।

रे रे भूढ दुराचार पापमानवकाधम।। 173 ।।

पवित्रे सहकारे में चटितोसि कथं खल।

फलानि च कथं भूमौपात्यं ते सहकारतः।। 174 ।।

गालीभीरूषितो भूत्वा युद्धं चक्रे मनोभव।

वानरोपि चिरं तेन क्रोधारुण निरीक्षणः।। 175 ।।

चिरं युध्वाथ मदनो धृत्वा पुच्छे तु वानरं।

भ्रमयित्वा यदा भूमावस्फालतिमनोभवः ।। 176 ।।

तदासौ प्रकटो जातो विवुधोभय पूरितः।

जगाद मुंचमंचत्वं मयिदाने कृपां कुरू।। 177 ।।

मुक्तेन तेन किं दत्तं किरीटममृतस्रजं।

पादेन व्योमगे तस्मै मदनाय समर्पितं।। 178 ।।

तं दैत्यं तु निजं कृत्वा पूजितो मदनो यदा।

तरूं मुक्त्वा समायातो भ्रातृभिष्च विलोकितः।। 179 ।।

तदास्ते भ्रातरः क्रुद्धा मारयामोधुना वयं। – सप्तम्लाभः

ततो वज्रमुखः प्राह स्वस्थास्तिष्ठं तु भ्रातर।। 180 ।।

तेषां तावच्च मिलितो मदनः सुरपूजितः।

मा यया मिलितास्तेवै सर्वेतु कुटिलाषया।। 181 ।।

कपित्थाख्यं वनं निन्युर्दूरेस्थित्वा जगुर्वचः।

अत्रैव च वने रम्ये योवैविषति मानवः।। 182 ।।

चिंतितार्थं समासाद्यसस्याच्च पृथिवीपतिः।

इतिवाक्यं हि वृद्धानां विजयार्द्ध निवासिनां।। 183 ।।

भवंतोत्रैव तिष्ठतु जगौ वज्रमुखष्चतान्।

अहं गच्छामि वेगेन प्राप्तोमि मन चिंतितं।। 184 ।।

तेन वाक्येन तुष्टोसौमदनोपि ययौ मुदा।

कपित्थाख्यं वनं गत्वा चटितोथतरुपरि।। 185 ।।

तावत् तत्र समायातो जगरुपधरोसुरः।

चलत् अंजन समाकारो भीमोति रौद्र रुपकः।। 186 ।।

युद्धं कृत्वाति विषमं मदनोपि गजेन च।

विमदं चक्रेथ गजं बलानैस्तर्ज्जनैस्तथा।। 187 ।।

तदा जगाद स गजो मदनं विनयान्वितः।

तवास्मि कामगजोहं स्मरणीयस्त्वया विभो।। 188 ।।

इत्युक्त्वा पूजितस्तेन समायातो मनोभवः।

तं दृष्ट्वाते पुनर्निन्युः षिखरमनुबालकं।। 189 ।। – अष्ठमोलाभः

दूर स्थित्वा पुनः प्राह वज्रदंष्ट्रः खगात्मजः।

अत्रोरोहतियषूरः सचैकाधिपतिर्भवेत्।। 190 ।।

तस्य वाक्येन तुष्ठौसौ मदनो विनयान्वितः।

जगामषिखरं वेगात्साहसैक रसान्वित।। 191 ।।

तथैव पादघातेन प्रबुद्धो भुजगाकृतिः।

स्मरस्य सन्मुखं दैत्यो वेगो देव समागतः।। 192 ।।

तेनयुद्धं महत्चक्रे ताडनैदुःप्रवादनैः।

मदनोपि रणे तं हि जिग्येवेणचासुरं।। 193 ।।

अष्वरत्नं छुरिकां च कवचानि च मुद्रिकां।

ददौमदनाय तुष्ठो दैत्यनाथस्तदा हि सः।। 194 ।।

तं दैत्यं तु निजं कृत्वा पूजितस्तेन मन्मथः।

तथैवच समायातं दृष्ट्वा ते खेचराः शठाः।। 195 ।।

पापोय तु समायात नीत्वालाभं महोत्तमं। – नवमोलाभः

किं कुर्मष्चस्य दुष्टस्य जगुरेवं परस्परं।। 196 ।।

ततस्ते तं पुनः निन्युः सरावाख्यं महागिरिं।

तं दृष्ट्वाचाग्रजः प्रोचे श्रृण्वंतु भ्रातरो वच।। 197 ।।

अत्रारोहति यो नूनं निःषंकानिर्भयोबली।

समस्तां खेचरीं लक्ष्मीं सप्राप्नोति न संषयः।। 198 ।।

तस्मादत्रैव तिष्ठंतु यूयं सर्वेममानुजः।

अहं गत्वा समेष्यामि नीत्वा लाभं यथेच्छितं।। 199 ।।

एवं तस्य वचः श्रुत्वा मदनष्चाग्रजं जगौ।

अहं गच्छामि हे भ्रातः सरावाकारके गिरौ।। 200 ।।

तस्मादेषं तु संगृह्य मदनोथ ययौजवान्।

चटित्वा सहसा तस्य षिखरं कंपयद्बला।। 201।।

तावत् तत्र निवासीस प्रकटो विबुधोभवत्।

मदनेन समं युद्धं चक्रे कोपेन पूरितः।। 202 ।।

युद्धेजित्वाथ तं देव मदनोसौजयान्वितः।

कंठिकां परमां तस्य चांगदं कट्कद्वयं।। 203 ।।

कटिसूत्रयुतं सर्वं सम्प्राप्य पूजयासह।

वेगेनैव समायातो दृष्ठस्तैर्दुष्ठमानसैः।। 204 ।।

ततस्ते कुपिता निन्युर्वराहसन्निभं गिरिं। – दषमोलाभः

दूरे स्थित्वाथ तं प्रोचुः सर्वेखेचरनंदना।। 205 ।।

नगोयं शूकराकारो मुखं चास्य तथैव हि।

अत्र प्रविष्यः शूरास एवं पृथिवी पतिः।। 206 ।।

तेन वाक्येन मदनः प्रधाव्य चटितो गिरौ।

मेलयंष्चमुखं सोपिकूर्पराभ्यां विदारितः।। 207 ।।

वाराहमुखनामासौ विबुधष्चाति बलोबली।

मदनेन समं युद्धं चक्रे भीरुभयाकरं।। 208 ।।

मदनेन जितः सोपिपूर्वपुण्य बलेन हि।

पुण्येन दुःकरं नास्तित्रैलोक्येय सुखावहं।। 209 ।।

जयषंखाभिधं शंखं धनुः पुष्पमयं वरं।

समर्पितं तु दैत्येन पूजयित्वामनोभवं।। 210 ।।

नीत्वा   लाभं समायातो मदनोजय भूषितः।

ततः पÁवनंतैष्च नीतः क्रोधेनतैः शठैः।। 211 ।। —एकादषमोलाभः

दूरे स्थित्वा जगौकामं श्रृणुवाक्यं विचक्षण।

कमलजाखं वनं रम्यं प्रसिद्धं वसुधातले।। 212 ।।

अत्रयोयातिवेगेन पुनरेति भयोष्भितः।

जगतोधिपति त्वं तु नूनं तस्य करे स्थितं।। 213 ।।

तेन वाक्येन तुष्टोसौ मदनो बल भूषितः।

ययौतत्राति वेगेन लाभेनैवोद्यमंध्रुवं।। 214 ।।

विशन् तत्र वनेधीरः खेचरं तु मनोजवं।

नामतो भुवि विख्यातं दृढ़ं बद्धं तरोरधः।। 215 ।।

मदनोथखगं दृष्ट्वा प्रपच्छ भयवर्ज्जितः।

केनवा विजनेरण्ये दृढं बद्धोसि खेचरः।। 216 ।।

ततो मनोजवः प्रोचे श्रृणुनाथ वचोमम।

वसंतक खगेनाहं बद्धोस्मि पूर्व वैरिणा।। 217 ।।

शरणं यातोस्मि ते नाथः रिपुरेषतरुपरि।

मां विमोचय वेगेन तवास्मि किं करो विभो।। 218 ।।

इत्युक्ते मदनेनोक्तं भातृ तथास्त्वं भयं वृथ।

मोचयामीतिवेगेन त्वां बद्धं खेचरण हि।। 219 ।।

मोचितस्तेनवेगेन मदनेनखगात्मजः।

सोप्यनाल्मप्य मदनं शत्रोष्च पृष्ठितो ययौ।। 220 ।।

गत्वा वेगेन तं धृत्वा समानीय जगौस्मरं।

त्वामुपकारस्य निधिमपृष्ट्वा च गतोयतः।। 221 ।।

तदेनं तु रिपुं नेतुगतोहं वेगतो विभो।

अद्य प्रभृति जीवामियत्तत् तवप्रसादतः।। 222।।

विद्ययोर्द्धितयं तस्मैहारं तु बहुमूल्यकं।

इन्द्रजालकरीविद्यां ददौ तोषात् खगात्मजः।। 223 ।।

मदनेनापि च तयोः साक्षमापरमाकृता।

तदाते नवसंतेन तुष्टेन मदनस्य च ।। 224 ।।

दत्ताति सुंदरीकन्या नवयौवन भूषिता।

सर्व लक्षणसम्पूर्णा पुण्यात् किं किं न लभ्यते।। 225 ।।

नीत्वा लाभं समायातं दृष्ट्वाते मदनं शठाः।

क्रोधेनान्यत्रतं निन्युर्वनं कालवनाभिधं।। 226 ।। द्वादषमोलाभः

दूरेस्थित्वा ततः प्रोचे मदनं वज्रमुखाद्वयं।

अत्रयोयाति वेगेन स लभे लाभमुत्तमं।। 227 ।।

तत्र गत्वाथ तं जित्वा दैव्यं दुष्टं महाबलं।

तेनतस्मै तदा दत्तं सषरंकौसुमंधनुः।। 228।।

मदनं मोहनं चैव तापनं शोषणं तथा।

उन्मादनं तु विख्यातं पंचैतेकौसुमाषराः।। 229 ।।

जनानां मोहने दक्षा युवतीनामुन्मादने।

तदादि मदनष्वाभूद्यथार्थः पूर्व पुण्यतः।। 230 ।।

त्रिभिः कुलकं ।। — त्रयोदषमोलाभः

नीत्वा लाभं समायातं दृष्ट्वा खेचरनंदनाः।

पुनः क्रोधेन तं निन्युर्भीमां भीम गुहां खलाः।। 231 ।।

तथैव मदनं प्रोचु सर्वरुपधरां परां।

जगामचातिवेगेन मदनोकुटिलाषयाः।। 232 ।।

गत्वावेगेन तं जित्वा तस्मादाय मनोहरं।

छात्रं पुष्पमयं रम्यं शय्यां पुष्पमयीं वरां।। 233 ।।

पूजितो मानितस्तेन नत्वा पादौ विसर्ज्जितः।

समायातोतिवेगेन पुण्या सौख्यं सदानृणां।। 234 ।।

समायातं युतं लाभै दृष्ट्वा ते दुष्टबुद्धयः। – चतुर्दषमोलाभः

क्रोधेनैवाग्रजं प्रोचुः मारयाम स्मरं वयं।। 235 ।।

यत्रयाति दुराचारो लाभं नीत्वा ततोप्ययं।

समायात्पतिक्षेमेन दवैर्हंतुं न शक्यते।। 236 ।।

अतोत्र खड्गघातेन मारयामोविसंषयं।

त्वमत्रतिष्ठमौनेन वारणीयावयं न हि।। 237 ।।

ततोवज्रमुखः प्रोचे श्रृणुं तु वचनं मम।

अद्यापिषत्रुयाताय वर्त्तते स्थानकद्वयं।

तत्रनीत्वा तु तं दुष्टं मारयामो वयं ध्रुवं।

तावत्किंचित्त कर्त्तव्यं दुष्टचित्तं मनोभवे।। 239 ।।

एतस्मिन्नंतरे सर्वे मिलिता भ्रातरः स्मरं।

विप्रतार्य्य पुनर्निन्युर्वनं विपुलनामकं।। 240 ।।

समुन्नतगिरिं तत्र श्रीजयंताभिधानकं।

नानावृक्षैः समायुक्तं वल्लीजाति विराजितं।। 241 ।।

दृष्ट्वा ते दूरतोप्येन जगौ वज्रमुखोग्रजः।

प्रविष्यात्रैवयोधीर रमित्वायाति वेगतः।। 242 ।।

चिंतितार्थं समामाद्यसस्यात् त्रिदषवंदितः।

एवं तस्य वचः श्रुत्वा ययौ वेगान्मनोभवः।। 243 ।।

यदाविषति मध्येसौ वनस्यैव विचक्षणः।

तावत् तत्रैवतेनापि दृष्टो नागाजयंतकः।। 244 ।।

तस्य पार्श्वे जलैः पूर्णान् वाहिनी वेगवाहिनी।

वर्त्तते तु तमालाद्यैर्युक्तं कंठोपकंठिका।। 245 ।।

षिलायाः फटके रम्ये सत्तमालतमोरणः।

स्थितां ध्यानस्य योगेन कामिनीं विहितासनां।। 246 ।।

रुपयौवन संपूर्णां नासाग्रणिहितेक्षणां।

लक्षणैर्विविधैर्युक्तां सत्कला गुरुपारगां।। 247 ।।

ताम्रवन्नखकिर्णैष्चा पाटलाकार धारिणीं।

ध्यानेन दधतीं जाप्पकरे स्फाटिकीं मालिकां।। 248 ।।

श्वेतचीनमयं वस्त्रं धारयंतीं सुधौतकं।

श्लथेन केषपाषेन छादिताश्रु युगांवरां।। 249 ।।

सुख सौरभमाक्रान्तैः भ्रमराणां च मंडलैः।

परितोभ्रममाणैष्च सेव्यमानसुखांवुजं।। 250 ।।

कुचभारेण नम्रांगीक्षीमांगी जघनालसां।

जितहंस गतिं बालां बल्लकीमधुरष्वरां।। 251 ।।

कंवुकंठासुनासां च चलद्वारिजलोचनां।

निजरुप जितं मन्ये त्रैलोक्य तरुणीकुलं।। 252 ।।

सर्वलक्षण सम्पूर्णां सर्वावयव सुन्दरां।

सर्वविद्या प्रवीणां च नारीगुण विराजितां। 253 ।।

एवं विद्यां च तां दृष्ट्वा मदनो विस्मयाकुलः।

चिन्तयामास चित्तेसौ कामेना सुंदराकृतिं।। 254 ।।

किमियं सूर्यनारीस्यात् किं कियं चन्द्रकामिनी।

किमियं शक्रवधूलोकं समायाता विलोकितुं।। 255 ।।

किमियं कामरमणीं कांति कीर्त्तिरथापिकीं।

किमियं किंनरी नूनं किमियंपन्नगागणा।। 256 ।।

इहकांति परालोके इह रुपं मनोरमं।

इहैव भव्यता सर्वा लावण्य मिहसंस्थितं।। 257 ।।

इहैव गुणधामष्च कलानां तिलर्सित्वहि।

महिमांमुद्रिताष्चेह अतः किं वर्ण्यते परं।। 258 ।।

एवं विधां स्थितां तत्र ध्यान योगेन निष्चलां।

त्रैलोक्य सुंदरीणां हि जित्वा रुपं समां गतां।। 259 ।।

एवं विद्यां च तां दृष्ट्वा मदनोमदनातुरः।

बभूत तत्क्षणादेव प×चबाणैहैतस्तत।। 260 ।।

यावच्चविग्रचित्तोसौतित्र तिष्ठति मन्मथः।

तावत् तत्र समायातो विबुध श्रीवसन्तकः।। 261 ।।

स्थितोस्यैवपुरोयावन्नत्वास्य पादमंकजं।

तावत्यप्रछमदनः कन्याया कारणं स्फुटं।। 262 ।।

कथयस्व महाभाग मम विस्मय कारणं।

किमर्थां भीषणे रण्ये स्थितेयं च नितोत्तमा।। 263 ।।

कस्येयं दुहिता वत्से कस्मात् तपति वातयः।

नवयौवन संपूर्णा तरुणी गुण मंदिरा।। 264 ।।

ततोसौ मदनं प्रोचे श्रृणुस्वामिन् वचोमम।

प्रभंजन वाभिधानोस्ति खेचराणामधीष्वरा।। 265 ।।

तस्यावार्गिति विख्याता दयिता गुणसागरा।

तयोः पुत्री तु संजाता विख्याता रतिनामका।। 266 ।।

नवयौवन संपूर्णा तपस्तपति साम्प्रतं।

मदनेन ततः पृष्ट किमर्थं कष्टमाश्रिता।। 267 ।।

ततः प्रोवाचविबुधः कथ्यते श्रृणुकारणं।

अस्यापितृगृहे योगी समायातोन्यदाविभो।। 268 ।।

आहारानंतरंसोथ पृष्टोस्या जनकेनहि।

भविता को वरः स्वामिन् मम पु=या निवेद्यतां।। 269 ।।

ततोपि मुनिना प्रोक्तं शृणु भूप निगद्यते।

द्वारिकायां हरेः सूनुः रुक्मिण्यास्तनुसंभवः।। 270 ।।

मकरध्वजाभिधानो हि भवितास्या दुहितुःपतिः।

सर्वलक्षणसंपूर्णा सर्व विद्या निधान भूः।। 271 ।।

विपुलाख्य वनस्यांते समेष्यति स्वयंस तु।

ईदृषैर्लक्षणैर्युक्तः साहसैकरसाकुलः।। 272 ।।

तस्यैव वचकृत्वा स्थितेयं बालिकावने।

तपस्तपतिध्यानं तु धत्तेतत्यति हेतवे।। 273 ।।

लक्षणैष्च गुणैः कृत्वा त्वमेवहि न संषयः।

अस्याःपुण्य प्रभावेन समयातो न संषयं।। 274 ।।

द्वयोः सदृष रुपस्य संयोगेनैव साम्प्रतं।

विश्वकर्मः श्रमोनूनं भूयात् च सफलस्तिवहि।। 275 ।।

इति तस्य वचः श्रुत्वा प्रद्युम्न प्रमदं श्रितः।

हर्षेणाधोमुखं पश्यन् जगाम सुन्दरं वचः।। 276 ।।

अहं तु पुण्ययोगेन समायातो वने भ्रमन्।

अस्यास्तु दर्षनादेषा वेद्धोस्मि मन्मथैः शरैः।। 277 ।।

भूयात् त्वत्प्रसादेन संयोग आवयोरिह।

उत्तमानां तु संयोगे दुःखं शाति देहिनः।। 278 ।।

तेन वाक्येन तुष्टेन मदनस्य कन्यया सह।

विहितं पाणिग्रहणं देवेनविधिपूर्वकं।। 279 ।।

तं लाभं परमं प्राप्य तुष्टोभून्मदनस्तदा।

तत्रैवचापरो लाभो लब्धस्तेनाति पुण्यतः।। 280 ।।

कृते तु पाणिग्रहणे तत्रैव हि वने वरे। – प×चदषमोलाभः

मिलितो लाभ संयुक्तोनामतः शकरासुरः।। 281 ।।

प्रणम्य मदन सोपि ददौ हर्ष भरेण हि।

कामधेनुं पुष्परथं वसन्तमिव सुन्दरं।। 282 ।।

मदनोरथमारुह्य कन्यया सह तत्क्षणे।

लीलयावन मध्याच्च निर्गतो यदा।। 283 ।।

तदादीनमुखाजाता सर्वेखेचरं पुंगवाः। – षोड्षमोलाभः

लाभैः षोडषभिर्युक्तं दृष्ट्वा तं तु मनोभवं।। 284 ।।

रथारुढ़ोति रम्योसौ मदनोरति संयुतः।

अग्रतोर्भ्रातूभिर्युक्तः पुरं जगाम लीलया।। 285 ।।

पुरं प्रति जगामासौ रथारुदो मनोभवः।

दधातुः पुरतस्तेपि सर्वे दीनमुखा यदा।। 286 ।।

पुण्या पुण्यफलं नूनं विदुषां पुरतोपिते।

वदंत इव प्रकटं दृष्ट्वा पुरनिवासिभिः।। 287 ।।

तावत्पुरनिवासोपि नार्यः श्रुत्वा मनोभवं।

रत्यासह समायातं दृष्टं बाह्ये विनिर्ययु।। 288 ।।

कौतुकाकुलताः सर्वैः सरलाश्चपलेक्षणाः।।

गवाक्षमांर्ग्रपिदधुर्वदनैः शशिसुंदरैः।। 289 ।।

स्मरस्य रूपपाशेन बद्धास्ता वनितोत्तमाः।

मुक्त्वा स्व गेहकार्या निपीडयन्ति परस्परं।। 290 ।।

तत्र काचित् जगावेवमपरां कामिनीं प्रति।

श्लथकेशैः समासाद्यपिहिताग्रदिशं किमु।। 291 ।।

प्रसारित भुजयुगास्त्वं तिष्ठसि ममाग्रतः।

पुरतोठाथवेगेन देहिमांर्ग्रममैव हि।। 292 ।।

अपरा तु सखीं प्रोचे शृण्वालि वचनं मम।

दृश्यते मदनः स्यैव रूपंनोनयनामृतं।। 293 ।।

तदा किं जीवितव्येन किं वा मानुषजन्मना।

नयनद्वय साफल्यमन्यथा विफलं भवेत्।। 294 ।।

नम्रान्या कुचभारेण श्रोणी भारेणचालसा।

सहसा गंतु मसहावीक्षितुं हि मनोभवं।। 295 ।।

तदा तु हि सखीं प्रोचे दृष्ट्वा हष्ट तनूरूहं।

निर्मितं चास्य वपुर्यैस्तएव परिमानवः।। 296 ।।

धन्या सा जननीलोके धारितस्तु ययोदरे।

अपरां तु वचश्चान्यत् तदाधोचे मनोगतं।। 297 ।।

रत्यासमन्वितं दृष्ट्वा मदनं मदनालसा।

धन्या सा सुंदरा यास्य भवितां चांकवर्त्तिनी।। 298 ।।

काचित् श्लथांबरारामा काचिद्वाश्लथ कुंतला।

कुचाग्रात् चुटिताहारा दधा च मदनं प्रति।। 299 ।।

कटकं कर्णयोः कृत्वा कटिसूत्रं तथा गले।

हारां कटिप्रदेशेतु मेखलामस्तके परा।। 300 ।।

नेत्रयोः कुमकुम कृत्वा कज्जलं तु कपोलयोः।

योग्यायोग्यं तु को वेत्ति मदन दृष्टि गोचरे।। 301 ।।

काचिच्चमदन दृष्ट्वा रूपयौवन संयुतं।

मनोभव शरैवेद्धा जाता हृष्ट तनूरूहा।। 302 ।।

नाना विधाभि चेष्टाभिः पुरनार्य समागमे।

कामपाशेन वृद्धानां का का चेष्टा न जायते।। 303 ।।

एव नारी समूहेन वीक्ष्यमानो मनोभवः ।

राजवेस्मनि संप्राप्य यत्रासौ खेचराधिपः।। 304 ।।

निजमस्तक केशैश्च समार्य विनयेनच ।

प्रणम्यमपरं भक्त्या पितुश्चरण पंकजे।। 305 ।।

पित्रा पितं समालिंग्य सचुंब्य मुखमस्तके।

प्रपछकुशलं तस्य शरीरादि समुद्भवं।। 306 ।।

ततोपिमदनेनोक्तं कुशलं सर्वदा मम।

भवत्पादप्रसादेन कृपयातव हे विभो।। 307 ।।

इत्युक्त्वा तु क्षणं स्थित्वा जनकानुमतेन हि।

जगामलीलयायुक्तो जनन्या मन्दिरं प्रतिः।। 308 ।।

आलिंग्य जननीं वेगात्प्रणम्य पाद पंकजं।

निषसादपुरस्तस्या विनयेन मनोभवः।। 309 ।।

तस्मै कनकमालापि दत्वाषीर्वादमुत्तमं।

पुत्रं विलोकयामास लाभैः षोड्षभिर्युतं।। 310 ।।

सर्वलक्षण सम्पूर्णं नवयौवन भूषितं।

स्वकीय यषसा व्याप्तं विष्वं सर्वगुणास्पदं।। 311 ।।

स कोमलैः सुनीलैष्च भंगुरैरायतैस्तथा।

एवं विधैष्चितं केषै षिरस्तस्याति सुंदरं।। 312 ।।

कृष्ण श्वेतसु रक्तादि त्रिविधायत लोचनं।

चन्द्रवद्वदनं सौम्यं कम्बुकंठ मनोहरं।। 313 ।।

मेरुभित्ति समाकार वक्षस्थल विराजितं।

मृगराजासमं मध्यर्मिभनाथ गतिषुभं।। 314 ।।

तप्तकांचन संकाष शरीरं गुण मन्दिरं।

उपमानां समूहेन युक्तां तस्य शरीरकं।। 315 ।।

एवं विधं मनोजस्य रूपं सर्वगुणाधिकं।

दृष्ट्वा कनकमालाथ कर्मना प्रेरितासता।। 316 ।।

हतामन्मथ बाणैष्च ह्वदये मर्म भेदकैः।

तदादीनमुखाजाताहिमदग्धं पंकजं यथा।। 317 ।।

विरहानल संतप्तं वपुर्जातं तु दुःखितं।

करार्पित कपोला सा चिंताकर्त्तुं समुद्यताः।। 318 ।।

नयनाभ्यां अश्रुपातं कुर्वती विरहार्दिता।

किं करोमि क्व गच्छामि कं पृच्छामि वदामि किं।। 319 ।।

लावण्येनैव संयुक्तं नवं हि यौवनं वरं।

रूपंकान्ति गुणा धैर्यं विभवः सकलाः कला।। 320 ।।

एनं तु सुभंगं लोके सर्व विद्या समन्वितं।

सेव्यतेनर्मिथो नूनं सकलं विफलं तदा। 321 ।।

पीयतेन यदाचास्य मधुस्तु मुख पंकजात्।

पश्यतेनैव नेत्राभ्यामस्यैव मुख पंकजं।। 322 ।।

क्रुद्धा प्रणय कोपेन पÅन ताड्यते हि च।

नालिंग्यतेति प्रेमेननेक्षते वक्र लोचनैः।। 323 ।।

सुरतेव कणतेयानप्राप्यैनं सुंदरं प्रियं।

तस्याः किं जीवितव्येन विफलेनामुना विना।। 324 ।।

चिंतयन्ती चित्ते सौ स्थिता यावत् च खेचरी।

तावदस्यै नमस्कृत्य जगादमदनो गृहं।। 325 ।।

गतेथमदने देवी दुःखात् कनकमालिका।

चिन्तयामास चित्तेवै किं में जातमिदं ननु।। 326 ।।

कामस्य सायकैर्विद्धांक्षतसर्व शरीरिकां।

न समर्था बभूवासौ षौढ़ विरह वेदनां।। 327 ।।

विकारान्विविधांष्चक्रे तत्क्षणे विगतत्रपा।

विलोक्यते कुचतटं जृंभतेति मुहुर्मुहुः।। 328 ।।

शरीरस्थांस्तदा सर्वान् निराकृत्य च भूषणान्।

चिन्तयापूरिता सर्वानि निदिच निजं वपुः।। 329 ।।

केषांष्च षिथिलान् कृत्वा बन्धयित्वा पुनः तदा।

भूषणांष्चषरीरेसौ पुनष्चक्रे तथैवहि।। 330 ।।

मदनोद्भूत तापेन ताप्यमान शरीरिका।

कदलीदलवातेन चंदनस्य जलेन च।। 331 ।।

चन्द्रस्य किरणैष्चापि हारैष्च घातसारकैः।

न शषाम्यपरं तापं मदनाच्च समुद्भवं ।। 332 ।।

न क्षुधानैव निद्राहि न सुखं न पुसंभवं।

विरहेण समाक्रान्ता ले खेचर राड्वधूः।। 333 ।।

चिकित्सिकैः समागत्य विविधैष्च विलोकिता।

न साध्योसौगदस्तेषां विरहाच्च समुद्भवं।। 334 ।।

एकदा सदसिस्थेनपि तत्रातु मदनं प्रति।

भणितं श्रृणु वत्स त्वं मदीयं वचनं वर।। 335 ।।

त्वया ज्ञातं न किं मूढ़त्वन्मातातुरुजार्िता।

वर्त्तते प्राणसंदेहो तत्र त्वं न गतः कथं।। 336 ।।

पितरं तु तदा प्रोक्तं कामेन विनयात् ततः।

न श्रुतं नैव विज्ञातं मातुरामयकारणं।। 337।।

गच्छाम्यहं तवादेषात् निजमातुर्गृहं विभो।

इत्युक्त्वा वातिवेगेन तत्रासौमदनागतः।। 338 ।।

तत्र गत्वातिदुःखेन विलोकयतिमातरं।

क्षोणीपृष्ठे प्रसुप्तं हि विरहाक्षतविग्रहां।। 339 ।।

दुःखितां मातरं दृष्ट्वा प्रणम्यविनयेन हि।

उपविष्ठस्ततष्चाग्रे विनयानतविग्रहः।। 340 ।।

तस्या शरीर चेष्टां तु स्वरूपं च तथैव हि।

विलोक्य चिंतयामास कारणं वै मनोभवः।। 341 ।।

नैवत्रिदोष संभूतोगदोयं लक्ष्यते मया।

वेदना महती चात्र शरीरे दृष्यतेधुना।। 342 ।।

कथं वात्र समुद्भूतो रोगोयं जननी तनौ।

भविष्यति कथं नूनं शांतीरोगस्य साम्प्रतं।। 343 ।।

इति चिंतातुरा यावत् स्थितोसौमदनौवली।

अधोमुखोति दुःखेन चिंतयन् गद कारणं।। 344 ।।

तावत्कामालसादेवी कृत्वालस्यं महतरं।

दंदतीजृंभिका प्रौढ़ां प्रोत्थायक्षणमात्रत।। 345 ।।

परिवार जनं सर्वं कृत्वादूरमेवहि।

जगाद मदनं वाक्यं क्वणंतीष्लिथगात्रका।। 346 ।।

त्वमेकाग्रेण चित्तेन श्रृणु वाक्यं मनोभव।

तव का जननी वेत्सि तवकोत्रपिताध्रुवं।। 347 ।।

मदनोपि ततः प्रोचे किमंब पृच्छते त्वया।

त्वं मे माता ध्रुवं विद्धि कालसंवर मे पिता।। 348 ।।

इति श्रुत्वा ततः प्राह राज्ञी कनकमालिका।

आदिमध्यावषानां हि श्रृणुं त्वं कथानकं।। 349 ।।

एकदाहंगतारण्येरंतुं तु स्वामिनासह।

नदीनदतडागेषु कैलाषगिरिसानुषु ।। 350 ।।

रमित्वा तु चिरं कालं खदिराख्या महातटी।

तस्यामध्ये महान् भाति तक्षकोगिरिनामकः।। 351 ।।

तस्योपरिसमायातौ दम्पती तु विमानगौ।

विमानं स्तम्भितं तावत् तव पुण्य प्रभावतः।। 352 ।।

गतावावामधोवेगा षिलां दृष्ट्वा महत्तरां।

चलमानां तव स्वासाद्विस्मयाच्च निराकृता।। 353 ।।

तत्र त्वां सुंदराकारं सर्वलक्षण संयुतं।

दृष्ट्वावेवेन मोहेन गृहीतो स्नेहतो मया। 354 ।।

मया तदा ह्रदिजातं ममायं पति निष्चितं।

इति ज्ञात्वा पुरेचात्र समानीय प्रवर्द्धितः।। 355 ।।

अतस्त्वं कामयोग्योसि साम्प्रतं मेतिवल्लभः।

भुंजस्वत्वं मया भोगान् स्त्रीहत्या चान्यथातव।। 356 ।।

उभयत्र विरुद्धं हि वाक्यं मातुर्मुखोद्गतं।

श्रुत्वासोमदनः प्रोचेदुःखात् कंपितमस्तकः।। 357 ।।

किमुक्तं तुछया माता निंद्यानामपि निंदितं।

किं तु कुल प्रसूतानां पुंसां वैयुज्यते कथं।। 358 ।।

कुमार्गेतु गतं माता निजं चित्तं निवारय।

यत स्वयषसे नूनं कुलमार्गरतासती।। 359 ।।

इत्युक्त्वा मातरंसोपि मुहुर्मुहुवचोवरं।

निर्गतस्तु ततो वेगात् जनन्यामंदिराद्गुणी।। 360 ।।

चिंतयाकुलतोजातः पुरं त्यक्त्वा वनेस्मरः।

तत्रस्थे तु जिनागारे ददर्ष मुनिनायकं।। 361 ।।

वरसागरनामानं मुनिसंघ समन्वितं।

द्वादषांगधरं धीरमवधिज्ञान संयुतं।। 362 ।।

त्रिः परीत्यमुनिं नत्वापविष्याग्रेति भक्तितः।

दुःखान् मलान् मुखोभूत्वा जगादयतिनं स्मरः।। 363 ।।

मातुष्चित्तविकारं च सुगोप्यमपि सत्वरं।

एकान्तेषनकौ सर्वं मुनये मदनो जगो।। 364 ।।

विकारं विविधं प्राप्ता कामेना कुलितासती।

कथयस्व कृपां कृत्वा निजेर्थेतु कथं विभो।। 365 ।।

कार्मोदितं वचः श्रुत्वा जगादयतिनायकः।

श्रृणु वत्स महाबुद्धे संसारस्य विचेष्टितः।। 366 ।।

कारणेन विनाकार्यं जायते न कदाचनः।

स्नेहोथ वा यथा वैरं जायते पूर्वकारणात्।। 367 ।।

पुराभवे त्वया वत्स मधुना भूमि स्वामिना।

इन्दुप्रभाभिधाना हि हेमरथस्यगेहिणी।। 368 ।।

ह्वता मोहेन सा नूनं कृताग्रमहिषीवरा।

कैटभाख्योनुजस्तेवै जातस्तत्र भवे तव।। 369 ।।

तयातेन त्वया नूनं गृहीतं प्रवरं तपः।।

त्वं तयातेन वासार्द्धं गतोवैषोड्षेदिवि।। 370 ।।

तत्र भुक्त्वा परं सौख्यं द्वाविंषत्यब्धिमानकं।

आयुरंते ततष्च्युत्वायावैवेंदुप्रभाभिधा।। 371 ।।

विजयार्द्धगिरौरम्ये कालसंवर भू भुजः ।

तस्येयंदयिताजाता विख्याताकनकस्रजा ।। 372 ।।

अनुजेनसमंतत्रावु भूय सुचिरं सुखं।

द्वारिकायां यदोर्वंषेनारायण सुतो भवत्। 373 ।।

रुक्मिणी तनुसंभूतो ह्रतस्त्वं पूर्व वैरिणा।

शिलायां पिहितोरोषात् गिरौतहोकनामका।। 374 ।।

कालसंवरभूपेन तथा कनकमालया।

निःकाषितोति वेगोपि वर्द्धितष्चातिमोहतः।। 375 ।।

त्वां दृष्ट्वा पूर्वमोहेन व्याकुली कनकस्रजा।

संजाताकामसंतप्ता पूर्व मोहोतिदुस्त्यजः।। 376 ।।

दातुकामाहिते नूनं मोहाद्विधाद्वयंवरं।

त्वया ग्राह्यं छलाद्वछ तत्र गत्वाति वेगतः।। 377 ।।

तत् श्रुत्वा मदनः प्रोचे मुनीन्द्रं चाति हर्षतः।

करोमि तव वाक्यं वैताता कारणबांधवः।। 378 ।।

अपरं किंचित्पृछामि विस्मयं चित्तसंस्थितं।

जनन्या साहसं जातो विरहो मम दुस्सहः।। 379 ।।

जनन्याः कर्मदोषेणचाथवा मम पापतः ।।

विरहोयं तु संजातो वाल्यपि कथ्यतां विभो।। 380 ।।

इत्युक्ते तु मुनिः प्राह श्रृणुवत्सात्रकारणं।

जननीकर्मदोषेण संजातो विरहस्तव।। 381 ।।

प्रोच्यतेचाधुनातच्च कारणं कर्म संभवं।

पुण्यं पापं सुखं दुखं भुज्यते पूर्व संचितं।। 382 ।।

जम्बूद्वीपे भुविख्याते क्षेत्रे भरतनामनि।

मगधाभिधेचदेषे विख्यात जनसंभृते।। 383 ।।

तत्रास्तेभुवि विख्यातं लक्ष्मीग्राम संज्ञिकं।

नृपतिस्तत्र संजात सोमषर्माभिधो द्विजः।। 384 ।।

सर्वषास्त्र प्रवीणोषौ श्रुतिस्मृति परायणः।

जपहोमरतो नित्यं ब्रह्मकर्म विचारयत्।। 385 ।।

तस्यापि कमलानाम जायामाया विवर्ज्जितः।

लक्ष्मीवती तया जाता पुत्रीरूप गुणालया।। 386 ।।

सर्वलक्षणसंपूर्णा यौवनेन विभूषिता।

निजरूपेण तृणवन्मन्यमाना जगत् त्रयं।। 387 ।।

एकदा तद्गृहे योगीमलदग्ध शरीरकः।

आहारार्थं समायातः कृतमासेन पारणः।। 388 ।।

विमलावधि संयुक्तः सर्वषास्त्रार्थ पारगः।

जितकाममहाषत्रू रत्नत्रय विभूषणः।। 389 ।।

तस्मिन् क्षणे स्थिता सापि कन्यकारूपषालिनी।

कुमरेंदु निजं रूपं पश्यंती सर्व सुन्दरं।। 390

तवत्पृष्ठि समायातो मुनीन्द्रोज्ञान भूषणः।

बिम्बितं मुनीन्द्रस्य रूपं तत्रैव दर्प्पणं।। 391 ।।

निजरूप समीपेतुं मुखं दृष्टं तया यदा।

तदा तु चिंतितं चित्ते कृत्वा गर्वमहत्तरं।। 392 ।।

क्व में रूपं मनोज्ञं वै सर्वलोक मनोहरं।

क्व च निन्द्य विरूपं च धिग्धिग्रूपंमुनेरिदं।। 393 ।।

बहुधा च तयातच्च निंदितंरूपमुत्तमं।

मुनिचन्द्रस्य पापिन्या पापं तु समुपार्ज्जितं।। 394 ।।

तेनपापेन पापा सा जाता कुष्ठेन पीडिता।

सुखं न लभते क्वापि निदा कर्म प्रभावतः।। 395 ।।

तेनकुष्ठ प्रभावेन जाता सा कुत्सिता तनौ।

सप्तमे दिवसे नूनं प्रविष्ठा ज्वलने खला।। 396 ।।

आर्त्तं च बहुधा प्राप्य मृता सा विवसासनी।

ततो निंद्य शरीराहि खरी जाताति पापतः।। 397 ।।

तत्रदुःखं घनं भुक्त्वा मृत्वा भूत् गृहषूकरी।

कोटपालहलामृत्वा पापाज्जाता तु साश्वुनी ।। 398 ।।

अथैकदा श्वुनीसावै जाता बालाहिमागमे।

वाटिकायाः समीपे हि तृणपुंजे स्थिता सती।। 399 ।।

सुतानां तत्र मोहेन ज्वलने ज्वलिता हि सा।

मृत्वा पाप फलेनैव यत्र जातातदुच्यते।। 400 ।।

जाता च भेकनिगर्मेपुरे धीवर देहजा।

पूर्व पाप प्रभावेन निंद्यापूतिषरीरिका।। 401 ।।

तेन वपुः कुगंधेन स्वजनैर्गेहतोपि सा।

निराकृता दुराचारा क्व वा पापात्मनां सुखं।। 402 ।।

गंगायाः समीपे सा कृत्वा तृण कुटीरकं।

स्थिता परं जनै निंद्याषतछिद्र समन्वितं।। 403 ।।

उडपेन जनास्तत्र प्रोत्तारयति सर्वदा।

तेन द्रव्येण सानूनं करोत्युदर पूरणं।। 404 ।।

किंचित् द्रव्यं पितुर्गेहं प्रेषयंती स्थिता तु सा।

दुर्गन्धेत्यभिधाना हि दर्षयंत्पघजंफलं। 405 ।।

क्षिपेती तु स्थिता कालमनेन विधिनापि सा।

एकदात्रसमायातो यस्य निंदापुराकृता।। 406 ।।

तदा तं यतिनं दृष्ट्वा चिंत्तितं तु तया ह्रदि।

कथं स्थास्यति योगीन्द्र शीतनात्र सरित् तटे।। 407 ।।

जालयामी ज्वलनं तिष्ठामि च कुटीरके ।

वस्त्रावृत्त शरीराहं तथापि हिमपीडनं।। 408 ।।

इतिमत्वा गत्वा सा प्रदोषे मुनिसन्निधिं।

हुताषनेन वस्त्रेण चक्रे शीत निवारणं।। 409 ।।

प्रभात समयं यावत्ते नैव विधिना स्थिता।

इतः शीतं मितः शीतं कुर्वन्ती विàलात्मक।। 410 ।।

प्रभात समये योगीमुक्त्वा ध्यानं जगौ च तां।

हे लक्ष्मीवती वत्से त्वं कुषलिन्यसि पुत्रिके।। 411 ।।

सोमषर्माभिधानस्य ब्राह्मणस्यैवदेहजे।

नामांतरं तया श्रुत्वा चिंतितं निजमानसे।। 412 ।।

किं वाल्यसि योगीन्द्रः सत्यवाचा समन्वितः।

जिनषामनसं भूतानान्यथा जल्पयन्तिते।। 413 ।।

एवं विमृष्य माणस्य मूर्छयाकुलिता भवत्।

जातिस्मरण मात्रेण चिंतयाति गतान् भवान्।। 414 ।।

शीतवात प्रभावेन गतमूर्छातु सा तदा।

मुनेस्तु चरणौ नत्वा जगाद विनयान्विता।। 415।।

नाथ नाथात्र किं जातं कुर्वंती परिदेवनं।

क्व वा जन्म द्विजातीनां क्व वा धीवरजं भवं।। 416 ।।

मुनिनिंदा प्रभावेना महत्पापमुपाज्जितं।

तेनपापफलेनाहं भ्रमितास्मि भवान् विभो।। 417 ।।

पुराभवमहापापात् त्वमेव निंदितो मया।

तत्क्षमस्व हे नाथ कृपां कृत्वा ममोपरि।। 418 ।।

तं धर्मं तु समाख्या हि येन पापात् प्रमुच्यते।

सर्वभूत हितस्त्वं हि त्वं तु सत्वोपकारकाः।। 419 ।।

इति श्रुत्वा रुदन्ती तां जगौ योगी दयापरः।

माकृथास्त्वं वृथा वत्से दुःखासंसारकारणं।। 420 ।।

रोदनात् क्षीयते राज्यमिति सर्वजनश्रुतिः।

पूर्यतं रोदने नैव कुरू धर्मं जिनोदितं।। 421 ।।

नूनं पुराज्र्जित कर्म्म भुज्यते प्राणिना सदा।

मुनिनिंदा प्रभावेन त्वं जातात्वं निंदिते कुले।। 422 ।।

गृहधर्मरता नूनं कुरुधर्मं दयान्वितं।

इत्युक्ते सा मुनिं प्राह कथयस्व विभो वृषं ।। 423 ।।

व्रतद्वादष संयुक्तं सम्यक्त्वेन समन्वित।

जिनधर्मं तदा प्रोक्तं मुनिना धीवरीं प्रति।। 424 ।।

तयागृहीतं सर्द्धर्म्मं भाषितं यज्जिनेष्वरैः।

नमिता सा मुनीन्द्रस्य पादौवै पाप नाषनौ।। 425 ।।

मुनीन्द्रोपिगतः स्थानं तपोयोग्यं कृपापरः।

जिनधर्मेतुरतासाथ पापश्रव विवर्ज्जिता।। 426 ।।

किंचित्कालं स्थिता तत्र जिनधर्मरता सति।

पश्चादठताथ सा बाला कौषला नगरीं मुदा।। 427 ।।

तत्र गत्वाथ हर्षेण जिनेन्द्र भवनं गता।

तत्रैव गणिना श्रेष्ठा मिलितास्याधर्म ।। 428 ।।

तयाचार्यिकया तस्याः कृतं धर्मोपदेषनं।

ततः सा धीवर सुता धर्म ध्यान परायणा।। 429 ।।

तस्याथ पृष्ठितो लग्ना तपो नाना विधं तु सा।

कृत्वा निज शरीरे च कृषाजातात्र धीवरी।। 430 ।।

तयान्पदाथ सा जाता पुरं राजगृहं वरं।

जिनेन्द्र भवने चक्रे गत्वा तत्र नमस्क्रियां।। 431 ।।

रात्रौवपर्यिका गत्वा पुर बाह्ये नगोपरि।

गुहामध्ये तु संविष्य स्थिता ध्यान समन्विता।। 432 ।।

गुहाबाह्येस्थिता सापि धीवरस्य च देहजा।

उपवासेन संयुक्ता जंयती श्री जिनेष्वरं।। 433 ।।

ततस्तत्र समायातोरात्रो व्याघ्रोति दुस्यहः।

तेन सा भक्षिता वेगात् स्थिता बाह्येतु धीवरी।। 434 ।।

मृत्वा सा ध्यान योगेन जिनधर्म प्रभावतः ।

सम्यक्तवा पालन्मन्नूनं संप्राप्तो षोडषं दिवं।। 435 ।।

तत्रेन्द्रस्य तु संजाता रमणीपूर्व पुण्यतः।

बुभुजे सुचिरं कालं सुखं धर्म समुद्भवं।। 436 ।।

आयुरंतेथच्च्युत्वा सा कुटिनाख्येपुरे वरे।

भीष्मरूपस्य संजाता दुहिता गुण भूषिता।। 437 ।।

पूर्व पुण्य प्रभावेन रुक्मिणीभिधानका।

तस्याग्रजेन सा दत्ता दमघोषस्य सूनवे।। 438 ।।

ततो नारद वाक्येन रक्ता साभूद्धरीं प्रति।

तया तु प्रेषितो दूतः सगत्वा केषवं जगौ।। 439 ।।

तेन वाक्येन तुष्टौसौ बलभद्र समन्वितः।

गत्वा तत्र रणं कृत्वानिहत्य चेदिदं नृपं।। 440 ।।

रुक्मिणीं तु समानीय परणीय स्वयं वने।

कृताग्रमहिपीतेन नीत्वा द्वारावतीं पुरीं।। 441 ।।

तयोस्त्वं तनयोजाताः सर्वावयव सुन्दरः।

रात्रौ त्वं पूर्व दैत्येन नीतोवैपूर्व दोषतः।। 442 ।।

ततो सौ मदनः प्रोचे मुनिं प्रविनयान्वितः।

केन पापेन जातोयं जनन्य विरहोमम।। 443 ।।

यतिर्ज्जगाद हे वत्स न तच्चापातकं तव।

जनन्याः पातंक विद्विपुरा जन्मनि तत्कृतं।। 444 ।।

तयाब्राह्मण पु=या तु लक्ष्मीवत्याभिधानयाः।

एकदा षिखिनो बालं कौतुकेन वियोजितं।। 445 ।।

घटीषोडष पर्यन्तं स्थापितं तं सुखेन हि।

पश्चात् तस्य जनान्यैतं दत्तं बालं तु पुण्यतः।। 446 ।।

तेन पापफलेनायं वियोगस्तवचाभवत्।

जनन्याः पूर्वपापेन पापं भव्यं न कुत्रचित् ।। 447 ।।

तावन्त्येवच वर्षाणि जातानीहात्र पापतः।

अत्त एव वियोगेहिन कार्यः केन कस्यचित्।। 448 ।।

धर्माधर्म फलं वत्स ज्ञात्वैवं निजमानसे।

पापं दूरेण संत्यज्य धर्म एव विधीयते।। 449 ।।

इतिश्रुत्वा मुनेर्वाक्यं नत्वास्य चरणांबुजं।

प्रमोदेन जगामासौ जनन्यामन्दिरं वरं।। 450 ।।

प्रणामरहितस्तत्रगतः ममात्रभवितं नूनं करिष्यति न संषयं।। 451 ।।

चिंतयित्वेतिचित्ते सा जगाद मदनं प्रति।

शृणुकाम महाभाग मम वाक्यं मनोहरं।। 452 ।।

यदिमद्वचनं रम्यं कुरुषे त्वं मनोहरं।

रोहिण्यादि समस्तंहिदास्येमंत्रगणं तव।। 453 ।।

तदा जगाद मदनो हास्यं त्वा कनकस्रजां।

अद्यप्रभृति ते वाक्यं किं कदा न कृतं मया।। 454 ।।

यदेवं भाषसे नूनं मादरेण समन्विता।

सर्वदा तव दासोस्मि करोमि भणितं तथा।। 455 ।।

एतएव कृपां कृत्वा देहिमंत्रगणं मम।

मांदेह्यथात्रवावष्यं करोमि तव भाषितं।। 456 ।।

तेन वाक्येन तुष्टासा जगाम मदनं प्रति।

गृहाणविधिपूर्वेहि मन्त्र राषिर्मियां वरां।। 457 ।।

इत्युक्त्वा सा ददौ तस्मै मदना यमुदान्विता।

मंत्रराषिं महा प्रीत्या मूढ़ाकामाकुला सति।। 458 ।।

बुध्वाविद्यागणं सोपि तयोक्तं विधि पूर्वकं।

सन्तोषं परमं प्राप्य जगाद वचनं च तां।। 459 ।।

शृणुपुण्यपरं योग्ये मम वाक्ये मनोहरं।

यदाहं रिपुणा नीत्वा निहितो गिरिकंदरे।। 460 ।।

तदा न शरणं तातो न जाता जननी मम।

शरणं त्वं मे जातासि नापरा शरणं मम।। 461 ।।

अतस्त्वमेव मे नूनं जनको जननी तथा।

पुत्रस्य यच्च कर्त्तव्यं तन्निवेदय साम्प्रतं।। 462 ।।

एवं वाक्य समाकर्ण्य वज्रपात समं तु सा।

वलानाय स्वयं नूनमुद्यतावै यदा तदा।। 463 ।।

मदनोपि स्वयं नत्वा जगाम जिन मन्दिरं ।

तदास्वं वंचितं ज्ञात्वा चिन्ताकर्त्तुं समुद्यता।। 464 ।।

किं करोमि हताषाहं तेन पापेनवचिता।

नीतं मन्त्रगणं सर्वं कथितं न कृतममं।। 465 ।।

येनकेनाप्युपायेन कर्त्तव्यो निग्रहो मया।

अस्य पापस्यष्टस्य मम वचन कारिणः।। 466 ।।

विमृष्यैवं चिरं चित्ते विदार्यकरजैर्निजं।

वयुष्चवदन चैव कुचयोर्युगलं तथा। 467 ।।

कुन्तलान् विरलान् कृत्वा धूलिधूसरितांस्तथा।

नेत्रयोः कज्जलैः कृष्णं विधाय मुखपंकजं।। 468 ।।

रुदित्वा दुःख संपूर्णा समागत्य नृपं प्रति।

दुःख गद्‌गदया वाचा जगाद विनयानता।। 469 ।।

श्रृणुनाथ महाभाग तेन पापेन यत्कृतं।

पालनाय त्वया दत्तो वनेयोविजने मम।। 470 ।।

मयापिपुत्र प्रीत्यासौ वर्द्धितो बालकोमुदा।

त्वयापि मम वाक्येन युवराज्य पदे कृतः।। 471 ।।

स पापी मम रूपं हि दृष्टवा यौवन भूषितं।

मदनेन समाक्रान्तचकारेदं कुचेष्टितः।। 472 ।।

नूनं नीच कुले सोवै समुत्यन्नोति दुष्ट धीः।

अन्यथा पापजां बुद्धिं जननीं कुरुते कथं।। 473 ।।

वलितोदुष्टबुद्धिष्च समागत्यात्र दुर्ज्जयः।

दारिताहं शरीरेहितनैवन खरैः खरैः।। 474 ।।

तव पुण्य प्रभावेन मागोत्रदेव्याः प्रसादतः।

शीलं मे रक्षितं नाथ मया भाग्यवषान्मम।। 475 ।।

यदि स्यात् शील भंगं मे पूर्व पाप प्रभावतः।

तदा भविष्यन्मरणं किं कलंकेन जीवितं।। 476 ।।

मत्वपित्व कुलेनाथ यदि स्याच्च कलंकता।

तदा किं जीवतव्येन वंषत्रय कलंकिना।। 477 ।।

कथंचित्पुण्ययोगेन तस्याहं बहुपंजरात्।

रजसादिग्ध सर्वांगानिसृताचाकुला सती।। 478 ।।

यदि पश्यतामि तस्यैव रुधिरावलितं षिराः।

लुठमानं ध्रुवं भूमौ तदा मे जीवितं प्रमा।। 479 ।।

नार्योदितं समाकर्ण्य कालसंवर भूपतिः।

सर्वान् पुत्रान् समाहूय जगावेकांततस्तदा।। 480 ।।

श्रृणुं तु मम वाक्यं हि पुत्रासर्वेपि सादरं।

एतं मदन नामानं पापं चैमार्यतां द्रुतं।। 481 ।।

एतं नीच कुलोत्पन्नमानीतं तु वनांतरात्।

केनजातं न जानामिं वर्द्धितं कृपया मया।। 482 ।।

अधुना यौवनं प्राप्य युष्माकं कीर्त्तिघातकः।

भवदि्भष्च वने गत्वा रथारूढ़ समागतः।। 483 ।।

भवंतपाद चारेणागच्छन्तोपि मया यदा।

तदापि मम चित्तात्सध्रुवं मुत्तरितः शठः।। 484 ।।

यथा को न जानाति मारणीयंस्तथाह्वयं।

इति तात वचः श्रुत्वा ते हर्षं परमं गताः।। 485 ।।

पूर्वं तु हंतु कामाहि वयं तस्यैव पापिनः।

किं पुनः पितुरादेषं संप्राप्ताः पुण्ययोगतः।। 486 ।।

प्रणम्य पितरं वेगात् निःसृता भ्रातरोखिलाः।

लोकापवाद नाषाय सर्वेपि मदनं जगुः।। 487 ।।

क्रीडार्थं तु वयं नूनं गच्छामी जलवापिकां।

तवात्रकथनार्थं हि समायाताः सुमोहतः।। 488 ।।

अस्माकं तव तुल्योहिनापरो विद्यते प्रियः।

तेन वाक्येन तुष्टोसौ निसृतस्तैः समन्विताः।। 489 ।।

पुर बाह्येगताः सर्वे जलस्य वापिकां द्रुतं।

तस्याः समीपमासाद्य तेन हर्षे समन्विताः।। 490 ।।

मुक्त्वावस्त्राणि सर्वाणि परिधायान्य वस्त्रकं।

तटस्थं चटिता वृक्षं पतितुं जल वापिकां।। 491 ।।

तावत् तत्र समागत्य मदनस्यापि पुण्यतः।

विद्ययाश्रवणे चास्य गलित्वा कथितं हितं।। 492 ।।

श्रृणु वत्स महाभाग मदीयं वचनं शुभं।

एते तु हंतुकामाहि पापास्त्रंवा वैरभावतः।। 493 ।।

अतएव जले स्नानं वापिकाया त्वया ध्रुवं ।

मद्वाक्यानैव कर्त्तव्यं तवाहं हितकांक्षिणीं।। 494 ।।

तद्विद्याया वचः श्रुत्वा मदनष्चकितो हृदि।

निजं रूपं विधायान्य द्विद्यायाष्च समुद्भवं।। 495 ।।

स्वयमदृष्यतो भूत्वा स्थितोसौ वापिका तटे।

यच्च विद्यामयं रूपं चटित्वाथ नगोपरि।। 496 ।।

बुंबापातं परं कृत्वा पपात वापिका जले।

पतितं मदनं दृष्ट्वा सर्वे ते खेचरांगजाः।। 497 ।।

नीयतां नीयतां वेगात्यापिनं मार्यताद्रुतं।

चंप्यतां युगपत्सर्वेरित्युक्त्वा पतितास्तथा।। 498 ।।

लवमाना यदासर्वे युगपत्पतिता जले।

तदासौमदनः क्रुद्धो विस्मयाच्च विचिंतयत्।। 499 ।।

किं वा कारणमुद्दिष्य मारणाय ममोद्यताः।

तातादेषेन किं त्वेते किं वादेष विनापि हि।। 500 ।।

पातिन्या तु तया मात्रा पितृरग्रेविरूपकं।

असत्यासत्य वाक्ये हिं कथितं वै भविष्यति।। 501 ।।

तेन वाक्येन रूष्टेन तातेनापिहि कोपतः।

आहूय च निजं पुत्रान् कथितं तु भविष्यति।। 502 ।।

एते तु तात वाक्येन कुर्वन्ति मम मारणं।

अतएव दुराचान्मारयामि विषंसयं।। 503 ।।

चिंतयित्वाति चित्तेसौ समानीय वृहत् षिलां।

स्वविद्यायाः प्रभावेन वापिकायाः प्रमाणिकां।। 504 ।।

पिदधेदृषदा तेन वापिकां गुरूकोपतः।

उर्द्धंपादाष्च तान् सर्वान् अधोवक्ताचानविलंबयन्।। 505 ।।

एकं तु मोचयामास कथनीय महीपते।

तं प्रत्युक्तं मनोजेन याहित्वं पितुरंतिकं।। 506 ।।

त्वं निवेदयतस्याग्रे यन्मया निर्मितं ध्रुवं।

तेन गत्वा तथा चोक्तं यत्कृतं मदनं नवै।। 507 ।।

पुत्रांस्तान् पिहितान् श्रुत्वा दृषदावापिकाजले।

कोपेन ज्वलितो राजा कालसंवर संज्ञिकः।। 508 ।।

स्वयमुत्थाय वेगेन चलिता मदनं यदा।

मारणायाति कोपन खङ्गं नीत्वा करे निजे।। 509 ।।

आमात्यस्तु तदा प्रोक्तं नाथ गन्तुं न युज्यते।

येनप×चषता पुत्रान् बद्धान्वै वापिका जले।। 510 ।।

लाभैष्च विविधैर्युक्तः सकथं जीयते त्वया।

अतएव महासौन्यं मेलयित्वा हि गम्यते।। 511 ।।

आमात्याहितां वाक्येन रणभेंरी प्रदाय च।

मेलयित्वा महत् सैन्यं निर्ययौभूपतिस्तदा।। 512 ।।

भ्रातृनुल्लंध्य वेगेन वापिकाया वरंडके।

तस्थौ चाधोमुखो भूत्वा मदनोलज्जयाकुलः।। 513 ।।

चतुरंग बलोपेतः पुरमध्याद्विनिर्ययौ।

निर्गच्छन्तं ततो दृष्ट्वा तातं तु मदनोबली।। 514 ।।

चिन्तयामास चित्ते साम्रहो तातस्य मूढ़ता।

रंडाया वाक्यतो नूनं प्रारब्धं मम मारणं।। 515 ।।

एवं विचिंत्यमानेथ निर्गतः पुरमध्यतः।

मार्ग स्थान् गिरिनाथांष्चदलयन् रथकद्यया।। 516 ।।

तुरंग खुरथातोत्थ समपद्रजमूर्ज्जितं।

गजदानसमूहेन कोप युक्तो नराधिपः।। 517 ।।

पदांतीनां समूहेन स्थागयन् सकलांधरां।

सैन्येन हतायुक्तो निर्गतौ बहि भूपति।। 518 ।।

वाजित्राणां निनादेन गजानां गर्ज्जनैः तथा।

स्थानां चापि चीत्कारैर्हयानांहेषतैर्वरै।। 519 ।।

धनुषां चापि विस्फारैः र्भटानामट्टहासकै।

व्यथितानिधनंतानिकर्णयो विवराणि च।। 520 ।।

एवं विधं महोटोपं सैन्यं व्याप्त दिगन्तर।

दृष्ट्वाथमदनः स्मित्वासस्मरनिज देवतान्।। 521 ।।

तथैव बंदिनां शब्दा वाजित्राणां तथैवहि।

संघट्टसैन्ययोस्तत्र तदा भूत्क्रोध युक्तयो।। 522 ।।

गजागजैः समंलना वाजिनो वाजिभिः सहः।

रथौघाष्च रथैः सार्द्धं पत्तयः पत्तिभिः समं।। 523 ।।

अतियुद्धं तु संजातं सैन्ययोर्दारुणं यदा।

गगने हि तदा यातो नानर्त्तनारदोमुदा।। 524 ।।

कालसंवर सैन्येन मदनस्य बलं हठात्।

त्रासितं चाति वेगेन लग्नं तु तत् पलायितुं।। 525 ।।

पलायमानं सैन्यं तु दृष्ट्वा चासौ मनोभवः।

अंजनाचलसंकरौर्गजानां निचहैर्युतः।। 526 ।।

सन्मुक्तं क्रोध संयुक्तष्चचालबलसंयुतः।

एवं विविध संघातैर्वर्षन् वर्षोपमोबला।। 527 ।।

कालसंवर भूपस्य भंगं नीतं तदाबलं।

गजानां चापि संघाता गजानां विवहैर्हता।। 528 ।।

वाजिनां निवहास्तत्र हतास्ते निजवाजिभिः।

रथैः रथाः परं भग्ना योधैर्योधा निपातिता।। 529 ।।

एवं तु सकलं सैन्यं मदनेन निपातितं।

कालसंवर भूपालष्चिंतयामास मानसे।। 530 ।।

दुर्ज्जयोयं रिपुंर्नूनं गर्जत्यग्रेतु संस्थितः।

कथं येष्या दुष्टैनमुपायं किं करोम्यहं।। 531 ।।

चिंतित्माने समुत्पन्ना बुद्धि रे का महीपतेः।

ममभार्या समीपे हि विद्यते विद्यकाद्धयं।। 532 ।।

तत्समानीय जेष्यामि शत्रुं चात्यंत दुर्ज्जयं।

विमृष्यैवं चिरंचित्ते सचिवं तु जगौ तदा।। 533 ।।

श्रृणुमात्य महबुद्धः मदीयं वचनं शुभं।

क्षणमेकं प्रयुद्धस्वत्वमनेन वलीय सा। 534 ।।

अहं गत्वा तु नगरे भार्यायाः तु समीपतः।

विद्या द्वयं समानीय शत्रुं जेष्यामि वेगतः।। 535 ।।

तदा तु मन्त्रिणा प्रोक्तं गम्यतां गम्यता द्रुतं।

तावत्करोमि युद्धं हि मदनेन समंत्वहं।। 536 ।।

युद्धे संस्थाप्य सचिवं समं तेन वलीयसा।

शीघ्रं गत्वा निषान्ते सौभार्यां प्रोचेल्यमानसः।। 537 ।।

स्त्रीचरित्र ततः कृत्वा रूरोदपुरतो नृपः।

तां रूदन्ती समालोक्य ज्ञातं भूपतिना हृदि।। 538 ।।

अनद्याविभवारिण्या दत्ते विद्येनसंषयं।

विमृष्यैवं तदा प्रोक्तं कथं रोदिषिभामिनि।। 539 ।।

देहि शीघ्रतरं विद्ये दुर्ययोसौ रिपुबली।

विद्ययोष्च प्रभावेन मारयामि क्षणादहं।। 540 ।।

ततो गदगदकंठा सा जगाद स्वामिनं प्रति।

रुदन्ती च अश्रुपातं हि कुर्वन्ती मूढ़ मानसा।। 541 ।।

नाथ पापेन ते नाहंनैकधा वंचिताविसो।

तस्य दुष्ट्स्य वार्त्तापि कथितुं नैवयुज्यते।। 542 ।।

एकदां कथितं बालं दृष्ट्वा तं चिंतितं मया।

आवयोर्ननु बालोयं वृद्धत्वे पालयिष्यति।। 543 ।।

विमृष्यैवं तु मोहेन मया विमुग्धचित्तया।

स्तन्यमध्ये तु संक्षिप्यपायिकः विद्यकाद्वयं।। 544 ।।

ईहग्विधोप्ययं पापी भविष्यति सुयौवनैः।

नैवं ज्ञातं मया नाथ मूढ़या मुग्धचित्तया।। 545 ।।

अतोभ्रष्टा ततो भ्रष्टा किं करोमि हताषिका।

वंचिता बहुधा तेन पापिना निर्विवेकिना।। 546 ।।

इत्युक्त्वा रूदितं लग्नामुक्त कंठं खला यदा।

तदा भूपतिना तस्या ज्ञातं दुष्चरितं ध्रुवं।। 547 ।।

कालसंवर भूपेन श्रुत्वा वाक्यं स्त्रियोदितं।

कंपितं स्वषिरस्तावत् चिंतितं तु स्वमानसे।। 548 ।।

अहो दुष्चरितं स्त्रीणां शक्यते केन वर्णितुं।

विद्याद्वयं च पुत्रस्तु त्रितयं नाषितं मम।। 549 ।।

अधुना जीवितेनापि नास्ति नूनं प्रयोजनं।

गत्वा तत् समुखं शीघ्रं म्रियते संषयं विना।। 550 ।।

एवं विमृष्य निस्वस्य निर्ययौगेहतो नृपः।

रणांगणं समासाद्य प्रोवाचैवं मनोभवं।। 551 ।।

तवकोषस्थिता बाणं मुंच शीघ्रं तु मां प्रति।

मारयामिकथं बालं रणमूढं दुरात्मकं।। 552 ।।

ततोपिमदनः प्रोचे श्रृणु तात वचो मम।

नारी वाक्यरतं मूढं तातं तुमार्यते कथं।। 553 ।।

अतस्त्वं प्रथमंमुचपष्चान्मम दूषणं नहि।

इत्युक्ते क्रोधयुक्तेन कालसंवर भूपति।। 554 ।।

बाणंमुमेच मदनं कृत्वा धनुखवेगतः।

दिव्येष्चापि हि सा मानैर्युयुधाते बलोद्धते।। 555 ।।

कालसंवर भूपेन बाणं मुक्त्वाति वेगतः।

मनोभव कुमारस्य रथं वेगादभोजि च।। 556 ।।

रथं भग्नं समालोक्य ततोपि मकरध्वजः।

गुणंचात्मसमं चक्रे मुक्त्वा बाणं सुवेगनां।। 557 ।।

पुनस्तु नागपाषेन बधयित्वाति वेगतः।

नीत्वात्मनः समीपेतं पितरं मुग्धमानसं।। 558 ।।

किंचित् नम्र मुखष्चक्रे चिंतां लज्जां समाकुलः।

मायायुधः प्रभावेन सैन्यं तु पातितं रणे।। 559 ।।

अधुनाकोपि वेगेन समागत्य नरोत्तमः।

मुंचपि यति मे तातं भव्यं भवति नान्यथा।। 560 ।।

एवं विमृष्यमानोस्मिन् प्रनृत्य गगनांगणे।

नरदोत्र समायातो हर्ष पूरित मानसः।। 561 ।।

अद्य भव्यं तु संजातं यदस्य जनकेनहि।

विरोधः परमोजातोधुनायं तु समेष्यति।। 562 ।।

आशीर्वादं तु सद्वाक्यैः दत्वासौनारदोमुनिः।

किमत्रसमरं जातं जानन्नपि जगाविदं।। 563 ।।

तस्य वाक्यं समाकर्ण्य मदनोपि मुनिं जगौ।

श्रृणुनाथ महाभाग मदीयं वचनं विभो।। 564 ।।

जनन्या वाक्यतो नूनं तातेनापि विरूपकं।

चिंतितं मम बालस्य मारणं लोकगर्हितं।। 565 ।।

जनन्याष्चरितं सर्वे नारदाय निवेदितं।

श्रूयमानेपिपितरि मदनेनापि लज्जया।। 566 ।।

पिहितौश्रवणौ वेगान्नारदो निजौ तदा।

वैधूयमस्तकं चापि संमील्य नयन द्वयं।। 567 ।।

वत्स मुंच जगन्निंद्यां वार्त्तानीचजनोनुगां।

स्त्रीणां हि पापचित्तानां चरितं केन वर्ण्यते।। 568 ।।

चक्रवाक समं प्रीत्या स्वामिन् प्राणवल्लभं।

पितरं मातरं पुत्रमनुजं च गुरूं तथा।। 569 ।।

मरणं प्रापयत्येव कुपिता दुष्टनारिका।

तत्रान्यमनुजेष्ठेवं का कथा दुष्टयोषितः।। 570 ।।

नारदोक्तं वचः श्रुत्वा जगावेवं मनोभवः।

श्रृणु नारद मद्वाक्यं पितृभ्यां वर्ज्जितोस्म्यहं।। 571 ।।

भविष्यामि कथं चाहं गमिष्यामि चक्रं प्रति।

दर्षयत्वं ममोपायं जीवनस्य महामते।। 572 ।।

कालसंवर भूपोयं निष्चितं जनको मम।

पयः पानकरी नूनं माता तु कनकस्रजा।। 573 ।।

एताभ्यामीदृषं कर्म निर्मितं मम साम्प्रतं।

तत्र क्वाहं गमिष्यामि यतः शरणवर्ज्जितः।। 574 ।।

नारदोपि समाकर्ण्य वचनं मदनस्य हि।

जगाद वचनं रम्यं शृणु वत्स ममोदितं।। 575 ।।

माकृथा त्वं वृथा दुःखं यदहं बंधु वर्ज्जितः।

बांधवा बहवः सन्ति तद् वृत्तान्तं निरूप्यते।। 576 ।।

द्वारिकायाः पति नूनं केषवोनामचक्रभृत्।

हरिवंषाभिधेवंषेयादवानां षिरोमणिः।। 577 ।।

भर्त्तुः प्राण समाना हि जननी रूक्मिणी तव।

रूपलावण्य संयुक्ता गुणानामनघालया।। 578 ।।

तयानेतुं तवांतेहं प्रेषितोस्मि महादरात्।

तत्रास्ति कारणं किंचिदयरंवच्मितेधुना।। 579 ।।

सत्यभामाभिधाना हि तव मातुः सपत्निका।

तया सह विरोधोस्ति नितांतं हे मनोभव्।। 580 ।।

अतएव मया सार्द्धं युक्तमागमनं तव।

मदनोपि समाकर्ण्य स्वस्य वंषस्य सत्कथा।। 581 ।।

प्रमोदं परमं प्राप्य नारदं प्रति प्रीतिधीः।

मुनिनायत्पुरा प्रोक्तं तदेव चिंतयन् मुहु।। 582 ।।

स्वस्य वंषस्य योग्यत्वं प्रधानत्वंमहर्ध्यता।

समाकर्ण्याथ कस्यापि संतोषोनैव जायते।। 583 ।।

नारदस्यैव वाक्येन मुमोच पितरं निजं।

उत्थाप्य सकलं सैन्यं पुण्यवान् पापवर्ज्जितः ।। 584 ।।

उत्थाप्यतो ते भटास्तावत् कुर्वन्तो दुःसहरवं।

गृÉातु मारयंते वनं पापिनं दुर्ज्जयं रिपुं।। 585 ।।

तदा तु नारदेनोक्तं भो भो योद्धा महाभटाः।

ज्ञातंपराक्रम नूनं सर्वेषां च संयुगे।। 586 ।।

व्रजं तु पुर मध्ये हि कुषलेन महाभटाः।

दत्तं तु भवतां नूनं जीवदानं स्मरेण हि।। 587 ।।

ज्ञात्वा सर्वं तु वृत्तान्तं सर्वेपि सुभटास्तदा।

चतुरंग बलोपेतं प्रयाता नगरं निजं।। 588 ।।

कालसंवर भूपोपि लज्जया कुलमानसः।

न किंचित् नारदं प्रोचे न प्रोचे मदनं प्रति।

कालसंवर भूपोति लज्जया कुलमानसः।

न किंचित् नारदं प्रोचे न प्रोचे मदनं प्रति।। 589 ।।

दीनोम्लानमुखो भूत्वा जगाम नगरं तदा।

गत्वा तु वल्लभां प्रोचेन किंचित् दूषणं तव।। 590 ।।

तत्पुरा निर्मितं कर्मं तदेव प्राप्यते ननु।

अतोदुःखं कः कर्त्तव्यं न प्रमोदं तु कारयेत्।। 591 ।।

इतितौ मन्दिरे यावत् स्थितौ चिंता समन्वितौ।

तावत् ते भ्रातरः सर्वे वापिका जलमध्यतः ।। 292 ।।

मुक्त्वा वेगेन कामेन दया पूरित चेतसा।

तेपिदानागताः सर्वेपुरे गर्व विविर्जिताः।। 593 ।।

तदा नगर लोकैस्तु ज्ञातं देव्या विचेष्टितं।

सर्वत्र प्रकटं प्राप्यमिति लोका वदंति हि।। 594 ।।

पापिनां न जयः क्वापि धर्मिनां तु जयः सदा।

अतएव नरैर्भव्यैस्त्याज्यं दूरेण पातकं।। 595 ।।

पुण्यस्यैव प्रभावेन मुखं देवनरोत्तमः।

प्राप्यते प्राणिना नूनं कार्यंर्भव्यैरतोवृषं।। 596 ।।

हेयं पापं प्राणिभिः सर्वदा वै किं किं दुःखं पापतो जायतेन।

तस्मात्पुण्यं सोम सौम्यं हि कार्यं पुण्या सौख्यं प्राप्यते भव्यजीवैः।। 597 ।।

लब्धा लाभ विषद फलदान् शत्रुनीतो विदेषे

प्रज्ञप्त्याख्यां भुवन विदितां रोहिणींचापि विद्यां।

भ्रातृन् बद्धारिपुगणमिमं संगरे चापि जित्वा।

पुण्यात् नूनं सुरमुनियुतो मन्मथोभात्तदानीं।। 598 ।।

***इत्याचार्य श्रीसोमकीर्त्तिविरचिते प्रद्युम्नचरित्रे षोडशविद्यालाभप्राप्ति पित्वबंधुजनविरोधनारदगमनो नाम**

नवमोसर्गः *

दशमसर्गः

अथात्र नारदेनोक्तं मदनं प्रति सुन्दरं।

कालक्षेयं विना वत्स द्वारिकायां तु गम्यते।। 01 ।।

तदा तु मदनः प्रोचे कृतज्ञो नारदं प्रति।

पितरौ चाप्यनापृछ्य मम गंतुं न युज्यते।। 02 ।।

अत्र तिष्ठ त्वमेवात्र पुरे चातो व्रजाम्यहं।

आपृछ्य पितरौ तत्र पुनरेमितवांतिकं।। 03 ।।

इत्युक्त्वा नारदमुक्त्वा गतोसौ मदनोबली।

जनन्याः सहितो यत्र भूपः तिष्ठति दुःखितः।। 04 ।।

तत्रगत्वा च तौ नत्वा जगावैवं मनोभवः।

श्रूणु तात महाभाग मदीयं वचनं शुभं।। 05 ।।

मया ज्ञान तयायच्च निर्मितं च दुर्निष्टतं।

क्षमस्व तत् कृपां कृत्वा मूढ़स्य पापमानसः।। 06 ।।

अतः परं तु मूर्खं त्वं मम किं कथ्यतेधुना।

निजमातरियष्चैवं विधं पापं विचिन्तयेत्।। 07 ।।

ये दीनाये तुनिर्नाथोपराधीनात्वया ध्रुवं।

तेषा साधुजना नूनं न कुप्यंति कदाचन।। 08 ।।

तवाहं किंकरो नाथ त्वया जीवापितोस्म्यहं।

त्वयाहं वर्द्धितो नूनं त्वत्तो जीवामि साम्प्रतं।। 09 ।।

ममोपरिकृपां कृत्वा क्षमस्व मम पातकं।

माता त्वं मम बालस्य क्षमस्व पापकारणं।। 10 ।।

गच्छाम्यहं पितुर्गेहं मिलनार्थं तवाज्ञया।

आदेषं देहि हे नाथ विनादेषं न गम्यते।। 11 ।।

स्मरणीयस्त्वया नाथ प्रतिहं बालकस्तव।

मिलित्वा पितरौ तत्र वेगादागम्यते मया।। 12 ।।

रक्षणीयस्त्वया तात विभागोमम सर्वदा।

स्थीयते तु मया नाथनूनमत्रैव प्रत्यहं।। 13 ।।

प्रसाद क्रियतां मात मयि भृत्ये सदैव हि।

अपत्यास्तु कुपत्या वा मातरो न कुमातर।। 14 ।।

इति प्रसिद्धिं सर्वत्र भुवने सकले बिके।

कोपं तु कुरू मां मात कोवात्र परतन्त्रके ।। 15 ।।

ज्ञातव्यं वै त्वयाचित्ते ममोदर समुद्भवं।

अन्तरं न त्वया गण्यं तव पुत्रो न संषयं।। 16 ।।

एवं प्रजल्यमानेपितौ हि चाधोमुखौ तदा।

न किंचिदूचतुर्वाक्यं लज्जया कुलमानसौ।। 17 ।।

तथा स पितरौ नत्वा विनयेन पुनः पुनः।

भातृन् स्वजनः वर्गं च सचिवांष्च तथौवहि।। 18 ।।

पुनः पुनस्तु संतोष्य प्रणम्य मोह संयुतः।

निर्जगाम पुरात्कामस्तूयमानो जेनैस्तदा।। 19 ।।

नारदांते समागत्य प्रणमैवं जगाद सः।

द्वारिका हि कियत् दूरेता तातः कथ्यतां मम।। 20 ।।

अयं विद्याधराः खंडः सा तु मानुषगोचरा।

एवं तु नारदेनोक्तं वचनं मदनं प्रति।। 21 ।।

तदाकर्ण्य जगावेवं मदनो विनयान्वितः।

कथवागम्यते तात दूरे सा नगरी यदि।। 22 ।।

तदा तु नारदः प्राह श्रृणु वत्स वचोवरं।

नेष्यामि तत्र वेगेन विमानेना शुगामिन्ना ।। 23 ।।

इतिनारदवचः श्रुत्वा जगाद मदनोबली।

सज्जतां सज्जतां तात विमानं वेगगामिनं।। 24 ।।

तेन वाक्येन तुष्टोसौ विषालं ललितं शुभं।

जगाद मदनं कृत्वा विमानं वेगगामिनं।। 25 ।।

आरोहय द्रुतं वत्स विमानं तव योग्यकं।

यत्रारूढ़ो गमिष्यावो जनन्यास्तवसन्निधिं।। 26 ।।

तुष्टो नारद वाक्येन प्रोवाचेवं मनोभवः।

वर्त्तते हि क्षमं तात विमानमुपविष्यने।। 27 ।।

ततोपि नारदो स्मित्वा जगाद मदनं प्रति।

बाढ़मस्ति समर्थं हि त्वमारोहय सत्वरं।। 28 ।।

तेन वाक्येन कामेन दत्ते पादेपिवेगतः।

त्रुटिताखिलसंधिस्तु जातं छिद्रषतैर्युतं।। 29 ।।

इति कृत्वा जगौ काम नारदंनयपेषलः।

साधु साधु भवात् नूनं षिल्पविद्याविषारदः।। 30 ।।

कस्य पार्ष्वे त्वयाभ्यस्तं विज्ञानमीदृषं विभो।

सदृषस्तवलोकेस्मिन्नूनं भूतो न भविष्यति।। 31 ।।

मायात्र प्रभृतिर्ज्ञातं नारदस्य समोभुवि।

विज्ञानी विद्यते नैव युक्तो विद्याबलेन हि।। 32 ।।

ऋषिस्तु लज्जितो भूत्वा जगाद वचनं सुधीः।

जरयाधिक देहस्य निपुणत्वं कुतो मम ।। 33 ।।

कुषलः सर्वविद्यासु सर्वविज्ञान कोविदः।

नवयौवन सम्पन्नो भवान्नकुरूषे कथं ।। 34 ।।

विमानं कुरू वत्स त्वमतोवेगाच्च गम्यते।

सुधी किं कालक्षेपोयं जननी तव दुखिता।। 35 ।।

व्रतिनो वचनादेव कामो विस्मय कारकं।

विमानं विदधेनूगाद्यषो राषिमिवात्मनः।। 36 ।।

लंबमान महाघंट मुछित ध्वज संकुलं।

पंचवर्णं परं रत्नस्तत्र निर्मित कूटकं।। 37 ।।

सर्वं कटि तटी पीठं कांचनेन तु निर्मितं।

वापिकादीर्धिकादीनां तडागानां तथैवहि।। 38 ।।

समूहैः कृत शोभन्ते हंस कोकैः समन्वितं।

कदलीपूगतालादि तरू वृंदैरलंकृतं।। 39 ।।

चामराणां समूहैष्च छत्राणां निवहैर्युतं।

गवाक्षादि प्रवेसैष्च स्वर्ग लोक मिवापरं।। 40 ।।

निर्माय सुन्दरं लोके विमानं वेग गामिनं।

जगाद नारदं कामः सर्वविज्ञानकोविद।। 41 ।।

योग्यं भवति तेतातदातुरोहय सत्वरं।

बाला ज्ञान तया नूनं विमानं निर्मितं मया।। 42 ।।

इत्युक्ते नारदो दृष्ट्वा विमानं चातिसुन्दरं।

दुःप्राप्यं पुण्यहीनानां विस्मयं परमं गतः।। 43 ।।

मदनेन समं सोपि विमानं सह रूढ़वान्।

मन्दं मन्दं हि कामेन गगनथेचटापितं।। 44 ।।

विलंवित गतिर्जातः कामोसौ कुटिलाषयः।

विलंबिनंतमालोक्य नारदः प्राह मन्मथं।। 45 ।।

त्वद्वियोगहिमाक्रान्तं जनन्या मुखपंकजं।

त्वमादित्य समोगत्वा दह्यमानं निवारय।। 46 ।।

त्वं सा धारय वेगेन मातरं तव दुखितां।

जनन्यास्तव दुःखं हि त्वयि पुत्रे कथं सति।। 47 ।।

एवं नारद वाक्यं हि श्रुत्वा चासौ मनोभवः।

विमानं चालयामास गगने वेगवत्तरं ।। 48 ।।

चक्रे सौक्रीडयातं हि नारदं परमाकुलं।

विस्वंस्थल जटा भारं कम्पमान शरीरकं।। 49 ।।

भग्ने तु कूपरे तस्य मुखं दन्तास्तथैवहि।

प्रोच्यमाने तदा तस्मिन् जिàायाति च खंडतां।। 50 ।।

ज्येष्ठ मासे तथा नूनं सागरे वाहनानि हि।

तथा कुलोतिकोपेन जगाद मकरध्वजः।। 51 ।।

वत्स वत्स महाभाग श्रृणुवाकां मयोदितं।

मां त्वं चात्र विमानस्थमाकुलं कुरूषे कथं।। 52 ।।

त्वमानन्देन पूर्णोसि स्नेह भार वषीकृतः।

उत्कंठया परं युक्तो जननी जनकं प्रति।। 53 ।।

रूक्मिणी मम पुत्री च सततं चाति वत्सला।

तव तातोपि मे नूनं परां भक्ति वितन्यते।। 54 ।।

यादवैः सकलैष्चापि पूज्यमानोस्मि सर्वदा।

मां त्वं समाकुलं किं हि कुरुषे कृपयोष्चितः।। 55 ।।

एवं तस्य वचः श्रुत्वा मदनो नारदं जगौ।

ज्ञातं त्वच्चरितं तात कुटिलत्वेन संयुतं।। 56 ।।

तवायातो नरोचहं शीघ्रं तु गमन मम।

तवात्र रूचितं नैव ना गमिष्यामि त्वं व्रज।। 57 ।।

इत्युक्त्वास्तं भयामास विमानं गगनांगणे।

कोपस्थेप्यस्व चित्तेसौ जगाद मदनं मुनिः।। 58 ।।

खेटलोक निवासं हि त्वया त्यक्तु न शक्यते।

अतो विलम्बं कुरूषे नूनं मपि समागते।। 59 ।।

यदि ते जननी वत्स गतास्यात् च पराभवं।

पश्चात्वयि गतेनापि नास्तिकं चित्प्रयोजनं।। 60 ।।

श्रृणु चान्यद्वचो वत्स प्रोच्यते तु तवाग्रतः।

नास्ति तमात्रिकाभीष्टा तथापि कथयाम्यहं।। 61 ।।

वहवः कन्यका रम्याः पितृभ्यां याचिताः पुर।

त्वदर्थमधुना सर्वाः परिणेष्यति तेनुजः।। 62 ।।

परिणीतासुकन्यासु गतेनापि ततोत्र किं।

इति श्रोत्रहरं वाक्यं श्रुत्वा चासौ मनोभवः।। 63 ।।

चचालवायुवेगेनर्णव तरंग चंचलैः।

कुर्ध्वैस्तु केतनै रम्यैर्विमानेन युतो युवां।। 64 ।।

गगनेथ विमानेपि चलितेनापि सत्वरं।

चरितं मार्गजं रम्यं किंचित् श्रेणिक वर्ण्यते।। 65 ।।

मार्गेस्वपुर नारीणां नयनोत्सव कारणं।

विकचास्येन हर्षाच्च नारदेनापि शोभितं।। 66 ।।

खेचराणां धराधीषं लंघयित्वाति वेगतः।

ददृषतुर्द्धरापीठं तौ मनोभव नारदौ।। 67 ।।

आकुलं वनजालेन सुरसिन्धु नगव्रजैः।

पश्यंतौ तौ क्रमेसौवं व्रजंतौ गगनांगणे।। 68 ।।

तावत् व्योम स्थितेनापि नारदेन निरीक्षिता।

अटवी खदिराभिख्या वृक्षवृंदैः समन्विता।। 69 ।।

गिरितक्षकेनाम्नि यत्रासौ बालको वरः।

पिहितस्तेन दुष्टेन दैत्यैन दृषदापरं।। 70 ।।

दर्षिता मदनस्यापि साटवी यतिना तदा।

मदनोपि च तां दृष्ट्वा प्रमोदपरमं गतः।। 71 ।।

ततोपि चलितं वेगात् विमानं क्षिति दुर्ल्लभं।

मदनं नारदं प्राह पश्य पश्य मनोभवः।। 72 ।।

कर्णयोः शुभगंचै तत् घंटानां मधुरं रवं।

श्रुत्वा तु हरिणीवृंदः स्थितमूर्ध्व मुखं क्षितौ।। 73 ।।

चपलैः षिषुभिर्युक्तं क्रीडयातु मनोहरं।

पुरतोपि पुनर्याति पुनस्तिष्ठति सुन्दरं।। 74 ।।

एवं विधं तु तं दृष्ट्वा मनोन हरते कथं।

प्रमोदं तु ततः प्रापविलोक्य मकरध्वजः।। 75 ।।

नारदोथपुनः प्राह गत्वा तु कियदंतरं।

मयूरं हि मनष्चोरं पश्य पश्य मकरध्वजः।। 76 ।।

उत्पुल्लवदनं रम्यं परं विततं पक्षिकं।

नृत्यकृत्ये समासक्तं कृतकेकं वनांतरे।। 77 ।।

पादौस्तु मंथरैर्युक्तं भुगाणां समूहकैः।

कृतगीतं तु तं दृष्ट्वा प्रमोदं मदनोगतः।। 78 ।।

ततोपि चालितौ तौहि विमानेना शुगामिना।

नारदौसो पुनः प्राह पश्यचाग्रे मनोभव।। 79 ।।

शार्दूलं क्रीडयाषक्तं रौद्रं चापि मनोहरं।

नादाकंपित शैलेन्द्र पश्चाद्वलितबालधिं।। 80 ।।

दंष्ट्राभिष्च नखैष्चापि विदारित महागजं।

तन्मांस भक्षणादेव रक्तपानि भयावहं।। 81 ।।

एवं विधं तु तं दृष्ट्वा मदनोहर्षपूरितः।

पुनर्जगाद मदनं नारदो गगनांगणे।। 82 ।।

पश्य पश्य महाबाह गजवृंदं पुरे स्थितं।

लीलया परयायुक्तं कृत लीला पदे पदे।। 83 ।।

मदेनार्द कपोलेषु गुंजन्मधुप जालकं।

वंषोन्नतं महाप्रौढ़ कर्णतालै विराजितं।। 84 ।।

पुनरग्रेकियद्गत्वा नारदेदो मकरध्वजं।

जगाद वचनं रम्यं पश्य कामपुरास्थितं।। 85 ।।

नगरमेक महाकार्यं गुरूवंषं ससत्वकं।

अनंत खड्गि संसेव्यं स्थिरमुन्नत शालिनं।। 86 ।।

त्वदाकृतिधरं रम्यं भूधराणामधीष्वर।

इत्युक्तेप्यागतं दृष्ट्वा सन्तुष्टो मकरध्वजः।। 87 ।।

ततो गत्वातिदूरं स नारदं मदन जगौ।

अवलोकय वेगेन नदीमेंकां पुरस्थितां।। 88 ।।

तट स्थित महावृक्ष पतक्तु सुमरेणुभिः।

वासितं सलिलं पेयं वहन्तीस्वर्नदीसमा।। 89 ।।

हंससारस संयुक्ता मगाधाम करान्वितां।

एवं विधां समालोक्य तुष्ठ चित्तो बभूव सः।। 90 ।।

कियदंतरसौ गत्वा जगाद नारदः स्मरं।

पश्य गंगाभिधाना त्वं नदी सर्वत्र विसृतां।। 91 ।।

विमलेन वारिणा युक्तां पवित्रां पाप नाषिनीं।

पृथुनितं महापृष्ठे निविष्ठ सुरकन्यकां।। 92 ।।

उपकंठे स्थिताना हि किन्नरीणां महास्वनैः।

हंससारस नादैष्च वषीकृत जगत्त्रयं।। 93 ।।

इत्थं भूतां नदीं दृष्ट्वा प्रमोदं मदनोगतः।

अहो सुरनदीरम्या जल्यन्नेवं सुविस्तरं।। 94 ।।

इत्याष्चर्येन संयुक्तां पश्यंतौतौधरावरां।

महाकौतुकयोगेन गतौ चकियदंतरं।। 95 ।।

गजानां तु सहस्त्रेष्च वाजिनां चापि वृंदकैः।

स्थानां तु समूहैस्तु पदातिनिवहैस्तथा।। 96 ।।

चतुरंग बलष्चैव वाजित्रं निवहैर्युतं।

दृष्टं स्थितं तु भू भागे स्थिताभ्यां गगनांगणे ।। 97 ।।

चक्रनाथस्य सैन्येन समं सैन्यं विलोक्य तत्।

नारदं मदनं प्राह विस्मयेन प्रपूरितः।। 98 ।।

कस्येदंशबलंनाथ दृष्यते वसुधातले।

विद्याधर निवासेपि द्वष्टं न च दृषं क्वचित्।। 99 ।।

नारदोपिस्मिसं कृत्वा जगावेवं मनोभवं ।

अस्यार्थं च समानीतस्त्वमत्र कारणं शृणु।। 100 ।।

हस्तिनागपुरे राजा दुर्योधन समाहुयः।

कुरुवंष समुद्भूतो वर्त्तते गुण सागरः।। 101 ।।

आदिनाथस्य तीर्थेयो दानतीर्थ प्रवर्त्तकः।

श्रेयान्र्निति विख्याताय यथार्थो जनता प्रियः।। 102 ।।

तद्वंष भूषणमनिः कुरूनाम भवन्नृपः।

यस्य नाम्नाति विख्यातः कुरूवंषो भुवस्तले।। 103 ।।

क्रमा च तत्र वंषे भून्नृपाणां तु सहस्रकं।।

बहुषु भूमिनाथेषु व्यतीतेषु पुरे वरे।। 104 ।।

धृतोनामनराधीषो विख्यातक्षिति मंडले।

तिस्रस्तस्यैव संजाता रामा विख्यातमूर्त्तयः।। 105 ।।

प्रथमान् गुणरूपाढ्ययाहिवांबाभिधानका।

द्वितीया त्वं अम्बिका नामा तृतीयाम्बालिकाख्यया ।। 106 ।।

अजनिष्ठ सुतास्तासु नृपतिर्धृतनामकः।

आद्योपि धृतराष्ट्राख्यः पांडस्तु विदुरास्तथा।। 107 ।।

क्रमेणापि त्रयस्तासु सुता विख्यात कीर्त्तयः।

धृतराष्ट्राभिधः प्राप गांधारीनामिकां प्रियां।। 108 ।।

पांडोष्चापि कथा वत्स पुराणेति निरुपिता।

तथापि कथयामास संक्षेपेण कथां वरं।। 109 ।।

पुराभूपतिनायाहि पांडुपुत्राय याचिना।

अंधकवृष्टि भूपस्य सूर्यपुर निवासिनः।। 110 ।।

केनापि पापिना नूनं तस्याग्रेथ निरुपितं।

पाण्डुस्तुष्वेतकुष्ठेन ध्रुवं नष्ट शरीरकः।। 111 ।।

इति श्रुत्वा तदा भूपो न ददाति च कन्यकां।

सा वार्त्तातुश्रुता तेन कथं चित् पांडुनाननु।। 112 ।।

तदादिदुःख भारेण पीडितः पांडुसंज्ञिकः।

सुखं न लभते क्वापि पुरे रण्येप्यहर्निषं।। 113 ।।

एकदा पांडुना मासामेका की तु वनेगतः।

तत्र पुष्पमयीं शय्यां दृदर्ष कदलीवने।। 114 ।।

मर्द्दितादम्पतीभ्यां सा सम्भोगावसरे ध्रुवं।

तां दृष्ट्वा चिन्तयामास दुःख संभारपीडितः।। 115 ।।

नूनं तु पुण्यवान् कोपि रमितः प्रिययासह।

अहं पुण्य विहीनोस्मि लब्धायेन न स्वप्रिया।। 116 ।।

इतिनिस्वस्य तत्रैव निविष्टः पाण्डुनामकः।

विलोकयच्चतां शय्यां दुःखादेव पुनः पुनः।। 117 ।।

तेनप्यस्याः समीपेहि दृष्टाचैकातु मुद्रिका।

तां नीत्वा तु करे कृत्वा वभ्राम विजनेवने।। 118 ।।

तावत् तस्याष्च मुद्राया पतिखेचर नायकः।

आगतो व्यग्रचित्तोसौ शय्यायां तां विलोकयः।। 119 ।।

शय्यायां न यदा दृष्टा तदा म्लानमुखो भवत्।

तत्रैव पाण्डुना दृष्टा म्लानवत्कोपि खेचरः।। 120 ।।

पाण्डुर्जगाद तं खेटं कस्मात्कृष्णमुखोसि भो।

तेन तं तु तदा प्रोक्तं मुद्रिकैः का गता मम।। 121 ।।

अंगुल्यास्तेन निष्काष्य तस्यै सा दर्षिता यदा।

तदा तेनापि तत्रोक्तं ममैव यदि दास्यसि।। 122 ।।

पाण्डुना साथतस्मैच दत्ता वै मुद्रिका शुभा।

तदा तु खेटनाथोपि दृष्ट्वास्य साहसं परं।। 123 ।।

जगाद श्रृणु भो मित्र कस्मात् म्लान मुखो भवान्।

इति पृष्ठे यथा वच्चदुःखे तस्मै निरूप्यतं।। 124 ।।

मित्रस्यैवं विधं दुःखं श्रुत्वा खेचर नायकः।

तामेव मुद्रिकां दत्वा जगावे वंचतां प्रति।। 125 ।।

ममेयं मुद्रिका वत्स जानीहि कामरूपदा।

अस्या प्रभावतो नूनं कार्यं कुरू ध्रुवं तव।। 126 ।।

सिद्धेकार्ये त्वयामह्यं देवावै मुद्रिकोत्तमा।

नीत्वा तां धृतपुत्रो जातो हर्षेण पूरितः।। 127 ।।

निजं रूपं परावृत्य जातः पारावतस्तदा।

जगाम तत्र वेगेन यत्र सा कन्यकोत्तमा।। 128 ।।

नीत्वारूपति कामस्य निषायां तु गवाक्षके।

एकाकिनी तु सा सुप्ता तस्यैसोमिलितस्तदा।। 129 ।।

अपूर्वं पुरूषं दृष्ट्वा सहसा कंपिता हृदि।

कस्त्वं भोत्र समायातो निषायां मन्दिरे मम।। 130 ।।

जगादसस्मितं कृत्वा माकृथास्त्वं वृथा भयं।

अहं तव पतिर्नूनं योवैपांडुसमाहुयं।। 131 ।।

दूरतं दृष्ट्वा तु तथा प्रोक्तं कुष्ठी पांडुश्रुतोमया।

तेनोक्तं केन दुष्टेन वृथात्र कथितं तव।। 132 ।।

मम दृष्यं परं रूपं जानीहि त्वं तु सुन्दरि।

इत्युक्त्वा रूप पाषेन बद्धा सा सुन्दरी तदा।। 133 ।।

नवसंगम योगेन साथ साधू स कंपिता।

रमिता तुष्ट चित्तेन पांडुना कामिनी शुभा।। 134 ।।

तस्यरूपगुणैर्बद्धोः जातासौ पांडुसंज्ञिकः।

सापितस्य गुणैर्बद्धा कामिनीकाय पूरिता।। 135 ।।

परस्परं तदा स्नेहः संजातोवडस्तयोः।

सप्तैव वासराः सोपि स्थितोत्र प्रेम पूरितः।। 136 ।।

अष्ट मे वासरे नूनं गन्तुकामो यदा भवत्।

तदा सा विनयं कृत्वा पांडु प्रोचे विचक्षण।। 137 ।।

श्रृणुनाथ महाभाग गन्तुकामो भवान भूत्।

किंचित् कथितु कामोस्मि भवन्तं लज्जयाकुला।। 138 ।।

कथयस्व प्रिये नूनं का लज्जास्वामिनं निजं।

इत्युक्ते पांडुनासोपि जगौचित्त समुद्भवं।। 139 ।।

यदा त्वं तु समायाततः कृपां कृत्वा ममोपरि।

स्त्रीधर्मोपिहि संजाताष्चत्वारोवासरा विभो।। 140 ।।

यद्युत्पन्नं ममात्रस्यादाधानं तु करोमि किं।

इत्युक्ते वटकं दत्वा जगाम प्रमदान्वितः।। 141 ।।

गत्वा तां मुद्रिकां तस्मै सिद्ध कार्यो ददौ मुदा।

गतेमसेथ सा ज्ञाता सखीनां निवहैस्तथा।। 142 ।।

ताभिर्गत्वा तदा प्रोक्तं तस्यामातुर्विचेष्टितं।

साथश्रुत्वा जगौ गत्वा नृपं कौन्ती विचेष्टितः।। 143 ।।

ततो लज्जाकुलो राजा जगाद भामिनीं प्रति।

त्वं गत्वा पृछता दुष्टं गर्भं कस्यात्र धारितं।। 144 ।।

तया पृष्टाथ सा प्रोचे माकृथा मालिनं मुखं।

पांडुरत्र समायातो स्तेनाहं रमिता ध्रुवं।। 145 ।।

तस्यात्र कंकणं पार्ष्वे वर्त्तते मम निष्चितं।

इत्युक्त्वा च तया तस्यै निष्काष्य दर्षितं च तां।। 146 ।।

राज्ञां तु कटकं नीत्वा गता भूपस्यसन्निधिं।

तस्मिन् दृष्टे तु दुःखे हंज्यक्तं तेन महीभुजा।। 147 ।।

क्रमेणास्याथ तं गर्भं जातं सम्पूर्ण मासकं।

तदा तया सुतो जातः सर्वलक्षण लक्षितः।। 148 ।।

कलंकस्य भयात् नूनं पुत्रं तं तु महीभुजा।

पेटिकामध्यतः कृत्वा क्षिप्तं तं यमुनाह्रदे।। 149 ।।

पुत्री सा पांडु भूपस्य दत्ता तेन महाभुजा।

उत्सवैर्विविधैः कृत्वा वोढातेनापि सा ध्रुवं।। 150 ।।

युधिष्ठिरादयस्तस्याः पुत्रा जाता विचक्षणाः।।

कन्ययायस्तु संजातः सकर्णोति प्रसिद्धकः।। 151 ।।

धृतराष्ट्रस्यपांडोष्च दत्वा राज्यं धृतोनृपः।

दीक्षां जग्राह जैनन्द्रीं विदुरेण समं वने।। 152 ।।

धृतराष्ट्रस्य संजातं पुत्राणां शतमूर्ज्जितं।

दुर्योधनादयं सर्वे विख्यातः क्षिति मंडले।। 153 ।।

धृतराष्ट्रोथ पांडोपि दृष्ट्वा पुत्रान सयौवनान्।

दीक्षितौ च तयोर्दत्वा राज्यंवै ज्येष्ठ पुत्रयो।। 154 ।।

बुद्धिकौषल योगेन राज्यं पांडोष्च देहजा।

त्याजितास्तेन वै सर्वे दुर्योधन महीभुजा।। 155 ।।

विदधात्यधुना राज्यं दुर्योधन महीपतिः।

तस्यास्ति देहजा नूनं विख्यातोदधिनामकः।। 156 ।।

रूपं सच्चरितं चैव गुणान् लावण्यमेव हि।

वचो मधुरताचैवं विद्या च विनयं तथा।। 157 ।।

शरीरं च तथा नेत्रे भातिभामंडलं परं।

लोकाबोधित वृतं च चरित्रं चापि चारूता।। 158 ।।

लीलया ललितं चैव कलानां निवहस्तथा।

तस्याः कोगदितुं शक्तो बृहस्पति समोपिहि।। 159 ।।

अनुत्पन्नस्य ते दत्ता सा तेनापि महीभुजा।

भवांष्चजातमात्रोपिह्वतस्तेन सुरेण हि।। 160 ।।

किंवदंत्यपि ते नूनं यतोनात्र श्रुता ध्रुवं।

तदास्याज्जनकेनेयं प्रेषितास्ति तवानुजां।।161 ।।

एवं नारद वाक्येन तुष्टो भूच्च मनोभवः।

उत्सकोसौ तदा जातो निजरामां निरीक्षितुं।। 162 ।।

नारदं तु जगावेवं श्रृणु तात वचो मम।

विलोकितुं ममोत्कंठा वर्त्तते सैन्यमुत्तमं।। 163 ।।

तवादेष वषैनाहं गत्वा पश्यामि तं द्रुतं।

तदा तु नारदः प्रोचे मनोजं प्रति सर्स्मितं।। 164 ।।

भवांष्च चपलो वत्स चापल्यं त्वं करिष्यसि।

अतो गन्तुं न दास्यहं किंचिद्विध्नं भविष्यति।। 165 ।।

कामोपि नारदं प्राह न करोमीह चापलं ।

विलोक्य शीघ्रमेष्यामि वाहं समेष्यामि तवांतिकं।। 166 ।।

तर्हि शीघ्रं समागच्छतच्चालोक्याति कौतुकान्।

इत्युक्ते विमानं खेटस्तं भयित्वा ययौ भुवि।। 167 ।।

नीत्वा शबलवेषं स द्रुतं तत्र समागतः।

यत्र तं सकलं सैन्यं भोजनार्थं स्थितं भुवि।। 168 ।।

विरलं वदनं तस्म वृहत् च दषनावलीः।

प्रौढेनापि ललाटेन कपोलाभ्यां भयावहः ।। 169 ।।

वल्लीभि भिर्वेष्टितं तस्य षिरजूटकं शुभं यचः।

चपलाभ्यामति रक्ताभ्यां लोचनाभ्यां कुरुपक।। 170 ।।

करेः करोपमौ प्रौढौ भीमौ तस्य महाभुजौ।

स्थूल जंघो महाकाय भृकुटी कुटिलालकः।। 171 ।।

भग्न पृष्ठिकटि ग्रीवो विषाल कठिनोरुकः।

प्रौढ़ादरोति वीभत्से रौद्रोरूप विवर्जितः।। 172 ।।

एवं विधोपि भिल्लोसौ दृष्टः कुरुनरैः सच।

तदा ते हसिता सर्वे कुमारा यौवनान्विताः।। 173 ।।

जगुस्तं शबरं सर्वे गंतु कामास्तु कौरवाः।

अतोव्रजद्द्रुतं पापत्यज मार्गं पुरः स्थितः।। 174 ।।

किं त्वं कारमुंमुद्दिष्य स्थितोसि पथि दुर्मुख।

इत्युक्तेथ जगौसोपि कोपेनहि वनेचरः।। 175 ।।

स्थितोहं कृष्ण वाक्येन योग्य शुल्क हरोस्मि भो।

तत् दत्वाचाति वेगेन व्रजंतु च भवत् जनाः।। 176 ।।

कृष्ण प्रीत्या जगुस्ते वै सुभटाः कोमलं वचः।

कथयस्व द्रुतं वत्स नेतु कामोसि किं ध्रुवं।। 177 ।।

गजवाजिरथाः सन्ति धनं धान्यं तथैवहि।

तासुवस्तुषुयत्ते हि रुचितं तद्गृहान्भो।। 178 ।।

तद्दत्वात् वयं नूनं गच्छामोनैव संषयं।

त्वं चेत् कृष्णचरष्चासि दुःखं ते दीयते कथं।। 179 ।।

सुखेन कुषलेनापि व्रजामोथ वयं वनात्।

इत्युक्ते शबरः प्रोचे शृण्वन्तु कुरु नंदनाः।। 180 ।।

न जाने किं वरं चास्ति सैन्ये तु भवतां भटाः।

यदुत्तमं परं श्रेष्ठं तत् दत्वा गत्यतां द्रुतं ।। 181 ।।

मयि सन्तोषिते नूनं कुषल भवतां वने।

कुपथिका कुलंहि सत्यंमे वर्त्तते भटाः।। 182 ।।

शबरस्य वचः श्रुत्वास्मितं कृत्वा जगुर्भटाः ।

उत्तमं सुखदं चात्र यदि वांछसि त्वं शठाः।। 183 ।।

तदात्र भूपतेः पुत्री गृहाण गुण शालिनीं।

उत्तमा सा तु सैन्येत्र वर्त्तते सुखदायका।। 184 ।।

भटानां वचनं श्रुत्वा हसित्वाथ वनेचरः।

सा हि चेदुत्तमा सैन्ये दीयतां मम चा वदत्।। 185 ।।

गम्यते यदि तां दत्वा वनादस्यान्महाभटाः।

तदा तु न भयं नूनं भवतां विजने वने।। 186 ।।

मयिसन्तोषितो चात्र कृष्णः सन्तोषितो ध्रुवं।

इतिवाक्यं पुरा दत्तं कृष्णेनोपि ममैव हि।। 187 ।।

त्वया सारतरं वस्तु ग्राह्यं सर्वत्र विष्ठते।

इत्यादेषवषेनाहं स्मितोस्मि च वनान्तरे।। 188 ।।

वनेचरस्य वेषे सा जगावेवं मनोभवः।

तदाते कुपिताः सर्वेजगुरेवं वनेचरं।। 189 ।।

किं जातो हरिणा त्वं हि यदेवं भाषिसे शठाः।

बलाच्च नेतु कामोसि कन्यामुदधि सञ्ज्ञिकां।। 190 ।।

रे रे निर्लज्ज पापात्मान् कथं पापकरं वचः।

जल्यसे त्वा दृसैर्मूढ़ैर्मनसापि न प्राप्यते।। 191 ।।

रक्तलोचन युक्तोसि कपिल केष धारकः।

सितदन्तधरोनूनं मसित कान्तिवेषभाक्।। 192 ।।

ईदृषस्य कुरुपस्य या युक्ता सुन्दरींनहि।

सा तु पुण्यवतां योग्या त्वादृषां पापिनां कथं।। 193 ।।

कटि पीनघनाभ्यां सा स्तनाभ्यां सा विराजिता।

सर्वलक्षण संयुक्ता प्राप्यते भवता कथं।। 194 ।।

यदि वांछसि तां बालां प्राप्तुं वा लोक दुर्लभां।

भृगतटाच्चनिःपत्यः मियस्वचातिवेगतः।। 195 ।।

वृत्तस्यधारिका नैवं तवेयंजाति निंदिता।

अनया सदृषी क्वापि प्राप्यते चाग्रजन्मनि।। 196 ।।

तत्र के चिद्भटा प्रोचुर्गत्वा कोपं सुदुःसहं।

किमत्र गृहिलेनामा क्रियते जल्य विस्तरः।। 197 ।।

एवं निक्षिप्य दूरेण वेगतो गम्यतामिति।

अस्माकं कुपितः किं वा करिष्यति नरोत्तमः।। 198 ।।

युक्तं न राजपुत्राणां किराते शुल्क दानता।

योग्यं तु दीयते शुल्कं राजपुत्रोभवेत् यदि।। 199 ।।

इत्युक्तेत्सकतां प्राप्ता राजपुत्राय यदाखिलाः।

रुरुधेसोथ धनुषा सर्वतोपि विसर्पिणा।। 200 ।।

तदाचाग्रविभागाभ्यां ते नैव धनुषाखिलं।

सैन्यं तु वेष्ठितं वेगान्मदनेन बलीयसा।। 201 ।।

वेष्टयित्वाथ तं सैन्यं कुर्वन् हास्यं तदोत्कटं।

जगाद कौरवांष्चैवं शृण्वंतु सुकुमारकाः।। 202 ।।

कथं न दीयते मह्यं पुत्री कुरू महीपतेः।

कृष्णस्य प्रथमः सूनु नृपतिर्वनवासिनां।। 203 ।।

मनोज्ञा कुवेषधारी किं न भवामि यतो मम।

दीयते न कुमारीयं भवार्मिमूढमानसैः।। 204 ।।

दीयते यदि नूनं मे कुमारी लोक विश्रुता।

हरेरपि तदा तोषो जायते परमोत्कटं।। 205 ।।

तत्समान पराकाचिद्वर्त्तते कन्यकोत्तमा।

तत्समो न वरो लोके मनुजेषु प्रवर्त्तते।। 206 ।।

बलाद्वागंतु कामावै यदि यूयं तु कौरवाः।

तदा मे कथ्यतां वेगाद्यत् त्वं किंचित्करोम्यहं।। 207

इत्युक्ते जे जगुष्चैवं कुरुपत्नं यथेप्सितं।

मारयित्वा गमिष्यामो भवन्तं पापकारिणं।। 208 ।।

इत्युक्ते तु किरातस्य वेषधारी निजान् प्रति।

कृत्वाथ कुकुभं प्रौढ़ सर्वास्तां निज सैन्यया।। 209 ।।

तदात्र प्रकटं जातं शबराणां च महद्बलं।

दिषां जालं तु संरूद्ध्य कृष्ण मूर्त्तिधरं स्थितं।। 210 ।।

विविधेष्चायुधैयुक्त तीक्ष्ण बाणैः समन्वितं।

युतंलकुटकाष्टादि पाषाणा परिग्रहं।। 211 ।।

भूमौ च पर्वते वृक्षे कंदरे चापि सर्वतः।।

किराताकुलितं विष्वं दृष्टं कुरूनरैः परं।। 212 ।।

जहिगृहाणवदंतोयां तिक्वेति दुरात्मकाः।

वृन्दस्ते समायाताः शबराणां हि कोटय।। 213 ।।

रक्तपल्लववृन्दस्य कृतचार्यवतं सकाः।

नाना पादप जातीनां फलैस्तु कृत कंठिकाः।। 214 ।।

एवं विधास्तु कृष्णांगाः समायाताः सहस्रषः।

कपिलरूक्ष विषीर्णास्तु येषां सन्ति षिरोरूहाः।। 215 ।।

मलिनवस्त्रष्च खंडाष्च धरायंतोल्पलोचनाः।

रूद्धास्तु सकला देषास्तत्रत्यैस्तु वनेचरैः।। 216 ।।

सैन्यस्याभिमुखं सर्वे धावंतस्ते समागताः।

तदा कुरूनराः सर्वे जाता हि क्षणमाकुलाः।। 217 ।।

असिःषराष्च कुन्ताष्च गदाषक्तिस्तथैव च।

नानायुधैः समायुक्ताः कौरवाः सन्मुखं स्थिताः।। 218 ।।

गजवाजिरथारूढाः शूरा विविधवाहना।

नृपास्तु चलिता वेगात् संमुखं तु किरातकान्।। 219 ।।

जगदुष्च नृपाष्चैवं निजांष्च सुभटान् प्रति।

सुभटाः प्रतिगृह्णं तु शबरांष्च समयंनिजान्।। 220 ।।

भूपालास्तु किरातैष्च युद्धं चक्रुः परस्परं।

पाषाणैस्तुषरैष्चापि किरातैर्निहता नृयाः।। 221 ।।

निजपृष्टिगतं वीरं निपात्य तुरंगास्तदा।

बभ्रमुः सकलं सैन्यं पातयंतोपरान् जनान्।। 222 ।।

गजागतमदाः सन्तः कुर्वन्तोरचमुत्कटं।

वरेचर भयात् नूनं बभ्रमुस्ते तदारणे।। 223 ।।

विषीर्णाः पतिता भूमौ भग्नास्तत्र महारथाः।

शकटेभ्य धृतपार्ष्व पतिता क्षिति मंडले।। 224 ।।

चूर्णगोधूम संभूतं मुदठानां तु पयस्तथा।

तन्दुलानां पराः पुंजाः पतिता भूमि मंडले।। 225 ।।

सुभटावस्त्रहीनास्तु भूषणादि विवर्ज्जिताः।

पतिता हसिताभिल्लोर्निजैस्तु शोचितस्तदा।। 226 ।।

तदा तत्र बलीवर्द्धा भ्रमंतो गुणकोष्भिताः।

धर्त्तुंनैव हि शक्तास्तु निजैः कुरूजनैरपि।। 227 ।।

करभाष्च खराष्चैव वृषभाद्वि शरीरकाः।

भयात् कम्पित देहास्तु रटंतः करुणावहं।। 228 ।।

निजानामपि लोकानां भारस्यारोपणं तदा।

करणंनैव हितेद़द्युः दुःखे दुखं सुखे सुखं।। 229 ।।

किरातान समूहेन कौरवानां बलं तदा।

विजित्य सहसा सर्वं भटैर्दत्तरणंरणे।। 230 ।।

मुनिनालोक्यमानोसौ किरातस्य हि वेषभाक्।

कन्यामुधृत्य बाहुभ्यां मुत्पत्य गगने ययौ।। 231 ।।

भिल्लानां भयतस्त्रस्तां कम्पमान शरीरिकां।

विमानमुत्तमं नीत्वां नारदान्ते निवेसिते।। 232 ।।

निवेष्य कन्यकां तत्र स्वयं शबरवेषभाक्।

पुरः वक्रमुखं कृत्वा स्थितौ सौ निंदिताकृतिः।। 233 ।।

एवं विधं च तं दृष्ट्वा कंकालाकृति धारिणं।

कंपंती सा जगावेवं नारदं विहितादरा।। 234 ।।

मदीयं निन्द्रितं कर्म पश्य तातेन धीमता तत्वमीदृषं।

रुदंती विलपंतीस्वं निदन्ती च मुहुर्मुहुः।। 235 ।।

दत्ताहं रूक्मिणी सूनोः पुरा तातेन धीमता।

ममोपापवषेनैवः सोपिहि वैरिणा।। 236 ।।

पश्चात् च तेन दत्ताहं भानोः भामासुतस्यहि।

मम कर्मप्रभावेन ह्रता मार्ग मलिम्लुचैः।। 237 ।।

रूदन्ती सा जगौ तत्र वचनं करूणावहं।

कथं न रक्षिता तातनीयमाना वरेचरैः।। 238 ।।

मम भाग्यस्य वसतिं कथमंब त्वपिहि।

रक्षिता नैव भिल्लेभ्यो दुष्टेभ्योत्र भयाकुलं।। 239 ।।

भो भोत्र बान्धवाः सर्वेमांवैदुःखस्य भगिनीं।

पश्यार्थ यतो नैव रक्षथा शबरे हृतां।। 240 ।।

कंपंती विलपन्ती सास्वसंतीस्रस्तमं वरं।

धारयन्ती तु दुःखेन त्रासन्ती तस्य दर्षनात्।। 241 ।।

मुखेतु करमाधाय रूदंती च पुनः पुनः।

विस्मयाकुल चित्ता सा नारदं तु जगाविति।। 242 ।।

श्रृणु नारद में वाक्यं शबरोयं दुरात्मकः।

कथमस्य हि संजाता परातु गगने गति।। 243 ।।

अथवाक्येपिदवोयं विकृताकृति धारकः।

दैत्योः निषेचरो वाक्यं विद्याधर सुतोथ किं।। 244 ।।

तवानुनाहि पापेन जाता चा संगतिः कथं।

वैरिणानेन दुष्टेनाहं यथात्वं धृतोसि किं।। 245 ।।

इत्युक्त्वा नारदं सापि मरणेकृत निष्चया।

एवं विधांतु तां दृष्ट्वा नारदोपि जगौमुदा।। 246 ।।

हर्ष स्थाने कथं शोकं किं धार्यते तु त्वयापरं।

जगादोदधिकन्या तं को हर्षस्तात कथ्यतां।। 247 ।।

पितृभ्यां तु पुरायो हि रूक्मिणी तनु संभवं।

कल्पितष्च पतिस्तेवैसोयमत्र समागतः।। 248 ।।

विद्याधरे निवासोच्चदर्थं तु समागतः।

मुंच शोकं परं बाले भजहर्षं तु पुण्यजं।। 249 ।।

सुन्दर्येवं समास्वास्य मुनिः प्राह मनोभवं।

न क्रीडा हि चरं रम्या हास्यं श्लाध्यं चिरंनहि।। 250 ।।

मनोहरेण रूपेन निजेरूपं मनोभवः।

जग्राह सर्वलोकानां नेत्रानन्द करं परं।। 251 ।।

नाना रत्न मयेनैव किरीटेन विराजितं।

स्रगानु लेपनं चापि चलत्कनक कुण्डलं।। 252 ।।

हारांगदकटकादि भूषणैः परिमंडितं।

सदंबुज समानाभ्यां नेत्राभ्यां हि मनोहरां।। 253 ।।

कनत्कनक शैलाभं तद्वच्च कटिर्नेरसं।

करि सुंडिसमाकार वृत्त दीर्घ महाभुजं।। 254 ।।

भ्रमरराषिवत् कृष्ण स्निग्ध कुंचितकुंतलं।

सर्वलक्षण संयुक्तं सर्वाभरण भूषणं।। 255 ।।

स्थिरं स्मित मुखं धीरं ममसापि भयोष्भितं।

यस्य निर्दर्षनं जातं सर्वेषां प्राणिनां भुवि।। 256 ।।

तद्रूपं तं समालोक्य मृगाक्षी विकचेक्षणा।

प्रमोदं परमं प्राप्ता तुष्टा चित्ता सती सती।। 257 ।।

तस्य दर्षन मात्रेण प्रीत्या हि परयान्विता।

बभूव सोपि तस्यैव रूपेण दूत मानसः।। 258 ।।

भावः कोपि तदा जातस्तयोः प्रेमात्परस्परं।

कथित्वं नैव शक्योसौ चित्तराग समुद्भवः।। 259 ।।

आन्योन्यंतु समालोक्य रूपंतौदम्पती जनौ।

अनुरागयुतौ जातौ प्रेमादुल्लसिताननौ।। 260 ।।

लज्जया नारदस्यैव किंचिद्वक्र विलोचनौ।

मुनिनापियुतौ तौ हितद्देषाच्चलितौ तदा।। 261 ।।

इत्थं हि मदनागच्छन् मुनिना भार्ययायुतः।

ददर्षाग्रेपुरीं रम्यां विविधोच्छितकेतनां।। 262 ।।

पृष्टवान्नारदं तुष्टः केयं नाथ पुरीवरा।

प्रेमचित्तो वदत्शोपि मदनं तु तपोधनः।। 263 ।।

इयं तु द्वारिकानामा प्रसिद्ध भुवनेपुरी।

नागराणां निवासाय विधात्रात्र विनिर्मिता।। 264 ।।

स्वर्गं खंडमिहानीतमथ वा किं सुरेष्वरैः।

लेकानां शेष पुण्येन कांतिमंतां भुवस्तले।। 265 ।।

कृष्णराज निवासस्य स्थान भूतां जनैस्तु तां।

महाषाल समायुक्तां गोपुरैर्घ नराजितां।। 266 ।।

मज्जत्पुर पुरं ध्रीणां कुच कुमकुम सज्जलैः।

विचित्रैष्चापि संपूर्णे खातिका परिवेष्टितां।। 267 ।।

प्रमत्तानां गजानां च कपोलमदवारिभिः।

संजातकर्दमा नित्यं राजमार्गेतु दुर्गमां।। 268 ।।

सुधाधौताग्रहर्मेषु कामिनी वदनेंदुभिः।

विस्मयो यत्र लोकानां जायते पक्षयोर्द्धयोः।। 269 ।।

प्रौढ़ाष्वपि प्रतोलीषु प्रवेषेष्च विनिर्गमैः।

जनानां यत्र मार्गावै जायन्ते दुःखदासदा ।। 270 ।।

मुक्ता फल समूहैष्च विद्रुमानां तु बृंदकैः।

शंखरत्नादि जातीभिः पूरिता सा पुरीवरा।। 271 ।।

यस्यां तु पादपा रम्या राजंते सर्व सुन्दराः।

मत्तभ्रमर वृंदैष्च मुखराः पुष्प पूरिताः।। 272 ।।

पÏन्योपि तडागेषु दृष्यन्ते भ्रमरैयुताः।

नानाविधाभिर्मणिभिः वापिका बद्धभित्तयः।। 273 ।।

यस्याः श्रियं समालोक्य स्वर्गवासी सुरोत्तमाः।

स्वर्ग त्यजति वेगेन निवासायपुरीं च तां।। 274 ।।

जिनेन्द्रस्य परं भक्त्या शक्त्यानारायणस्य हि।

कारापकोपि देवेन्द्रः कर्त्ता च धनदः स्वयं।। 275 ।।

तस्याः का वर्णनालोके क्रियते तु मयाध्रुवं।

भुवनत्रय मध्येहि नेदृषी नगरीपरा।। 276 ।।

तत्युक्त्वा नारदः कामं सांभिझं गृह संततिं।

दर्षयामास हर्षेण द्वारिकोपरि संस्थितः।। 277 ।।

इत्थं नारदवाक्येन कौतुकं विविधं स्मरः।

कुर्वन् जगादतमृषिं श्रृणुनाथ वचो मम।। 278 ।।

द्वारिका दृष्टु कामोस्मित वादेष वषाद्विभो।

गत्वा विलोकयामीतिः प्रोच्यते भवता यदि।। 279 ।।

मदनस्य वचः श्रुत्वा जगाद नारदोमुनिः।

गन्तुं न युज्यते वत्स द्वारिका यादवैर्भृता।। 280 ।।

यादवास्तु परं तुष्टाष्चपलोति भवानिति।

उपद्रवः परं तेस्याद्यादवेभ्योति निष्चितं।। 281 ।।

गमनायोछकं दृष्ट्वा तदैवोदधिकन्यका।

कृत्वा दृष्ट्वा समस्यां हि जगाद नारदं प्रति।। 282 ।।

मदनस्य त्वयानाथ दातुं गन्तुं न युज्यते।

पीडां ते यादवै नूनं चपलो मदनो विभो।। 283 ।।

तस्या ज्ञात्वा समस्यां तां नारदोमदनं जगौ।

गन्तुं दास्येन ते वत्स द्वारिकायां तु मां विना।। 284 ।।

नीत्वा त्वामे कदाहं वैजनन्यैव समर्पये।

पश्चात्वं मनसोभीष्टां कुरू कार्य परंपरां।। 285 ।।

ज्ञात्वा तयोरभिप्रायं मदनोपि जगौ वचः।

न किंचिच्चपलत्वं हि करिष्ये तात साम्प्रतं।। 286 ।।

मिलितेतु कुटंबस्य स्वजनैरूपलक्षिते।

कथं विलोक्यते तात द्वारिका सकलामया।। 287 ।।

अतएव क्षणं गत्वा विलोक्य द्वारिकां पुरीं।

अधुनैव तवाभ्यासे समेष्यामि सुनिष्चितं।। 288 ।।

इत्थं प्रोवाच कामोपि संस्तंभ्य गगनांगणे।

विमानं रामयायुक्तं नारदेनापि संयुतं।। 289 ।।

उत्तीर्य यादवायाति द्वारिकाया भुवस्तलं।

तावद्बाह्येद् दर्षासौ भानुं भानुमिवापरं।। 290 ।।

प्रतापनिलयं वीरं छत्र चामर भूषितं।

नाना विभूति संयुक्तं राजपुत्रैः सुसेवितं।। 291 ।।

एवं विधं चतं दृष्ट्वा गत्वाथ विस्मयंस्मरः।

प्रपछ च निजां विद्यां कोयं विद्येममादिष।। 292 ।।

विद्ययाथ तदा भाणि विनयान्मकरध्वजं।

श्रृणुनाथ महाभाग कथ्यते तु तवाप्पयं।। 293 ।।

वाजि वाहनसंरक्तो वेष्टितो राजपुंगवैः।

तव मातुः सपत्न्यावै पुत्रोयं भानु नामकः।। 294 ।।

उदयैका निवासोयं रूपलक्षण संयुतः।

तवात्ररूचितं यच्चतत् कुरूष्व महामते।। 295 ।।

विद्यावाक्यं समाकर्ण्य तदैव मकरध्वजः।

प्रज्ञप्तीत्याख्यां महाविद्यां चकाराष्वं मनोहरं।। 296 ।।

लम्बोदर महाकायं चपलं वेग शालिनं।

सर्वाष्व लक्षणैयुक्तं सर्वावयव सुन्दरं।। 297 ।।

एवं विध हयं कृत्वा विद्यायस्तु प्रभावतः।

निजजटां वरिकं रूपं जग्राहासौ मनोभवः।। 298 ।।

कम्पमान समस्तांगः पाणिपादौ षिरस्तथा।

अतिवृद्धो अतिस्थूलष्च षिथिल भ्रूरूद्धलोचन।। 299 ।।

एवं भूतं निजं रूपं कृत्वा चासौ मनोभवः।

अश्वं कांचन सन्नद्ध पल्लायनेन सुन्दरः।। 300 ।।

गृहीत्वा स्वकरेणैव हयमुच्चैःश्रवः समं

तत्र देषे समायातो यत्रासौहरिनंदनः।। 301 ।।

वाहमानो हयानूभानुः दृष्ट्वातं तुरगाधिपं।

हर्ष युक्तो जगादासौ तंतुटावरिकं प्रति।। 302 ।।

अष्वोयं कस्य भो वृद्ध किमर्थं धार्यते त्वया।

मयादृष्टोसि सत्यं त्वं सर्वं मे प्रतिपादय।। 303 ।।

ततष्टावरिकः प्राह श्रृणु त्वं कृष्णनन्दन।

ममष्वोत्यंत योग्योयं धार्यते तु मया ध्रुवं।। 304 ।।

किक्रीणामि त्वा सावष्वं गृßात्वर्थीजनो ननु।

त्वदर्थं तुरगं नीत्वा प्रदेषाष्व समागतः।। 305 ।।

सत्यभामा सुतस्त्वं हि तव योग्याहयो ननु।

अन्येषां दुर्लभो नृणामर्थितो यदिस्वाकुरू।। 306 ।।

तदा भानुस्तु तं प्राह श्रृणुटारिकमद्वचः।

विक्रीणासि यदाचाष्वं मौल्यं चास्यममादिष।। 307 ।।

सत्यं वचवीमिचासत्यमित्यु क्रेटारिकेनहि।

तत्रापि भानुना प्रोक्तं हसित्वा टारकं प्रति।। 308 ।।

उत्तमाः स्थविरायेहि सभ्यास्तु भवादृषाः।

तेषां तु वदनाद्वाक्यमसत्यं नैव निः सृतिः।। 309 ।।

मह्यं सुवर्ण कोटीत्वं देहिमौल्यं हयस्यवै।

तत्श्रुत्वा भानुरप्याह किं हास्यं क्रियते त्वया।। 310 ।।

त्वं तु कृष्णकुमारोहि यत्व हास्यं मयोकथं।

क्रियते नियतं वत्स हास्यं नीच जनार्दितं।। 311 ।।

समर्थोत्यंत तुरगो हस्यते हि मया कथं।

ग्राह्यं यद्वस्तु सर्वत्र परीक्ष गृह्यते जनैः 312 ।।

भानुस्तद्वचनं श्रुत्वा जगाद टारिकां प्रति।

सत्यं वदसि हे तात करोम्ये वन संषयं।। 313 ।।

ससंभ्रमं समुत्थाय स्वयमेवहरेः सुतः।

आरोरूह हयंतं हि चपलं मूढधीस्तदा।। 314 ।।

वाहया मासवेगेन हयं लक्षणभालिनं।

बभ्रामस्तुरगः सोपि लीलयागतिमुत्तमं।। 315 ।।

रंजयामास चारस्यैव चित्तं भानोर्यथाध्रुवं।

समपादैर्वाक्रपादै र्भ्रमयित्वा क्षणमात्रकं।। 316 ।।

ततो वेगेन संयुक्तां गतिं दघ्रे मनोहरां।

वस्त्राभरणामेवास्य सर्वं तु पातितं भुवि।। 317 ।।

धृतोपि तुरगष्यासौभानुना नैव तिष्ठति।

भ्रमित्वा तु तदा वेगात्पातितोसौ धरातले।। 318 ।।

पातयित्वा तदा भानुं तुरगो विनयान्वितः।

समीपेस्य समागत्य स्थितष्चापल्य वर्ज्जितः।। 319 ।।

अनेकैः राजपुत्रैष्च सेवितं हरि नन्दनं।

पातितं तं समालोक्य जहासटारिकोच्चकैः।। 320 ।।

हस्तयोस्ताडनं कृत्वा जगाद वचनं तदा।

श्रृणु भानु मदीयं हि वाक्यं चाति मनोहरं।। 321 ।।

त्वदीया विमला कीर्त्तिर्विख्याता क्षिति मंडले।

हयिषिख्या समुद्भुतासेदृषी ननु साम्प्रतं।। 322 ।।

तवकीर्त्तिः समाकर्ण्य हय षिक्षा समुद्भवां।

दूरेदेषात् समायातो हयं नीत्वा तवांतिकं।। 323 ।।

त्वां दृष्ट्वा तु मयाज्ञातं तुरगाणां वाहनं किल।

आरोहनं तथैवात्र न जानासिमगपि।। 324 ।।

हय षिक्षा समूढोसि नूनं त्वं हरि नन्दनः।

अनेन निपुणत्वेन राज्यं भोक्तुं न शक्यते।। 325 ।।

स्थापयित्वा नरंकंचिद्धय षिक्षा विषारदं।

तस्य पार्ष्वे त्वया मूढ षिक्षणीयाकलाखिला।। 326 ।।

लोकानां वदनोद्भूतं पुरा वाक्यं मयाश्रुतं।

हयाषिक्षां न जानाति सत्यभामासुतो ध्रुवं।। 327 ।।

पूर्वे तु राजपुत्रस्य हयषिक्षा विलोक्यते।

हयषिक्षा विहीनस्य कीर्त्तिः स्यात् निर्मला कथं।। 328 ।।

मुखं तदा समाछाद्य लोका हास्यं तु चक्रिरे।

क्रियमाने तदा हास्यं तस्मिष्च टारिके स्फुटं।। 329 ।।

हसंतं तं समालोक्य कर ताडन पूर्वकं।

तदा क्रोध भराक्रान्तो जगाद हरिनन्दनः।। 330 ।।

रे रे वृद्ध परं मूढ वृथा हससि किं शठ।

सर्व कर्म विहीनोसिष्लथ गात्रोजरार्दितः।। 331 ।।

शक्यते तु यदा नूनं हयोवाहयितुं स्वयं।

हस्यते तु तदान्यस्य चान्यथा हस्यते कथं।। 332 ।।

अन्यं दूषयितुं लोके समर्था बाहवोजनाः।

दोषं भक्तुं समार्थाये ते नूनं विरलाजनाः।। 333 ।।

इत्युक्तेटारिकः प्राह शृणु भो सत्यकात्मज ।

नास्तिमे साम्प्रतं शक्तिरष्ववाहयितुं वरा।। 334 ।।

वृद्धत्वे यदि मे शक्तिर्हयं वाहयितुं भवेत्।

बहुमोल्योममाष्वोवै तवात्र दीयते कथं।। 335 ।।

यदि दैव वषात्सर्वे भवतो राजपुत्र काः।

धृत्वा मामपि बाहुभ्यां यत्नाद्रोपयितुं क्षमाः।। 336 ।।

दर्शयामि तदासर्वं कौषल्यं तव चाग्रतः।

प्रसंभंवाहयामीतिविषेषात्तुरगोत्तमं।। 337 ।।

जयामिषिक्षया नूनं त्वामत्र हरिनन्दनं।

किमत्र बहुनोक्तेन जयामि हरिमप्यतेः।। 338 ।।

इति तस्य समाकर्ण्य वाक्यं गर्व समन्वितं।

प्रमोदं परमं गत्वा हरेः सूनुर्तिजान् भटान्।। 339 ।।

जगाद वचनं रम्यं श्रूयतां भो भटोत्तमाः।

वृद्धं चैनं तु बाहुभ्यां धृत्वा चारोप्यतां हये।। 340 ।।

पश्यामः कौतुकं नूनं अष्व वाहन संभवं।

इत्युक्ते मिलिताः सर्वे भटास्ते तस्य सन्निधिं।। 341 ।।

उधृतस्तैस्तदा सर्वैः टंक्वासौ क्षितिमंडलात्।

यावदारोपणायैवष्लथगात्रोति मा यया।। 342 ।।

पपातप्रौढगात्रोसौ मर्द्दयन्नखिलान् भटान्।

स्फोटयन् कर्पूरादंतान् मस्तकानि निषेवितः।। 343 ।।

केचिदत्रतदाजाता गत चेष्टा भटोत्तमा।

किंचिन्मूर्छां समापन्नामृत्वास्त्वन्ये भटाध्रुवं।। 344 ।।

लुठंति भूतले केचित्कंपमान शरीरकाः।

अन्येतु कर पÅषु मुखं दत्वा स्थिता भटाः।। 345 ।।

टंक्वापिष्लथगात्रोसौ मर्द्दयष्च भटोत्तमान्।

निष्वसंतु जगावेवंमाययापिलपंस्तदा।। 346 ।।

पातितोहं महा दुष्टेः शठैः विनयवर्ज्जितैः।

ममात्रैवं कटीभग्ना नितराव्यथते ध्रुवं ।। 347 ।।

एतेषां दुष्ट चित्तानां द्रव्य वस्त्रादिकं त्वया।

कथं वा दीयते भानोस्त्वया मूर्षेण निष्चितं।। 348 ।।

जल्पन्नित्छंतु टंक्वोसौ मर्दयन् भट सत्तमान्।

जगादपुनरप्येवं कुमारं भानु संज्ञिकं।। 349 ।।

चातुर्यं मे स्थितं नूनं हयि षिक्षा समुद्भवं।

कथं वा दर्षयामीह वराकास्ते भटाननु।। 350 ।।

यद्यारोपयितुं शक्त्या दैवयोगान्ममैवहि।

दर्शयामि तदा सर्वे कौषल्यं पुरतः तथा। । 351 ।।

इत्युक्ते भानुनाश्रुत्वा प्रोक्तं निजभटान् प्रति।

सर्वेसंभूय वेगेन मत्समाये भटोत्तमाः।। 352 ।।

स्थापनीयोति वृद्धोयं तुरगोमान पूरितः।

पश्यामोथ वयं चास्य कौषल्यं हय संभवं।। 353 ।।

भानुवाक्यं समाकर्ण्य बलिष्ठाये भटोत्तमाः।

ते सर्वेत्र समायाता समीपं टारिकस्य हि।। 354 ।।

उधृतस्तु तदाचासौतैः सर्वैर्भटसत्तमैः।

उर्ध्वं गत्वा पपातात्र तथैवहि भटोपरि।। 355 ।।

पतित्वान् भटान् सर्वान् मर्मर्द प्रौढ गात्रकः।

जगाद स तथैवात्र कुर्वन् बुंबारवं परं।। 356 ।।

भो भो भानो तवात्रैव भटास्तु सत्ववर्ज्जितः।

तै नीचैस्तुरगे चाहं शत्तयोपारयितुं नहि।। 357 ।।

यदित्वं स्वयमेवात्र समागत्य भटैः सहः।

आरोपयसिमा नूनं कौतुकं दर्षयामिते।। 358 ।।

तेन वाक्येन संतुष्टो वासुदेवसुतः सुधीः।

उत्थितोराजपुत्रैव योग्यैस्तु स्वयमेवहि।। 359 ।।

उधृतो सौत तष्टंक्वो जातो लघुषरीरकः।

यावदारोप्यते तेन नीत्वा पल्यनांतिकं।। 360 ।।

तावत्प्रपात्यतं भूमौ पपातो परितः स च।

ममर्दचाखिलान् वीरान् भानुं चापि विषेषतः।। 361 ।।

गुरूमूर्त्तिस्तनो भूत्वा मर्दयित्वाचिरं च तान्।

कुर्वेष्च विविधालाप मुच्छितो वेगतः पुनः ।। 362 ।।

उत्थाय ह्वदये पादं दत्वा भानोस्तदैवहि।

चढित्वा तुरगे तस्मिन् वाहयामासतं हयं।। 363 ।।

पश्यतां राजपुत्राणां हर्ष पूरित चेतसां।

गत्या मनोज्ञया चासौ भानोरपि पुरस्तदा।। 364 ।।

क्षणमेकं हयं रम्यं वाहयित्वा धरातले।

प्रकाश्य निज कौषल्यं वाजि षिक्षा समुद्भवं ।। 365 ।।

उत्पत्य गगने वेगाद्वाहयामास तत्र तं।

उन्मुखै राजपुत्रैष्च सत्यभामां गजादिभि।। 366 ।।

वीक्ष्यमानं विनोदेन हयं तं गगनांगणे।

वाहयित्वा क्षणं तत्रतिराभून्मदनोवली।। 367 ।।

चमत्कृत्य च तान् सर्वान् सत्यभामासुतादिकान्।

दैत्यो वा खेचरष्चैव इति चिंतासमन्वितान्।। 368 ।।

कृत्वा चाविलक्षांष्च जगाम मदनस्ततः।

गच्छंष्व्याग्रे ददर्षा सौ सत्यभामा वनं वरं।। 369 ।।

तं दृष्ट्वा मदनो विद्यां जगौ कर्णपिषाचिकां।

कस्येदं तु वनं रम्यं विद्ये मम निरूपय।। 370 ।।

विद्याकामं जगावेवं श्रृणुनाथ वचो मम।

सत्यभामा वनं विद्धिपुरस्योपवनं ध्रुवं।। 371 ।।

कामोविद्याप्रभावेन जातः षोडषवार्षिकः।

पंच सप्तहयान् कृत्वा दुर्बलान् प्रौढगात्रकान्।। 372 ।।

स्वयं वाहकरुपेण नीत्वा सान् हयान् वरान्।

वनस्यैव समीपे हि स्थित्वा प्रोवाच रक्षकान्।। 373 ।।

एतदेव वनस्यैव चारर्णार्थं समागतः।

दूरदेशाद्वयान्नीत्वा दुर्बलान्मार्गयोगतः।। 374 ।।

तस्मान् च क्षणमेकं हि ते चात्र सुन्दरे वने।

चरंतुस्वेच्छया युक्ता येन विक्रयमाप्नुयुः।। 375 ।।

तस्य वाक्यं समाकर्ण्य जगुस्ते वनपालकाः।

भवान् किं वातकीचासि वाथ वासि पिषाचकी।। 376 ।।

केन वा मुषितोसि त्वं छलितोसि प्रतारितः।

येन प्राणहरं वाक्यं जल्यसि त्वं तु निंदितं।। 377 ।।

सत्यभामा वानं चैत kनोर्मातुर्मनोहरं।

दृष्टु न लभ्यते यच्च प्राणिभिः पुण्यवर्ज्जितैः।। 378 ।।

हयानां तु गतिं तत्र चरणार्थं समीहते।

नागवल्लीवनं रम्यं लतामंडप राजितं।। 379 ।।

प्रसाद वांस्तु भामायास्तनयोः भानु संज्ञिकः।

यद्यत्ररं तु लभंते प्रवेषं नापरो जनः।। 380 ।।

तेषां तद्वचनं श्रुत्वा मदनोपि जगाविति।

श्रृणुतं मामकं वाक्यं भो भो वै वनपालकः।। 381 ।।

जाता वा निष्टुरा नूनं भवंतो निर्विवेकिका।

भवतां कारणं तत् च किंवादेषस्य कारणं।। 382 ।।

सौराष्ट्र देषजा लोका निष्टुरा दुष्ट चेतसः।

कथयंति यथा लोकास्तथैवात्र च दृष्यते।। 383 ।।

पुरू पुरूषांतरे ये स्थानं स्थानं तथैवच।

न जानन्ति नरामूढास्तेषां किं जीवितं प्रमा।। 384 ।।

संचरंतु हयामेमीतृणानामेव भक्षिणः।

सारिण्या परितो नूनं वचन मध्ये स्थित ध्रुवं।। 385 ।।

अप्रतीतिष्च भवतां हयानां चेत्प्रवर्त्तते।

मदीयां मुद्रिकां रम्यां गृह्णंतु भो गृहाणकं।। 386 ।।

षिक्षितास्तु हया नूनं मया न्यायविधिं पुरा।

वनस्था फलत्रं तु न भक्षन्ति कदाचन।। 387 ।।

तदीयं वचन श्रुत्वा नीत्वा तस्यैव मुद्रिकां।

जगुरेवनरास्तेहि श्रृणुहो हयपालक।। 388 ।।

कुल्यका परितोमीहि चरन्तु तुरगास्तव।

फलपत्र भक्षणा देवगताते मुद्रिका ध्रुवं।। 389 ।।

एवमस्तिवति संभाष्य मुक्तास्तेन हयाष्वते।

पश्यतां रक्षकाणां तु चरंति न्याय संयुतां।। 390 ।।

भक्षतस्तृणमात्रं ते दृष्टवा वै वनरक्षकाः।

मन्दं मन्दं गतागेहं नीत्वा तां मुद्रिकोत्तमां।। 391 ।।

गतेषु तेषु ते नूनं हया इच्छानुचारिणः।

भक्षयामास सर्वतं वनं वेगेन विद्यया।। 392 ।।

उन्मूल्यक्षणमात्रेण समूलं तु निराकृतं।

यथा वनस्यात्रवार्त्तापि ज्ञायतेनहि।। 393 ।।

तन्नंदन समानं हि वनं वैस्थंडिलीकृतं।

मदनस्य हयेः सर्वं वाटिकापि निराकृता।। 394 ।।

सरांस्यापि तदा तेन सत्ययाकारितानि च।

शोषितानि जलानि च बभूवमरूवत्तदा।। 395 ।।

मातुः कार्यस्य करणे प्रवणो मदनोबली।

एवं कुर्वन् ययौ मार्गे ददर्ष नगरी वनं।। 396 ।।

नानाजातिद्रुमाकीर्णं नानापक्षिकृताश्रमं।

फलपुष्पसमूहैष्च राजितं वसुधातले।। 397 ।।

स्वर्गलोकात् समायातं नन्दनं किं धरातले।

नेदृषं तु मया दृष्टं खेटलोकेपि कुत्रचित्।। 398 ।।

विमृष्यैवं तु कामोपि विस्मयाकुल मानसा।

प्रपच्छ निजविद्यां तु वनस्य कारणं तदा।। 399 ।।

कस्येदं तु वनं विद्ये सत्यं ब्रूहि ममाग्रतः।

विद्यापि तदा वाच श्रृणुकाम निगद्यते।। 400 ।।

वनं वै सत्यभामाया प्रसिद्धं वसुधातले।

तवयातुः समं याहि रिपु त्वं दधते सदा।। 401 ।।

यथा रुचि तथा कार्यं त्वया विक्रमशालिना।

विष्णोः प्राण प्रियायाहि भानोर्माता तु सा ध्रुवं।। 402 ।।

विद्या वाक्यं समाकर्ण्य तदैव मदनोमुदा।

चक्रे तु मर्कटं रम्यं चपलं विद्या समुद्भवं।। 403 ।।

दीर्घपुंछ महाकायं चंडीरास्यं चलांगलं।

तनु मध्यं चलत् नेत्रं सितदन्त कुनादकं।। 404 ।।

निजंष्व पंच रूपं हि कृत्वात्र मदनोगुणी।

नीत्वा तं मर्कटं तत्र समायातो वनांतिकं।। 405 ।।

आगत्य च वनं प्राह तत्रतावनरक्षकान्।

श्रृणुंतु रक्षका वाक्यं मदीयं हितकारकं।। 406 ।।

ममायं मर्कटो बाल क्षुधया परिपीडतः।

फलमेकं वनस्यास्य भोक्तुं तु परिवांछति।। 407 ।।

वरमेकं फलं चास्मै फलं तु दीयतां ध्रुवं।

भक्षयित्वा फलं चायं स्पष्टो भवति निष्चितं।। 408 ।।

मर्कटे तु दृढ़े नूनं महं गत्वा पुरे वरे।

रंजयामि जनान् सर्वान् क्रीडया मर्कटस्य हि।। 409 ।।

ममस्याज्जीवनोपायं ब्रवीमि भवता मतः।

ददतु शीघ्रमेवात्र फलनेकं कपेर्वरं।। 410 ।।

तस्य वाक्यं समाकर्ण्य जगुस्तेवनरक्षकाः।

किं वा तेन गृहीतोसि पिषाचेनाऽथ चात्र किं।। 411 ।।

सत्याख्याया वनं चैतत् फलपुष्पैः समाकुलं।

स्पृष्टं तु दुर्लभं चान्यैर्गत पुण्यैर्नराधमैः।। 412 ।।

फलस्य प्राप्तिं भोक्तुं वैका कथा कथ्यते तव।

अतोव्रजतु तं मूढ नीत्वा ते कपिनं वरं।। 413 ।।

दृष्येच्चेद्वैष्णवैर्लोकैः पुरुषैस्तैस्तु सांप्रतं।

प्राप्नोषि च तत् कष्टं त्वं तेभ्योत्यंत दुराषया।। 414 ।।

नदोषोत्रनास्त्यस्माकं जगुरेवं वनपालकाः।

तदेत्छं वचनं श्रुत्वा मदनोपि जगाविति।। 415 ।।

कस्माद्यूयं तु संजाता निष्ठुरा वनपालकाः।

दातुं तु फलमप्येकं शक्तोनोकर्मटस्य मे।। 416 ।।

यदा यं मर्कटो वेगात्क्षुधयार्दित गात्रकः।

समायाति न मे दोषो रजुंछित्वाबलादपि।। 417 ।।

एवं मुक्त्वाथष्वपचो मुमुच वेगतः कपिं।

जगाद हास्य युक्तोसौ क्षुद्राः पश्यंतु सांप्रतं।। 418 ।।

विष्णुर्वासत्यभामावा किमस्मै कुपितायवै।

कुरूते सांप्रतं मूढा मह्यमप्यत्र निष्चितं।। 419 ।।

इत्युक्त्वाथ द्रुतं सोपि प्रयातः श्व पचाकृतिः।

ततोथवन पालास्तं कपि हंतु समुद्यतः।। 420 ।।

दंडैः खडैठः पलाशैष्च पाषाणैः सरतोपमैः।

अन्यैः शस्त्र समूहैष्च रूद्धोप्यत्र समागतः।। 421 ।।

वनपालास्तत सर्वान् परिहृत्य बलादसौ।

प्रविवेष वने यावत् तावत् जाताः सहस्रषः।। 422 ।।

ध्वस्तं सर्वं वनं तैष्च सद्वृक्षैः परिपूरितां।

लता समूहैः संयुक्तं कोपात्सर्वं निराकृतं।। 423 ।।

तथा कृतं यथा तस्यालंकारोपि न दृष्यते।

उन्मूल्य सागरेक्षिप्ताक्षावाटी तथा लता।। 424 ।।

तथा कृत्वाथ मदनो मुमोचष्वपचाकृतिं।

पुरीं प्रायाति वेगेन कृत कार्यो मुदान्वितः।। 425 ।।

प्रविष्टो नगरी मध्ये ददर्ष रथमुत्तमं।

आयातं सन्मुखं रम्यं सौवर्ण्यं रत्न खंचितं।। 426 ।।

दिव्यैःमंगल कुम्भैष्च पूरितं स्त्रीजनैर्युतं।

नानादर्षतोद्योतं पताकाभिर्विराजितं।। 427 ।।

एवं विधं च दृष्ट्वा मदनो विस्मयाकुलाः।

प्रपच्छनिजविद्यां तु कस्येदं रथमुत्तमं।। 428 ।।

विद्ययापि ततो भाणि श्रृणुकाम निगद्यते।

भानोर्विवाह मांगल्य कुम्भेः पूरितमध्यकः।। 429 ।।

काहलैष्च मृदंगेष्च भेरीनादैष्च संयुतः।

कुम्भकार गृहा कुम्भान्नीत्वा यातिरथोत्तमः।। 430 ।।

सत्यभामागृहं हर्षात् प्रयातिस्त्रीजनैर्युतः।

तत्र मातुः सपत्नी सा तथा रुचिः तथा कुरू ।। 431 ।।

विद्यावाक्यं समाकर्ण्य ज्ञात्वा सर्वं विषैषतः।

मातुः शत्रुजनं बुध्वाचकार विकृताकृतिं।। 432 ।।

दधावसन्मुखं कृत्वा खरेणोष्ट्रयुतं रथं।

क्षोभयन् सकलान् लोकान् मदनो निज विद्यया।। 433 ।।

हस्यमानोजनैः सर्वैष्चर्णयामास तं रथं।

पातयामास कुंभोघान् खंडयामास तौरणं।। 434 ।।

धावन्नितस्ततः सोपि भानुलोकं विचूर्णयत्।

खंडिताः श्रवण स्त्रीणां पातितास्तु मुखद्विजाः।। 435 ।।

भग्नास्तु कुबरास्तासां चरणावैविभंजिता।

स्फाटितानि च वस्त्राणि विगुप्तास्तास्तदाखिलाः।। 436 ।।

मुखेभ्यो गीत संस्थाने विलापं तु विनिर्गतं।

एवं कृत्वा तु मदनो बभ्राम प्रति वीथिकां।। 437 ।।

मुक्त्वासौदंष मषकान् खरोष्ट्रव संयुत।

रथारूढः पुरीं सर्वान् बभ्रामोर्द्धमुखः स्मरः।। 438 ।।

तं विलोक्य जनासर्वे जगुरेव परस्परं।

किं नरोयं सुरो वा किं खेटोयं पन्नगोथ वा ।। 439 ।।

दैत्योथ चेंद्रजालं वा दृष्यते किमिदं ननु।

स्वप्नोथ वाथिजाग्रत सुमाया वाप्यथचाकिमु।। 440 ।।

कृष्णस्य नगरीमध्येक्रीडां शंका विवर्ज्जितः।

यः करोति न सो नूनं स्वल्पशक्तिर्भविष्यतिः।। 441 ।।

वदंतोपि जनाष्चैवं कुर्वन्तः कर पाडनं।

हास्य युक्ता पुनः सर्वे प्रोचुरेवं परस्परं।। 442 ।।

अद्य प्रभृतिनोदृष्टं कौतुकं परदुर्लभं।

कोपिमहानुभावोयं पुरी भ्रमत्यनाकुलः।। 443 ।।

इतिलोक वचः श्रृण्वन् मदनः प्रमदान्वितः।

भ्रमित्वा तु चिरं तत्र वेषमन्यं गृहीतवान्।। 444 ।।

गच्छन्नग्रेपुरीमध्ये ददर्ष जल वापिकां।

कनत्कांचन निर्माणं रत्नासोपान संयुतं।। 445 ।।

नाना स्त्री कृत रक्षां हि पवित्रं जल पूरितां।

एवं विधं च तां दृष्ट्वा विद्या प्राह मनोभवः।। 446 ।।

कस्येयं सुन्दरावापि मम विद्ये निरूपय।

विद्ययाभणितं तं च श्रृणु सत्यं मनोभवः।। 447 ।।

भानोर्मातुस्तु सत्याया विद्धिवापिं मनोहरां।

नारीभिः कृत रक्षां च लोकानामतिदुर्लभां।। 448 ।।

विद्या वाक्य समाकर्ण्य ह्रष्टो भूत्वा मनोभवः।

निज विद्या प्रभावेन विप्रो जातोविचक्षणः।। 449 ।।

योगपहेन संयुक्तष्छत्री दंडी सकुंडितः।

श्रुत्वाम्नायी च वेदवित्पिंगलाक्षः सदर्भकः।। 450 ।।

जान्वालंबिस्तु वस्त्रेण श्वेतेनासौ विभूषितः।

कोपीनेनापि संयुक्तः शुभ्र यज्ञोपवीतकः।। 451 ।।

वृद्धःकंपित गात्रष्च प्रौढः स्थूल शरीरकः।

एवं विधोद्विजोभूत्वा प्रोच्चरन्वैदिकीं ध्वनिं।। 452 ।।

तत्रागत्य जगादासौताभ्यः स्त्रीभ्यो द्विजोत्तमः।

शृण्वंतु वाक्मेकं पुत्र्यः किंचिच्चयाचये।। 453 ।।

स्नातुं मह्यं प्रयछन्तु वाणी नीरे मनोहरे।

कमंडलु जलेनैव पूरयित्वा तु दीयतां।। 454 ।।

पुरीं मध्येजलं नीत्वा दत्वा कस्यापितज्जलं।

शान्त्यर्थं याचयामीति भोजनं तस्य पार्ष्वतः।। 455 ।।

श्रुत्वा तस्य द्विजस्यैव वाक्यं विनय संयुतं।

प्रोचुस्तास्तं द्विजं रामा रे रे मूढमते शृणु।। 456 ।।

विष्णुः प्राण प्रियायाहि सत्यभामाभिधानका।

भानोर्मातातिं विख्याता न श्रुता किं त्वया शठा।। 457 ।।

सौभाग्यस्य निधानं या तस्य वापी मनोहरा।

द्रष्टु न लभ्यते चान्यैः स्पृष्टुं वार्त्ता तु का शठा।। 458 ।।

कोकयुग्मे स्तनाचेयं चारुहं सैष्चगामिनी।

अंगनेव प्रियानृणां दुर्लभा पापिनां द्विजा।। 459 ।।

यादवानां समूहेष्च भो जगानां तथैव च ।

पौरैः स्वजनवर्गैष्च सेव्यपादोपियः सदा।। 460 ।।

विष्णुस्तु वनिताभिष्च यदि मज्जतिमज्जति।

सत्यभामासुतः श्रीमान् सोपि मज्जतिनान्यकः।। 461 ।।

भवादृषां गति क्वात्र युक्तं वा प्रोच्यते भुवि।

भट्टातो व्रज शीघ्रं त्वं ताड्य सेवैष्णवैर्जनैः।। 462 ।।

तासामुक्तं समाकर्ण्य जगाद द्विजवैषभाक्।

केषवस्य सुतः पुत्र्योयदि मज्जति वापिकां।। 463 ।।

कथं न दीयते मह्यं मज्जनं वापिकाजले।

अहमप्यग्रिमः सूनुर्विष्णोरस्मीति निष्चितं।। 464 ।।

यदिवः कौतुकं किंचित्तर्हि श्रृण्वंतु में वचः।

भूपतिर्गज पुरोयोहि कौरवान्वय संभवः।। 465 ।।

दुर्योधन इतिख्यातः प्राथितः क्षिति मंडले।

तस्योदध्यभिधानाहि कन्यारुप गुणान्विता।। 466 ।।

प्रेषिता सा निजैर्लोकैर्भानो विवाह हेतवे।

ह्वतामार्गेतु भिल्लैः सा कुरुणां रक्षितामपि।। 467 ।।

भिल्लास्ते तां ततो नीत्वा ददुर्निजयतेस्तदा।

सोपितां कन्यकां दृष्ट्वा चिंतयामास मानसे।। 468 ।।

क्षत्रियस्य कुले जाता रूपयौवन भूषिता।

नेयं योग्या ममैवात्र योग्याराजकुलस्य हि।। 469 ।।

एवं संचिंत्यं चित्तेसौ ते भिल्लानामधीस्वराः।

स्थापयामास तां तत्र कन्यां सर्वत्र विश्रुता।। 470 ।।

तावत्तत्र समायातो भ्रमन्मार्गवषात् क्षितौ।

अहंरूपगुणैर्युक्तो नवयौवन भूषिता।। 471 ।।

तेनमां सुंदरं दृष्ट्वा चिंतितं च तदा हृदि।।

कन्येयं चास्य योग्यावै दीयते संषयं विना।। 472 ।।

इति संचिन्त्यतेनापि पादौ प्रक्षाल्य भक्तितः।

मह्यं समर्पिता सा हि कन्यारूपगुणान्विता।। 473 ।।

तत्समायुवती लोके न भूता न भविष्यति।

मत्सम्यामो न वरष्चान्यो वर्त्तते वसुधातले।। 474 ।।

विष्णोः पुत्र निमित्तं या प्रेषिता कन्यकोत्तमा।

सा तु मह्यं प्रदत्ताहि विष्णु पुत्रोभवाम्यहं।। 475 ।।

तदात्रवापिका नीर स्नातुं नो दीयते कथं।

द्विजवाक्यं समाकर्ण्य हसित्वा वनिता जगु।। 476 ।।

वृद्धस्त्वं जरयापूर्णाः रूपयौवन वर्ज्जितः।

क्व चायं निंद्यरूपस्त्वं क्व सा रूपयगुणान्विता।। 477 ।।

वृद्धत्वेपि हि कौटिल्यं हास्यां यौवन संभवं।

पूर्वजं न नहासीह तदे तत् कौतुकं महत्।। 478 ।।

यदुक्तं तु त्वया विप्रसर्वं तत् घटते ध्रुवं।

त्वं क्व विप्रजरापूर्णाः कुरुराजसुता क्व च।। 479 ।।

भिल्लैस्तु हरणं क्वात्र युता राजसुतैष्च सा।

सत्यातीतं वचो नूनं कथं जल्यसिवृद्धकः।। 480 ।।

इतिहास्य वचोभिष्च वार्यमानोपिसो द्विजः।

मन्दं मन्दं विवेसासौ प्रियोक्तिर्वापिका जले।। 481 ।।

कुपिता हठ ह्रत्याताास्ताडयामास तं द्विजं।

यदा लग्ना करास्तस्य तासां वृद्धद्विजस्य हि।। 482 ।।

तावत् ताः शोभन जाता कुरूपारूपवर्जिताः।

तस्यस्पर्षन स्त्रिण सर्वारूपगुणान्विताः।। 483 ।।

परस्परं निजं रूपं विलोक्य युवती जनाः।

संषयामास तं क्षिप्रं तासांप्रत्युपकारकं।। 484 ।।

कुपितोप्युपकारं त्वं करोषि द्विजनायक।

त्वा त्वत्समोनापरो लोके गुणवांस्तु दयापरः।। 485 ।।

विनिर्गतास्ततः सर्वा बाह्ये प्रमदपूरिताः।

वापिकायाष्च मध्यात्ता रूपालोकनहेतवे।। 486 ।।

कर्णाभ्यां तु विहीनाया जातास्ताः कर्ण भूषिताः।

काणाक्षि दिव्यनेत्रास्तु मूकावचन संयुताः।। 487 ।।

शुष्ककुचागुरुकुचा कुरूपरूप संयुताः।

अतिकृष्णासु गौरांगा जातास्ता वनितास्तदा।। 488 ।।

एवं विधं निजरूपं पश्यंतोपि परस्परं।

यावत् तत्र स्थिता बाह्ये तावद्विप्रेणतज्जले।। 489 ।।

कमंडलं निजं जप्त्वा जलं जग्राह वापिजं।

नीत्वातु जलं सर्वं बाह्ये वेगाद्विनिर्गतः ।। 490 ।।

ताभिस्तु वीक्ष्यमाणोसौ पूरयित्वा कमंडलु।

वापिकाया जलं ह्वत्वा जगामष्लथगात्रकः।। 491 ।।

विलोक्यमान रूपंता निजं तत्र परस्परं।

अन्योन्यं तु प्रषंषतिरूपं कांतिं तथा गुणान्।। 492 ।।

एका जगाद ते रूपं जातमत्यंत सुंदरं।

द्वितीयापि तदा प्रोचे श्रवणो तव सुंदरौ।। 493 ।।

तृतीयापि च तत्राह तरुण त्वं तावगतं।

जजल्य वचनं त्वन्या नेत्रयोस्तेतिरूपता।। 494 ।।

अपरापि तदा प्राहा जातौ ते कठिनौ कचौ।

तत्रोचेन्यावरारामा जातं रे जठरं कृषं।। 495 ।।

एव परस्परालापं कुर्वन्त्यस्ता स्थिता यदा।

तावदेका जलं पातुं गतावै वापिका जले।। 496 ।।

पतितां जलरहिता शुष्क तृणैष्चाछादितां।

जीर्णामिव च तां दृष्ट्वा निर्गता वापिकांतरात्।। 497 ।।

सा रामातु विनिर्गत्य तासां सर्वं निवेदयत्।

विगुप्तास्तु वयं सर्वास्तेन विप्रेण सांप्रतं।। 498 ।।

छÁयित्वा जलं नीतं वापिकाया दुरात्मना।

तस्या वाक्येन ता सर्वा विलोक्य शीर्णा वापिकां।। 499 ।।

ताम्रनेत्रारुषा सर्वा दधातुः पृष्ठतो द्विजं।

वदंत्योवचनं दुष्टं क्व यातु पापमाहनः।। 500 ।।

यावत्ताः पृष्ठितोनार्य्यो गच्छन्ति ब्राह्मणं प्रति।

तावच्चेष्टां तु विविधां कुर्वन् मध्ये जगाम सः।। 501 ।।

पुर्यास्तु हट्ट शोभां सोजहार सकलामपि।

हट्टेषु मणिजातीनां रत्नानां भूषणांस्तथां।। 502 ।।

शस्त्रवस्त्रधृतोदीनां सुगंध द्रव्यणामपि।

कर्पूरलवणादीनां धान्यानां तु तथैव च।। 503 ।।

सर्वेषां व्यत्पयं कुर्वन् पुरीमध्ये प्रयात्यसौ।

हस्त्यष्वाहनादीनां गवादीनां विषेषतः।। 504 ।।

करस्पर्षनमात्रेण चकार व्यतयं तदा।

यावदूर्ध्वमुखोयाति कुर्वन् नेवं विचेष्टितं।। 505 ।।

तावत्तत्र समायाता नार्यस्ता रोष पूरिताः।

गालीनां निकरैः कृत्वा शंपत्यस्तं तु बाडवं।। 506 ।।

वचल्गुर्वेगतोनार्यो विप्रस्यापि चतुः पथे।

रे रे दुष्ट जलं सर्वं नीत्वा याति कथं शठ।। 507 ।।

तासां वलान मात्रेण पाणिपात्रं द्विजोनहि।

भूमावास्फालतद्भग्नं यावत्तावदठ्तं जलं।। 508 ।।

वापी भूतं जलं सर्वं यत् नीतं निज विद्यया।

तत्सर्वं तत्र तेनापि मुक्तं कोपवषात् तदा।। 509 ।।

चतुपथं तदा सर्वं प्रवाहे नीयते ध्रुवं।

महानद्यास्तु पुरं वा समुद्रष्चलितः स्थिते।। 510 ।।

मुक्ताफलादिकं तत्र हेमरत्नादिकं तथा।

प्रवाहे वाहयत्सर्वमापणेभ्यो जलेनहि।। 511 ।।

आपणानि गृहाणीह वनानिवाहनानि च।

प्रवाहे जलजे तस्मिन् नीयंते पुरमध्यतः।। 512 ।।

तदालोकैरितिज्ञातं कल्पांतोयं समागतः।

अन्यथा सागरस्थित्या कथं चलति निष्चितं।। 513 ।।

तावत् ता वनिताः सर्वा प्रयलाप्यगता रथात्।

जनानां कौतुकं कृत्वातिरोधान्मदनस्ततः।। 514 ।।

पुनरग्रे जगामासौ पुरीमध्ये विनोदवान्।

द्वितीयं वाडवं रूपं नीत्वा यौवनभूषितं।। 515 ।।

पुष्पाणां सर्वजातीनां निकरं वा चतुःपथे।

मालाकार समूहैष्च गुंथ्यमानं विलोकयन्।। 516 ।।

दृष्ट्वा पुष्पमयं पुंजं मदनो विस्मयाकुलाः।

प्रपछ निजविद्यां स सापि तस्मै निवेदयत्।। 517 ।।

पुष्पाणिं सुत्यभामाया भानोर्विवाह हेतवे।

श्रुत्वा यतत्रागत्वासौ प्रोचेतातुष्चश्रक्वारिणः।। 518 ।।

कियंत मम पुष्पाणि सुंदराणि ददंति च।

सत्यायामंदिरं रम्यं यानि नीत्वा व्रजाम्यहं।। 519 ।।

हरेस्तु सत्यभामायास्तत्र दत्वा समाषिषं।

भोजनं याचयामीहयाभ्यां प्राप्नोमि वांछितं।। 520 ।।

विप्रोस्मि क्षुधयाक्रांतो मह्यंयछतु वेगतः।

तत्र भानोर्विवाहस्यसोत्सवो वर्त्तते तरां।। 521 ।।

तस्य वाक्यं समाकर्ण्य प्रोचुः पुष्पोपजीविनः।

अस्माकं वचनं विप्र शृणु त्वं हितकारकं।। 522 ।।

पुष्पाणि सत्यभामायाः सुत विवाह हेतवे।

रक्षितानि च सर्वाणि गुंथ्यंतेस्माभिः सांप्रतं।। 523 ।।

पुष्पस्य दलमेकं तु दातुं शस्तुवयं नहि।

अतोदूरतं वेगात् गच्छ गच्छ द्विजोत्तमा।। 524 ।।

तेषां वाक्यं समाकर्ण्य मदनोपि जगाविति।

शठायाः सत्यभामायाः सर्वेलोकाः शठाध्रुवं।। 525 ।।

इत्युक्त्वा तानि पुष्पाणि स्पृष्टा निजकरेणहि।

मंदार पारिजातादि वकुलोत्पलचम्पकाः।। 526 ।।

शतपत्राणि पुन्नागाः कमलानि जाति जूथिकाः।

तानि सर्वाणि वेगन जातात् अर्क मयानिहि।। 527 ।।

वंक्षत्वा ततष्चासौ जगाम लीलया युतं।

गंधाष्च विविधान् सर्वानापणेन यथा क्रमं।। 528 ।।

धान्यजातिं च सर्वांष्च यदुत्क्षष्टपरापरं।

तत् तु चान्यस्य स्थाने सौचान्यमेव नियोजयत्।। 529 ।।

रामठस्यापि स्थाने तु गजस्थाने खराष्चके।

हयस्थाने तु वेत्षरान् रामठं तत्र योजयेत।। 530 ।।

रामठस्यापि स्थाने वै कस्तूरिका जाता शुभा।

लवणं तत्र कर्पूरं कर्पूरं लवणादिभिः।। 531 ।।

गजोपकरणं सर्वं जातं रखमयं तदा।

खरोपकरणं तत्र गजानां चा भवत्तदा।। 532 ।।

रीरी सुवर्णता प्राप्ता स्वर्णं रीरीमयं तथा।

रत्नानि काचखंडाष्चतेपिप्राप्तास्तुरत्नतां।। 533 ।।

मुक्ताफलमयं ता तं धान्यं यौगंधरीयकं।

तथा मुक्ताफलानीह तथा जातानि पूर्ववत्।। 534 ।।

घृतं तु तैलतां प्राप्तं तैलं घृतमयं तदा।

कम्बलाः पट्टकूलत्वं पट्टकूलानि पूर्ववत्।। 535 ।।

एवं नाना विद्यां चेष्टां कुर्वन याति शनैः शनैः।

तावदग्रेतु संप्राप्तो राजमार्गं मनोहरं।। 536 ।।

मदमत्तगजानां च दाननीरैस्तथैन च।

कर्द्दमीकृतमार्ग त्वा द्विषमोदृष्यते तरां।। 537 ।।

तस्मिन् मार्गे तदागच्छन् ददर्ष वर मंदिरं।

तं दृष्ट्वा विस्मयाक्रांत प्रपछ निजविद्यकं।। 538 ।।

कस्यसौधर्मिदं विद्ये दृष्यते तु मनोहरं।

विद्यातु मदनं प्राह शृणुनाथ निगद्यते।। 539 ।।

तव तातस्यः तातो वसुदेवाभिधानकः।

तस्य गेहमिदं विद्धि स्वर्ग गृह विषेषकः।। 540 ।।

पुनः प्रपछतां विद्यां किमस्य वल्लभवद।

विद्ययापि तदा प्रोक्तं मेषयुद्धं तु वल्लभं।। 541 ।।

विद्यावाक्यं समाकर्ण्य मेषविद्यामयं स्मरः।

कृत्वा ततो पितं गेहं चलितो विस्मयाकुलः।। 542

स्वर्णतोरणसंयुक्तं ध्वजमालादिलंकृतं।

माणिदर्पण वृंदैष्च कुंभैर्भृगारकैर्युतं।। 543 ।।

मृगेन्द्रैः सरभौघैष्च व्याघ्रैरिंछक जातिभिः।

पितांगणं मनोज्ञं तद्विषोसौ तु मनोभवः।। 544 ।।

प्रतोलीमध्य तो याति यादवग्रे ददर्ष सः।

सभामध्यस्थितं सौम्यं निविष्ठं हरि विष्टरे।। 545 ।।

शस्त्रश्रमविधौदक्षै राजपुत्रैस्तु संयुतं।

तातस्य जनकं दृष्ट्वा हर्षतोसौ मनोभवः।। 546 ।।

कनत्कनक संकाषं पूर्ण चन्द्रमुखं शुभं।

दिग् नागकर संकाषं लंबवृत्त महाभुजं।। 547 ।।

शैलेन्द्र भित्ति संकाषं वक्षस्थल विराजितं।

इन्द्रनीलमणिछाय वक्रकेष विराजितं।। 548 ।।

कम्बु कंठ सुनाभिं च रक्ताधर विषोभितं।

तद्वच्च पाणिपादं च कुंद दत्तं मनोहरं।। 549 ।।

एवंत मातकं वीक्ष्य तुष्टोभून्मदनो बली।

गजाष्वषिखाविषदं शस्त्र विद्या विषारदं।। 550 ।।

सौम्यं स्वभाव ललितं दूरतोप्यनमन्मुदा।

ततो कोपि च तं दृष्ट्वा मेष हस्तं युवानकं।। 551 ।।

वृत्तांगयष्टिं शूरं च बहुषोभा विराजितं।

मंजीरबद्धकंठं च सुवक्ररूक्षश्रृंगकं।। 552 ।।

एवं मेषं समालोक्य चित्ते तु मुदितोभवत्।

प्रपछतं नरं शौरि सादरं स्वयमेव हि।। 553 ।।

कस्यायं सुन्दरो मेषस्त्वानीत क्वेन हेतुना।

सोवाचन्मम मेषोयं विषमष्चाति दुर्ज्जयः।। 554 ।।

न हास्यं वर्त्तते नाथ नितरां सबलोहङः।

विजितानेन बहतो हडयुद्धे हडापुरा।। 555 ।।

हडयुद्धविधौ दक्षं श्रुत्वा त्वां तु समागतः।

अस्यात्र विषदं युद्धं विलोकयितुमर्हसि।। 556 ।।

विलोक्यते त्वया युद्ध यदिवास्य विलोक्यते।

नपरोवर्त्तते भूमौ परिक्षा निपुणोनरः।। 557 ।।

तस्य वाक्य समाकर्ण्य जगादव हरेः पिता।

मज्जानुं प्रतिमुंचत्वं यदि मेषं सुदुर्ज्जयं।। 558 ।।

मज्जानुमथने दक्षो हडस्ते यदि जायते।

तदायं सबलो मेषो नापरस्तु धरातले।। 559 ।।

तस्य तद्वचनं श्रुत्वा जगाद हडपालकः।

नैवसुंचाम्यहं मेषं चपलं सबलं दृढं।। 560 ।।

हरेस्तातमहं ज्ञात्वा यदि मुंचामि त्वां प्रति।

तदा तव जनैरेतैर्मारयेहं न संषयं।। 561 ।।

इमं गृहाणमे मेषं यदि नेतुं तु वांछसि।

पातयित्वा छलेमांवै कथं गृह्णासि मे हडं।। 562 ।।

मेषो मे नितरां नाथ समर्थो वर्त्तते ध्रवुं।

कथं वा मुच्यते चायं त्वज्जातुं प्रति सांप्रतं।। 563 ।।

यदि भूतलगतं पूज्यं करोति सबलोहडः।

तदा तु यादवाष्चैते किं न कुर्वन्ति मांध्रुवं।। 564 ।।

तस्य तद्वाक्यमाकर्ण्य हसित्वा सौ नृपोवदत्।

मुंचदोषं न ते चात्र मज्जानुं प्रतित्वत्हडः।। 565 ।।

वसुदेव वचः श्रुत्वा जगौपरिजनानसौ।

पात्यते यदि भूपोयं ममदोषलवोपिन।। 566 ।।

इत्युक्ते ते जनाः प्राहुस्तव मेषो वराक कः।

तेनायं पात्यते मूढ वसुदेवो बलीकथं।। 567 ।।

सर्वेषां वचनं श्रुत्वा वज्रतुंडतु तं हडं।

मुमोचासौ नृपोवेगात् जल्यन् पूज्य सहस्वभो।। 568 ।।

यदि त्वं तु समर्थोसि प्रधान पुरुषोसि वा।

आयातं दुर्ज्जयं चैनं सहस्वेति सुदुर्ज्जयं।। 569 ।।

प्रोच्येमाने तदा तस्मिन् प्रधाव्यासौ हडस्तदा।

जघानमस्तके नैव तत् जानुं ते वा ध्रुवं।। 570 ।।

तथा हतो यथा चासौ मुर्च्छां माप्य धरांगतः।

पतितं वसुदेवं तं वीक्ष्य यादवे पुंगवाः।। 571 ।।

प्रधाव्यचागताः सर्वे कर्त्तुं तस्य प्रतिक्रियां।

शीतोपचारयोगैष्च मलया गुरुचंदनैः।। 572 ।।

यावत्वेवसुदेवस्य संज्ञामानंति यादवाः।

तावत्प्रस्तावमालोक्य हडं नीत्वा तु निर्गतः।। 573 ।।

निजं पितामहं कृत्वा गर्वेण तु विवर्ज्जितं।

सस्मितोमदनष्चासौ बाह्येनिर्गत्य यातवान्।। 574 ।।

तदामार्गवषादǿच्छन् ददर्षाति मनोहरं।

मोहोत्सवैः समायुक्तं सुत विवाह संभवैः।। 575 ।।

ध्वज तोरण मालाद्यैर्भूषितं मंडपैर्युतं।

एवं विधं गृहं वीक्ष्य विद्यां प्रपछमान्मथः।। 576 ।।

कस्येदं सुन्दरं विद्ये मंदिर भुवनोत्तमं।

विद्या प्राह तु सत्याया भवनं लोकविश्रुतं।। 577 ।।

विद्या वाक्यं समाकर्ण्य प्रमोदं परमं गतः।

निजमातृ सपत्न्यास्तु वीक्षेहं गृहमुत्तमं ।। 578 ।।

एवं विमृष्य मदनो सर्वविद्या विषारदः।

विप्रो बभूव हर्षो सौ चतुर्दष प्रमाणकः।। 579 ।।

उच्चै पठंश्चवेदं सो विषालाक्षोति पिंगलः।

अत्यन्तं चपलो वादीयट्ष्च बहुभाषणः।। 580 ।।

भोजनार्थं विवेषा सौ सत्यभामा गृहं वरं।

सत्यभामां समालोक्य स्थितां सिंहासने वरे।। 581 ।।

स्वस्त्यस्तु चक्रनाथस्य मानसे राजहंसिनी।।

जगाद देवि हे सत्ये विस्तीर्ण पुण्य भाजिनी।। 582 ।।

शास्त्रार्णवस्य कृत्स्नस्य पारमाप्तो द्विजोत्तम।

भोक्तुं वांछाम्यहं त्वत्तो क्षुधयाचाति पीडितः।। 583 ।।

उपभोजय मातसन्तृयष्टोष्ठं कृष्ण वल्लभे।

श्रुत्वेति वचनं तस्य हसिता सत्यभामिका।। 584 ।।

हसितां तां समालोक्य द्विजवेष धरो वदत्।

नेच्छासि भोजन दातु यदि त्वं हससे शुभे।। 585 ।।

तस्मिन् दिने द्विजाः सर्वे द्वारिकापुरिवासिनाः।

निमन्त्रिता विवाहेतु भोजनार्थं च सत्यया।। 586 ।।

ते तत्र मिलिताः पूर्वं तावत् तत्र समागतः।

मनोभवो यथाचैनं भोजनं कृष्णवल्ल्भां।। 587 ।।

मदनस्य वचः श्रुत्वा प्रोचुस्ते द्विजपुंगवाः।

भो भो निर्भाग्य विप्रस्त्वं याचसे भोजनं किमु।। 588 ।।

सत्यभामातु यं दृष्ट्वा वीक्ष्यते सा च भाग्यवान्।

तुष्टा हरिवधू नूनं कृतार्थं कुरतेन किं।। 589 ।।

अतोगजहयादीनां रत्नानि विविधानि च।

कांचनं पट्टकूलानि गोधनं पत्तनानि च।। 590 ।।

द्रव्यं देषादिकं चान्यन्नरीणां च कदंबकं।

याचितं न कथं मूढत्वया भाग्योष्भितेनहि।। 591 ।।

अथवा दूषणं ते किं वचो भाग्यानुसारिकं।

गतपुण्य जनानां तु मुखे वाक्यं हितादृषं।। 592 ।।

प्रत्युत्तरं जगादासौ पटुवाङ्मदनोद्विजान्।

मृग्यं राजादिकं यद्वोतत्सर्वमन्न हेतवे।। 593 ।।

तस्मात्तदेवयाचेहं सत्यभामां हरेः प्रियां।

परिपूर्ण धनं चान्नं ममायं स्वादुकृद्वरं।। 594 ।।

तददातु सत्यभामामे सुत मंगल हेतवे।

मयितुष्टे जगत्तुष्टं भुंक्ते भुक्ताद्विजोत्तमा।। 595 ।।

अतोमां विधिना मातः तुं भुंजस्वयथेष्ठकं।

तेन वाक्येन तुष्टा सा जगौ परिजनान्निजान्।। 596 ।।

भो परिवार लोकामे नीत्वा चैनं महानसे।

यथेष्ठं भुंज्यध्वं तु ब्राह्मण क्षुधयातुरं।। 597 ।।

विप्रोयं सर्व शास्त्रज्ञो विवेकी वर्त्तते तरां।

महादरेण विप्रेनमभि भक्त्या प्रभोज्यतां।। 598 ।।

इत्युक्त्वा निजलोकांष्च विप्रं पुनरुवाच सा।

भुंजयिष्यंति मे लोका गच्छतत्र द्विजोत्तम।। 599 ।।

सत्यभामा वचः श्रुत्वा जगाद द्विज वेषभाक्।

अधमैरिमैर्द्विजैः सार्द्धं भुंजेनाहं शठात्मभिः।। 600 ।।

पाखंडिभिः कुषीलैष्च सुतदारादि वेष्टितैः।

सन्ध्या क्रियादि हीनैष्च व्रताचरण वर्जितैः।। 601 ।।

वेद वेदांगहीनैस्तु नाम्नैव वाडवैरिमैः।

निविष्टैर्विप्र सदसि ब्रह्मकर्म विवर्जितै।। 602 ।।

सत्यहीनैर्द्विजैः सार्द्धं भोक्ष्येहं कमंबिके।

तस्माद्विप्रगणादेतात् पृथकदेयं ममासनं।। 603 ।।

इमेतु पतिता देवि किमेतैः कार्यमेवते।

सर्वलक्षणहीनैस्तु केवलं धनकांक्षिभिः।। 604 ।।

सर्वलक्षण संपन्नं सर्वविद्या विषारदं।

भुंजयस्व द्विजं मत्वालोकद्वय सुखप्रदं।। 605 ।।

मायि तृप्ति ध्रुवं तृप्तं गवादि ब्राह्मणादिकं।

पात्राय चात्रयद्दत्तं तत्सर्वं पुण्यहेतवे।। 606 ।।

अखिलार्थ विदमह्यं प्रयत्नमंबिके कुरू।

तरितुं तारितुं योहं समर्थं पात्रमस्मिवै।। 607 ।।

किमेभिरधमैः सर्वैः कोटिसंख्यैर्द्विजैः शतैः।

वेदषास्त्रविहीनैष्च व्रतषील पराङ्मुखैः।। 608 ।।

तस्य वाक्यं समाकर्ण्य सत्यभामा निजान्।

जगाद च स्मितं कृत्वा विस्मयाकुल चेतसा।। 609 ।।

भो भो परिजनाष्चायमादरेण घनेन हि।

भुंजयंतु विषेषेण विप्रोवेदार्थ पारगः।। 610 ।।

आहूतो सौ परिजनैर्भोजनार्थं बटूत्तमः।

तत्रागतो भवत्वेवं भणित्वास्मित चेतसः।। 611 ।।

तत्र विप्रगणास्यापि प्रमुक्ताः पट्टकाघनाः।

तेषुचाग्रेनिविष्टोसौ क्षालनाय ददौ पदं।। 612 ।।

ततो विप्रगणाः सर्वे दृष्ट्वा तत्र शठं बटूं।

कुपिता निज चित्ते ते जगुरेवं परस्परं।। 613 ।।

पापोयं जातिहीनोवै सर्वविप्रगणादयं।

विवेकं नैव जानाति निविष्ट चाग्र पट्टके।। 614 ।।

तदाकैष्चिच्च वृद्धैष्च प्रोक्तुं तिष्ठ त्वयं शठः।

अनेनाधर्मानंदेन कलहो क्रियते कथं।। 615 ।।

पादयोर्युगलं सोपि प्रक्षाल्य वेगतस्तदा।

समागत्य निविष्टोत्र चाग्रपीठे कलिप्रियः।। 616 ।।

क्षालयित्वा निजौ पादौ ततो विप्रगणाष्च ते।

पश्यंति च समागत्य तावदग्रे स्थितः शठः।। 617 ।।

तं दृष्ट्वा कुपिता विप्रा हसित्वा गर्वपूरिताः।

जगुरेवं ततः सर्वे पापोयं कलहप्रियः।। 618 ।।

जातिं कुलं तथा गोत्रं वेदं च प्रवराणि च।

ज्ञायतेनास्य मूढ़स्या शाखाहीनोद्विजोधमः।। 619 ।।

वचसापि परं क्षुद्रो सोधोत्र भुंजते कथं।

अपरे केचित् तत्रोचुः किं साध्यं कलहेन हि।। 620 ।।

अत्रचैकाकिनं मुक्त्वा पापमेनं शठंबटू।

अपरे भवने गत्वा भुजामो वै विषेषतः।। 621 ।।

एवमुक्त्वा ततः सर्वे विप्रालज्जासमन्विताः।

गतास्तु कुपिता चित्ते पृथुग्गेहं यदा तथा।। 622 ।।

तथापिचाग्रमेपीठे निविष्टो सौ बटूत्तमः।

दृष्ट्वा तं कुपिताः सर्वे द्विजास्तं बटुकं प्रति।। 623 ।।

सत्यया वीक्ष्यमाणे सौ प्रायेण कलह प्रियः।

द्विजाः परस्परं प्रोचुः दुष्टोहं जातिवर्ज्जितः।। 624 ।।

द्विजवेषधरो नूनं द्विजद्वेषी नरोधमः।

सर्ववेद विधौ दक्षान् स्मृतिषास्त्रार्थ पारगान्।। 625 ।।

जातिवंष कुलोपेतान् सर्वविद्या विषारदान्।

त्रिपाठकांष्चतुर्वेदान् द्विज वेदान् द्वियाज्ञिकान्।। 626 ।।

निक्वारको महादुष्टः पापोयं कुद्यतां ध्रुवं।

द्विजद्वेषिनिपापेहि ताडिते पातकं नहि।। 627 ।।

इत्यादिभाषण परानालोक्य द्विजपुंगवान्।

हासित्वा मदनः प्रोचे भो भो श्रृण्वंतु वाडवाः।। 628 ।।

यूयं वेद विदोनूनं षड्भिरंगैः समन्विताः।

तत्रापि किं प्रमाणं हि यद्याचारविवर्ज्जिताः।। 629 ।।

ब्रह्मत्वे सति किंचार प्रमाणं नर लक्षणे।

ब्राह्मण्यं लक्षणं लोकैः दुप्रापदययायुतं।। 630 ।।

यत्राजगौ हयाष्चैव नरा नृपगणास्तथा।

मातरं पितरं चापि हूयते सोत्र किं प्रमा।। 631 ।।

पुण्यं तु कथ्यते यत्र मारितैः जीव राषिभिः।

प्रमाणं तत्कथं नूनं शास्त्रं वेदोथवा नरः।। 632 ।।

मधुमांसंतथा मद्यं भोजनं यत्र कीर्त्तितं।

तत्र वा प्रोच्यते धर्मो तदसत्यं न संषयः।। 633 ।।

अगम्यागमनं यत्र दासीदानादिकं तथा।

अपेयमेव पेयं च तत्र धर्मो कथं भवेत्।। 634 ।।

इत्यादिकं विरुद्धं च यत्र वाक्यं तु प्रोच्यते।

सकथं वाडवा वेदः प्रमाणं क्रियते नृभिः।। 635 ।।

इत्युक्ते ते द्विजाः सर्वे जाताः कोपेन पूरिताः।

प्रोत्तस्थुर्मदनं वेगात् ताडनायाति वेगतः।। 636 ।।

नियंतु निधनं पापं श्रुति स्मृति पराङ्मुखं।

विप्राणां निंदकं दुष्ट ंनात्र दोषोमनागपि।। 637 ।।

हंतुं प्रचलितास्तं च कोपात् कंपित कूर्चकाः।

मदनेनापि तान् दृष्ट्वा सहसा हंतुमुद्यतान्।। 638 ।।

मुक्त्वा विद्यां निजां तावद्वल्गापिताः परस्परं।

अन्योन्यं निजगात्राणि ताडयंतोतिकोपतः।। 639 ।।

स्वदोर्भिर्मुष्टिः घातैष्चषिरोभिस्तु षिरांसिते।

स्वेदवंति शरीराणि धारयंतस्तदा शठाः।। 640 ।।

पतंतोपि स्खलंतस्ते व्रजंतोपि रूषातुराः।

वदन्तोथ स्फुरंतस्ते लुठंतो वसुधातले।। 641 ।।

नदंतो दुःखतः सर्वे रुदंतो रूधिरारूणाः।

वृहद्भि मुष्टिघातैष्च युद्धं कृत्वाति रौद्रकं।। 642 ।।

विलक्षास्तु विषणाष्च जाताः सर्वेद्विजास्तदा।

केचिन्मूर्च्छा समापन्ना पतिता क्षितिमंडले।। 643 ।।

इत्येवं कौतुकं दृष्ट्वा हसंती सत्यभामिका।

जगौ द्विजगणान् सर्वान् युज्जते भो कथंद्विजाः।। 644 ।

दास्यामि भोजनं चाहं सर्वेषां भवतामिह।

भवद्भिस्तु कथं युद्धं क्रियते भो ममाग्रतः।। 645 ।।

हास्यं तिष्ठति नो तस्या बटुकं तु जगाद सा।

भो भो बटोत्वमप्यत्र कथं युद्धंसिवाडवैः।। 646 ।।

तस्यावाक्यं समाकर्ण्य जगादागत्य तत्र सः।

ज्ञातं तु सत्यभामेति चरितं दुष्ट चित्तजं।। 647 ।।

एकाकिनं तु मामत्र द्विजाष्चैतेप्य संख्यकाः।

हंतुं समुद्यता दुष्टा वारिता न कथं त्वया।। 648 ।।

त्वयैवैते समुद्दिष्टामारणाया शठा मम।

क्रोधिकारोन्यथाचैष मम विप्रस्य मारणे।। 649 ।।

तदातु सत्यया प्रोक्तुं ज्ञातं सर्वं विचेष्टितं।

यो येन मारितो नूनं ज्ञातः सोपि मया ध्रुवं।। 650 ।।

त्वमप्यत्रममाग्रेहि भुंक्ष्व स्वद्विजनायका।

भो भो परिजनाष्चैनमत्र भुंजाप्यतां द्रुतं।। 651 ।।

इत्युक्ते परिजनैः वेगादासनं तत्र स्थापितं।

सौ वर्ण भाजनोपेतमत्यादार समन्वितं।। 652 ।।

प्रक्षाल्य च करौ सोपि स्थितो यावत् मनोभवः।

तावच्च परिजनैरेवं विविधान्नं समाहृतं।। 653 ।।

मुक्तं फलादि संयुक्तं पक्वान्नैः विविधैर्युतं।

तदा तु सत्यया प्रोक्तुममृतं कुरू हे द्विज।। 654 ।।

तदा तु मदनेनोक्तुं श्रृणु मातं विचक्षणे।

ममान्नं तृप्ति पर्यन्तं मुंचनीयं त्वया नघे।। 655 ।।

इत्युक्ते सत्यया प्रोक्तं भुंक्ष्व भुंक्ष्व द्विजोत्तम।

तवात्रकंठ पर्यंतं मुंचयिष्यामि सांप्रतं।। 656 ।।

इत्युक्ते मदने वेगाद्वृहत्पिंडैस्तदाद्भुतं।

लग्नो भौक्तुं क्रमं त्यक्त्वा यथा हस्ती बुभुक्षितः।। 657 ।।

तदाध्वं च ददध्वं च जल्यन्नेवं क्षुधातुरः।

पतंतमपि पात्रेसौ वुभुजे वेगतोखिलं।। 658 ।।

जनौघास्तावत् संतुष्टाः क्षिपंति भाजने वरे।

विविधान्नं तु समानीय क्रमे न परिवर्ज्जितः 659 ।।

यादवानां तु या योषाः समायाता निमंत्रिताः।

भानोर्विवाहमुद्दिष्य ताः सर्वाः कौतुकान्विताः ।। 660 ।।

विविधान्नं समानीय चाग्रता वाडवं प्रति।

मुंचंतिस्म विनोदेन बुभुजेसोपि वेगतः ।। 661 ।।

रणन्नूपुरं संयुक्ता भूरिभूषणा राजिताः।

अन्योन्यं स्वनितंवादि पीडयंत्यः समागताः।। 662 ।।

योषितो मुंचयंतिस्म वाडवाय स कौतुकाः।

मंडकान् मोदकौघाष्च पूतान् वटक संयुतान्।। 663 ।।

घेवरान् फेणिकांष्चैव परमान्नं तथैव च।

खज्जकान् मोदकान् रम्यान् परा लापसिका तथा ।। 664 ।।

उंदनं मुदठ्सूपीच शाकानि विविधानिच।

घृतं तैलं तथा दुग्धं दाधिं तक्रं विषेषतः।। 665 ।।

ताभिर्न्नारीजनैस्तस्मै यन्मुक्तं तच्चभक्षितं।

सत्यभामा गृहे किंचिदन्नं पक्वान्नकं तथा।। 666 ।।

अनिष्पन्नं तथा पक्वां तत् सर्वं तेन भाक्षितं।

मुद्गास्तंदुलाष्चूर्णं च व्रीहयोपि यथास्तथा।। 667 ।।

गोधूमामाष संयुक्तायत् किंचिदपरं तथा।

सत्यभामा गृहस्थं यत् तत् सर्वं तेन भक्षितं।। 668 ।।

गजानां तुहयोदृष्ट्राणां निमित्तं यातुनिर्मिता।

यवागौर्भक्षितातेन क्षुधयातुर चेतसा।। 669 ।।

सत्यभामा गृहे तावत् जाताः कोलोहलो महान्।

अहोकोपि महान् प्रेतो द्विजवेषेणचागतः।। 670।।

सत्यभामा गृहेयच्च पुत्र विवाह हेतवे।

सर्वान्नं भक्षितं तेन कथं जीवति प्रति हं।। 671 ।।

अन्योन्यं सर्वत्राणि नितम्बस्तनपीडनं।

कुर्वन्त्योत्र समायाता योषितः कौतुकान्विताः।। 672 ।।

वीक्षां बभूवुस्तं विप्रंसोपि भुक्त्वा तदाखिलं।

दृदध्वं शीघ्रमेवान्नामिति वाक्यं जगौतरां।। 673 ।।

कथं नोमुच्यते लोका भोजनं भाजने मम।

दरिद्रा कृपणा सत्या भवतां किं तु दूषणं।। 674 ।।

सत्यभामे मदीयं त्वं श्रृणु वाक्यं मनोहरं।

भानुस्ते तनुजो नूनं नाथोनारायणः स्वयं।। 675 ।।

खेटाधीषोपि ते तातः स्त्रीणां त्वमसि स्वामिनी।

कृपणत्वं तथाप्यत्र कथं तु ध्रीयते त्वया।। 676 ।।

एकोहं स्वल्प भोजी च त्वदग्रे यो न तर्पितः।

तस्याग्रेचापरे लोका प्रीणिष्यंति कथं खले।। 677

ममोदरे तवान्नं क्व कृपणाया न स्थास्यति।

अतो गृहाण पापेत्वं तवान्नं सकलं शठे।। 678 ।।

इत्युक्त्वा वमयामास सत्यायास्तु तदाग्रतः।

पूरितांचांगणेहं च सत्यां मग्नां तथा करोत्।। 679 ।।

द्विजाः सर्वे तदातत्र मग्नाः सर्वास्तु योषितः।

चित्रसालीं तु चित्रामं पेटिकां वस्त्रधारिणीं।। 680 ।।

शीतरक्षाकदंबं च तूलिका निवहं तथा।

अत्र किं बहुनोक्तेन पूरितं निखिलं गृहं।। 681 ।।

ह्रत्वा जलं तदा सर्वं निर्गतोमदनस्तदा।

प्रतोल्याबहि निर्गत्य चिंतां चक्रे तदाहृदि।। 682 ।।

अतोव क्वच गच्छामि गच्छेमार्ग्र वषादहं।

गच्छन्नग्रे ददर्षासौ सुन्दरं मंदिरं वरं,।। 683 ।।

गजाष्वनरवृंदैष्च पूरितं तु महोत्सवैः।

एवं विधं गृहं दृष्ट्वा विद्यां प्रपछ मन्मथः ।। 684 ।।

कस्येदं सुंदरं गेहं विद्यत्वं मे निरूपय।

विद्याया तु तदा प्रोक्तं श्रृणुनाथ निगद्यते ।। 685 ।।

तवमातुर्गृहे विद्धिरुक्मिण्याः सोत्सवैर्युतं।

विद्यावाक्यं समाकर्ण्य ह्रष्टो भून्मदनस्तदा।। 686 ।।

जग्राह क्षुल्लकं वेषं क्षीणांगोति विरूपकः।

दुर्गन्ध वदनोपेतः षितदंतोल्यवक्र कः।। 687 ।।

उद्दंतुरोविरूपाक्ष शुष्क गात्र कुलक्षणः।

दीर्घपादौति ह्रस्वौ च हस्ताभ्यांष्चाति श्यामकाः।। 688 ।।

कुटिलांगुलि घोषाष्च शुष्क जंघोडति निंद्यतः।

निर्मांसक स्फिक् भग्नोरूपृष्ठिस्तु कुटिलोदरः।। 689 ।।

दंडी चापि करंकीच कोपीनावृत गात्रकः।

एकं खंडेन वस्त्रेण भिक्षा पात्रेण संयुतं।। 690 ।।

कमंडलुयुतो दीनः स्फुटितांहि करांगुलिः।

व्रणीत्वेवं विधो भूत्वा विवेष जननीगृहं।। 691 ।।

विराजमानं माणिभिः समंतात् सुंदरं घरं।

भेरीदुंदुभिशंखौघ मृदंगपटहादिकैः।। 692 ।।

वीणावंषादितालैष्च झल्लरीयण वैरपि।

तेषां नाद समूहैष्च पूरितं सर्वतोगृहं।। 693 ।।

श्रीखंडकालागुरुभि धूप धूमैः प्रधूपितं।

मंदिरं तु पुरीं चापि समस्तं गगनांगण।। 694 ।।

एवं विद्यं गृहं तस्या विवेष क्षुल्लको यदा।

तदा ददर्षतां देवीं निविष्टा विष्टरे शुभे।। 695 ।।

बहुव्यापार संयुक्तां नारी निवह वेष्टितां।

जिनेन्द्रभवनस्याग्रे स्थितां सर्वगुणान्विता।। 696 ।।

नीलाबंधखंड संकाष देह दीप्ति धरां वरां।

पूर्णेंदुर्विवसंकाष मुखबिंब विराजितां।। 697 ।।

बंधूकपुष्प संकाष पक्वा बिंब समाधरां।

विकषकुंदवद्वंतां पाणिपादां तु कंजवत्।। 698 ।।

कनत्कांचन रत्नैष्च कृत भूषां मनोहरां।

सर्वलक्षण संयुक्तां सर्वावयव सुंदरां।। 699 ।।

एवं विधां च तां दृष्ट्वा कामोह्नदिविचिंतयत्।

एषा सच्यथवा कीर्त्ति ब्राह्मी वा सूर्य कामिनी।। 700 ।।

किं वा शम्भोः परापत्नी किं वा पन्नगरावूधूः।

जिताः सत्यनयामन्ये सर्वांश्चामरयोषितः।। 701 ।।

विलासिनी जनानां हि रूपं नीत्वा तु वेधसा।

निर्मितानि तयं मन्ये कृष्णर्थं प्रीतिचेतसा।। 702 ।।

जिनेन्द्र भवनस्याग्रे मंडपाध स्थितां च तां।

न नाम मनसा कामो जननीं तुष्टमानसाः।। 703 ।।

को वा पूज्यजने प्रीतिंनोधत्ते विजयान्वितः।

उत्पन्नष्चोत्तमे वंषे पूज्ये प्रीतिं करोति सं।। 704 ।।

आयांतं तं समालोक्य यतिवेषधरं तदा।

रुक्मिण्यापि समुत्तस्थौ जिनधर्मे प्रभाविका।। 705 ।।

सन्मुखं तं तदा गत्वा नत्वा सा पदपंकजं।

इच्छाकारं परं चक्रे गत भूतल मस्तकाः।। 706 ।।

वर्णिनापि तदाप्रोक्तुं दृष्ट्वास्या विनयं महत्।

दर्षनस्य विणुद्धिते भूयान्मात भवे भवे।। 707 ।।

दत्ते सिंहासने चासौ निविष्टः क्षुल्लकः शठः।

रत्नमरीचि चक्रेणोद्योतिते भवनांगणे।। 708 ।।

उत्तंगस्तन भारेन तनुमध्याति पीडिता।

वृहद्वेलां स्थिताग्रे च दृष्ट्वा क्षुल्लक वेषभाक्।। 709 ।।

ज्ञात्वा तु दुःखतां कष्टात् स्थितां चाग्रेहि मातरं।

जगादवचनं रम्य मात्राग्रेचोपवेष्यता।। 710 ।।

इत्युक्तेथ निविष्टा सा धर्मस्नेहेन पूरितां।

सम्यक्त्वस्य परां वार्त्तां चक्रे सा तेन वर्णिना।। 711 ।।

अन्योन्यं प्रीति संयुक्तौ जिन शासन भाविनौ।

चक्रतुद्धर्मजां वार्त्तां प्रियालापौ विचक्षणौ।। 712 ।।

नष्ट कुदृष्टि मोहौतौ स्थितौ मायोष्भितौ तदा।

यतिवेषधरः प्रोचे रूक्मिणीं प्रीति मानसाः।। 713 ।।

श्रृणु देव महाभाग्ये कृष्ण भार्यै शुभाषये।

बहुतीर्थानहं कृत्वा दृष्ट्वादेषमनेकषः।। 714 ।।

प्रसिद्धिं तव सम्यक्त्वे श्रुताचात्र समागतः।

यादृषी त्वं श्रुता पूर्वं तादृषीनोधुना किमु।। 715 ।।

मार्गश्रमज तापेन पीडितोहं न संषयं।

त्वयान दुष्णपानीयं नदत्तं पादक्षालनं।। 716 ।।

भो जनस्यापि चिंता तु न कृता सांप्रतं त्वया।

वार्त्ता चात्र समारब्धा विवेक परिवर्ज्जिता।। 717 ।।

तस्योक्रतु समाकर्ण्य चिंतित च तया हृदि।

सत्यं वदति धन्योयं विवेकेनास्मिवर्ज्जिता ।। 718 ।।

तयापरिजनं प्रोक्तुं मीषदुष्णं जलं वर।

अनीयतां द्रुतं चात्र क्षालयामि पद द्वयं।। 719 ।।

यदि परिजनाः सर्वे जलानेतुं गतास्तदा।

पावकस्तंभितं स्तेन माया कपटं चेतसा।। 720 ।।

जलं तु शीतलं जातं पावकोज्वलतेनहि।

तदाव्रणी जगावेवं क्षुधया पीडितोस्म्यहं।। 721 ।।

दीयतां दीयतां मह्यं भोजनं चास्ति चेत् तव।

न शक्तोहं क्षणं स्थातु ब्रूहि त्वं किं करोम्यहं।। 722 ।।

गत प्राणोस्म्यहं जात देहि मे भोजनं द्रुतं।

तदा तु रूक्मिणी वेगात् स्वयमेव समुत्थिता।। 723 ।।

अग्निं तु प्रकटं कर्त्तुं प्रवर्त्तस्वयमेवहि।

तथापि ज्वलते नासौ स्तंभितो मदनेन च।। 724 ।।

धूम्राकुला तदाजाताष्लिथ केषाथ रूक्मिणी।

वसिता जिनधर्मेण कृष्णं चित्तं न चाकरोत्।। 725 ।।

समाकुलां तु तां दृष्ट्वा जगादयति वेषभाक्।

उष्णेनैव जलेनात्र पूर्यतां पूर्यतांबिके।। 726 ।।

पक्वान्नं मंदिरे तेहि यदि किंचित् प्रवर्त्तते।

तदातमेवमह्यं त्वं प्रयच्छ भोजनं शुभं।। 727 ।।

मृतेमयि ततो नूनं कार्यं किं भोजनेन ते।

पूत्कारं कुरूते चासौ क्षुधयापरिपीडितः।। 728 ।।

भाजनेषु च सर्वेषु विलोकयति रूक्मिणी।

तावद्विद्या प्रभावेन तेनान्नमखिलं ह्रतं।। 729 ।।

विलोक्यमाना सर्वत्र चैकस्मिन् भाजनेवरे।

विष्णोऽर्थं तु निष्पन्ना वर्त्तते मोदकादष।। 730 ।।

एकैकंचाति दुःखेनयांष्च भक्षति केषवः।

तान् दृष्ट्वा चिंतयामास रूक्मिणी चिंतयातुरा।। 731 ।।

एतस्मै क्षीणगात्राय यदि दास्यामि मोदकान्।

प्रापयिष्यति पंचत्वं तदा हत्या ममैवहि।। 732 ।।

अन्यमन्नं न पश्यामि क्षुधया पीडितो ह्ययं।

न ददामि यदाचैतांस्तदा दास्याति गालिकां।। 733 ।।

अतोभयातुरां साथ वर्णिनं चाऽसने शुभे।

निवेष्यथालिकां चाग्रे करयोः क्षालनं ददौ।। 734 ।।

क्षलितौ तु तदा तेन वर्णिना वेगतः करौ।

जगादमुंचमुंचान्नं मया स्थातुं न शक्यते।। 735 ।।

विमृष्टं तु तया चैवं यद्यर्द्धंमोदकं मया।

मुंच्यते च तदा क्रोधं प्रापयिष्यति क्षुल्लकः।। 736 ।।

तदा जगाद वर्णीतां क्रोधारुण निरीक्षणः।

कृपणत्वात् ध्रुवं मात नैव मुंचसि मोदकं।। 737 ।।

मन्दं मन्दं तदा मुक्तं भुक्तं तेन तु मोदकं।

मुंच मुंच जगावेवं तया मुक्तं द्वितीयकं।। 738 ।।

तेन भुक्तं तदा वेगात् चक्रे पूत्कारमायतं।

अनेन विधिना सर्वे तया मुक्ताष्च मोदकाः।। 739 ।।

सर्वाष्चभक्षयित्वा सौ मुंच मुंचेति वाग् जगौ।

अपरं भवनेचान्नं नव्यलोकत रूक्मिणी।। 740 ।।

यदा तु चा तुला जाता दृष्ट्वा तेन बलीयसा।

तदा जगाद हे मात पूर्यतां पूर्जतां मम।। 741 ।।

इत्युक्त्वा च मनं नीत्वा गेह बाह्ये समागतः।

तत्रासनं तया मुक्तामुपविष्टः क्षुल्लकः सुधीः।। 742 ।।

मातुर्द्धर्मानुरागं च परिक्षा सकलं तदा।

प्रमोद पूरितो जातो यतिवेष धरोपि सः।। 743 ।।

तस्यैव क्षुल्लकस्यार्थे निविष्टा रूक्मिणी यदा।

तदा तौ चक्रतुर्वार्त्तां सम्यक्त्वेन विभूषितां।। 744 ।।

सीमन्धर जिनेनैव ये ये भावा निरूपिताः।

ते सर्वे प्रकटा जाता कामागमन सूचकाः।। 745 ।।

रूक्मिण्या भवनस्याऽग्रेयः शुष्काषोकपादपः।

फलपुष्पैः समाकीर्णा जातो सौ गुंच्छकैष्चितः।। 746 ।।

शुष्कावापी तदा पूर्णा जलजैष्च जलेन च।

उद्याने कोकिलानादो मयूराणां तथैव च।। 747 ।।

वसन्तसमयः प्राप्तास्तु तदा तु समयं विना।

भ्रमराणां झंकृतिर्जातो वृक्षाः पुष्पफलैष्चिताः।। 748 ।।

मूक्योपिवचनं प्राह विरूपा रूप संयुताः।

कुब्जाष्च सरलस्तत्रांधास्तु लोचनसंयुताः।। 749 ।।

मनः प्रीतिकरः सर्वोजनन्यास्तत्र चाभवत्।

रूक्मिणी चिंतयामास तदाचित्तेतिहर्षतः।। 750 ।।

एते ते सकला जाताः पुत्रागमन सूचकाः।

दृष्यते नैव पुत्रासौतत्किंच कारणं परं।। 751 ।।

रोमांचितं शरीरं मे प्रमोदष्चाति मानसे।

कुचयोः क्षीर श्रवणं दिक्षुर्निर्मलता तथा।। 752 ।।

दृष्यते न च पुत्रोमेकिं चास्याः क्षुल्लकः सुतः।

यदि स्यात्क्षुल्लकः पुत्रो निद्यरुपोति कुत्सितः।। 753 ।।

तदाहं सत्यभामाया दर्षयामि कथं मुखं।

साहंकारातु सा नूनं हसिष्यति दुराषया।। 754 ।।

अहं तु गतमानावै जाता पुण्य विवर्ज्जिता।

चिंतयंती पुनष्चैतां चिन्तांचित्तेदधारसा।। 755 ।।

मयि विष्णोस्तु संभूतः सचेदृषः कथं भवेत्।

बीजं तु क्षेत्रयोगेन जायते च शुभाषुभं ।। 756 ।।

मयियस्तु समुद्भूतो बलवान् रूपसंयुतः।

सद्विद्यासगुणः श्रेष्ठो यषस्वान् प्रथितात्मकः।। 757 ।।

अथवा किं तु क्षेत्रस्य प्रमाणं नैव निष्चितं।

पुण्याद्रूप सुरूपं च ध्रुवं भवति देहिनः।। 758 ।।

प्रमाणतापरं क्षेत्रे यदिस्यात् प्राणिनां ध्रुवं।

हरिणोष्ट्रहरिनागाष्च भोगभूमौ कथं त्वमी।। 759 ।।

अथवा तु मया पूर्वं नारदस्य वचः श्रुतं।

मेघकूटे तु खेटस्य गृहवर्द्धति ते सुतः।। 760 ।।

अखिलानां तु विद्यानां खेचराणां तथैव च।

कलानां सकलानां हि भर्त्तुरेव न संषयः।। 761 ।।

सोपि विद्या प्रभावेन नीत्वा मायां मनोहरां।

ममचित्त परिक्षार्थं समायातो भवेदयं।। 762 ।।

लब्धाषोडषलाभांष्च विद्याद्वयविभूषितः।

रिपु वर्गस्य जेतायः कथंस्यादीदृषः खलु।। 763 ।।

चिरं विमृष्य सा राज्ञी क्षुल्लकं शील भूषिणं।

जगाद वचनं रम्यं विनयेन समन्विता।। 764 ।।

हे क्षुल्लक प्रभो स्वामिन् किंचित्पृच्छामिचादरात्।

स्वमातृबंधु कथया कर्णौ में सुखिनौ कुरू।। 765 ।।

रुक्मिण्यां वचनं श्रुत्वा जगाद क्षुल्ल्को यदा।

मदीयं वचनं रम्ये श्रुणुत्व श्रावकोत्तमे।। 766 ।।

यैष्चत्यक्तं निजं गेहं गृहीतंयमिनां व्रतं।

इच्छातु सकलात्यक्तवा रागद्वेष विवर्ज्जिता।। 767 ।।

मुनयस्वे यतीन्द्रास्ते वैराग्येण विभूषिताः।

स्वजाति कुल बन्धूनां कथं कुर्वन्ति ते कथं।। 768 ।।

त्वापि मातनो युक्तं मुनीनां शील धारिणां।

कुलजात्यादि प्रष्नोयं त्वं सम्यक्त्वा विभूषिता।। 769 ।।

जिनमार्गे त्वया क्वापि हीना जाति कुलेन किं।

क्वापि पूर्वं श्रुता मातयतोत्र त्वं तु पृच्छसि।। 770 ।।

यदुन्नतः किं कुरुषे यदि हीनस्तथापि किं।

उपकारमपकारं किं किं ते हीनोत्तेमेपीवत्।। 771 ।।

मौढ्या वृथात्र पृच्छसि चतुरात्वं हि रुक्मिणी।

किमस्माकं हरिस्तात त्वमेव जननीपरा।। 772 ।।

यतीनां श्रावको एव पितरः परिकीर्त्तिताः।

अतोत्र पृच्छते किं हि यतीनां बन्धुजां कथं।। 773 ।।

एवं संतुष्ट चित्तौ तौ कुर्वन्तः सत्कथांयदा।

तदा पूर्वं कृता ताभ्यां प्रतिज्ञा जनविश्रुता ।। 774 ।।

रूक्मिणी सत्यभामाभ्यां तां संस्मृत्य सुकेतुजा।

नापि केन समं दास्य प्रेषयामास सत्वरं।। 775 ।।

केषानां वल्लरी नेतुं रुक्मिणी सदनं प्रति।

गायंत्यस्ताः समायाता नीत्वा सन्मणि भाजनं।। 776 ।।

सत्यभागा जनंतं च प्रतोल्यां याददागतं।

आयांतं च समालोक्य सहसा रूक्मिणी तदा।। ।। 777 ।।

भूत्वातिदुःखिता वेगादश्रुपातं चकार सा।

इत्थं भूतां च तां दृष्ट्वा प्रपच्छ क्षुल्लकोपितां।। 778 ।।

कथं ते सहसा मात शोकोयं वै सुमुदठ्तः।

तत्सर्वं कारणं मह्यं वेगतस्त्वं निरूपय ।। 779 ।।

इत्युक्ते गदगदां वाणीं धारयंती तु सा जगौ।

कथयामि विभोस्तुभ्यं शृणु त्वं चैव मानसा।। 780 ।।

प्रोक्तुं युष्मद्विधानां हि यतीनां दुःख कारणं।

कदाचिद्विलयं याति दया धर्म प्रभावतः। 781 ।।

सत्यभामाभिधानास्ति पत्युर्मे प्रथमांगना।

विद्याधरीकलानां च गुणानाम लघालया।। 782 ।।

अहं तु भीष्मभूपस्य देहजा च मनुष्यणी।

यत्युः प्रसाद चित्तास्मि किंचित् च पूर्वपुण्यतः।। 783 ।।

प्रागावयोस्तु संजाता मर्यादा गर्व युक्तयोः।

सत्साक्षिक समायुक्ता केथयामि तवापितां।। 784 ।।

यस्यास्तु प्रथमः सूनुर्भावी पण्यानुयोगतः।

विवाह प्रथमस्तस्य भविष्यति न संषयः।। 785 ।।

विवाह समये तस्य यातु पुत्र विवर्ज्जिता।

स्वकेषवल्लरीभिः सा करोति पादपूजनं।। 786 ।।

इतिसंस्था कृता तत्रमावाभ्यां चाति गर्वितः।

पुत्रपूर्वं मया जाता सर्वलक्षण लक्षितः।। 787 ।।

ततोपि सत्यभामायाः तास्मिन्नेव दिनेभवत्।

पुत्रः कमलनेत्रस्तु भानुर्नामा विचक्षणः।। 788 ।।

तत्रकेनापि पापेन दैत्येन पूर्व वैरिणां।

ममपुण्य विहीनाया ह्रतो बालोदुरात्मना।। 789 ।।

वृद्धिं गतः क्रमेनैव कुमारा भानु संज्ञिकः।

पुण्येन सत्यभामायाः सुखं पुण्यात्प्रजायते।। 790 ।।

सोपि विवाहयोग्यो भूत्पूर्वपुण्यप्रभावतः।

हस्तिनापुरः स्वामी दुर्योधन समाहुयः।। 791 ।।

तस्योदध्याभिधानास्ति कन्यागुण विभूषिता।

सानुरागंतु सा भानुं परिणेतुं समागता।। 792 ।।

गृहीतुं मेल्य पुण्याया नूनमेलकवल्लरीं।

समायातस्तदीयोयं लोकोनापि क संयुतः।। 793 ।।

ममालकछेदा भयात् पूरैवहिमर्त्तं मया।

तदाकृतं तदाचात्र नारदोसौ समागतः।। 794 ।।

तेन पुत्रागमासंषि कथयातर्प्पितास्म्यहं।

अतस्त्यक्त्वा मया नूनं मरणाषा चातिहर्षतः।। 795 ।।

श्रीमंधरजिनेन्द्रेण नारदाय पुरा तदा।

पुत्रागमनकाले हि ये ये भावा निवेदिताः।। 796 ।।

ते ते सर्वेधुना जाता ममगेहेति सुंदरा।

नासौ समागतः पुत्रो हताषां किं करोम्यहं।। 797 ।।

शत्रुर्मेमर्त्तुकामाया नारदोपि पुरा भवत्।

न पुत्रो न मृताचाहं द्वाभ्यां भ्रष्टा करोमि किं।। 798 ।।

निवेद्य वर्णिनै सर्वं रुक्मिणी दुःखकारणं।

अश्रुपातं तदा कर्त्तुं लग्ना दृष्टातु तेन सा।। 799 ।।

माकृथास्त्वं वृथा दुःखं मातर्मद्वचनं श्रृणु।

पुत्रः करोति ते कार्यं तथाहं न करोमिहं।। 800 ।।

प्रोवाचैवं तु कामोपि चकार विविधा क्रियां।

सत्यया प्रहितस्याग्रे केषान् हर्त्तुजनस्य च।। 801 ।।

नवीनां रूक्मिणी तत्र चक्रे मायाविनिर्मितां।

सिंहासन स्थितां दिव्यां सर्वाभरण भूषितां।। 802 ।।

रूक्मिणीं प्रथमां कामो दृष्ट्वां कृत्वातिवेगतः।

स्वयं तु कंचुकीरूपं नीत्वाचाग्रेसितस्तदा।। 803 ।।

तावत्समागतः सोपि सत्यभामा जनोखिलः।

नापिकेन समं नम्रो भीतो वाक्यं मिदं जगौ।। 804 ।।

नोस्माकं दूषणं मात वर्त्तते खलुमात्रकं।

वयं तु सेवकानीचा स्वामिन्या प्रहितास्म्यहे।। 805 ।।

प्रभुरादेषतष्चात्र समायाता वयं ध्रु।

दूषणं सत्यभामाया प्रेषितास्मस्तयावयं।। 806 ।।

तदामायामयी प्रोचे भव्यं जातं समागताः।

किमर्थं तु समायाताः कारणं मे निवेद्यतां।। 807 ।।

किंचित्पणः कृतः पूर्वं भवन्तीभ्यां सभांतरे।

बलं तु साक्षकं नीत्वा तं च संस्मर्य प्रेषिताः।। 808 ।।

तव केष वचः श्रुत्वा जगौ मायामयी तदा।

भव्यं कृतं समायाताः गृह्णातु केषवल्लरीं।। 809 ।।

रेनापिक समागच्छ माकृथास्त्वं वृथाभयं।

गृहाण वेणिकां रम्यां नारीजन समावृतः।। 810 ।।

नार्योपि पटलां चाग्रेमुमुचुः हर्ष पूरिताः।

मांगल्येन समायुक्तां दधिदूर्वाक्षता युतां।। 811 ।।

नापिकोपि तदाद्दीपन् क्षुरं तत्र समागतः।

निविष्टो सौ प्रमोदेन रूक्मिण्याः पुरतो ननु।। 812 ।।

तदा मायामयी सापि निज मुद्घाट्य मस्तकं।

जगाद त्वं गृहाणेमान् केषान् भय विवर्ज्जितः।। 813 ।।

नास्ति में दूषणं मातर्जगावेवं तु नापिकः।

तदामायामयी प्रोचेन किंचित्तव दूषणं।। 814 ।।

गृहाण निर्भयो भूत्वा समस्तालकवल्लरीं।

क्षुरस्तु वाहितस्तेन तस्याः षिरसि वेगतः।। 815 ।।

नार्योपि पटलीं घृत्वा चक्रुगीत महोत्सवं।

तदासौनापिकस्तत्र चिछेदनासिकां निजां।। 816 ।।

अंगुल्याः करयोः सर्वाकर्णो तु निज वेणिकां।

परंनारी जनस्यापि तथैव निर्मितं तदा।। 817 ।।

नैव जानाति ता मूढा न जानाति स नापिकः।

काममाया विषेषण पश्यंत्यन्ये सकौतुकाः।। 818 ।।

रूक्मिण्यास्तु प्रषंसांताष्चक्रुरेवं परस्परं।

अहो मृदुत्वं सौजन्यं सुवाक्यं तु सुरूपता।। 819 ।।

किमस्या वर्ण्यते नूनं गुणानामनघालया।

रूक्मिण्यास्तु समः कोपि न भूतो न भविष्यति।। 820 ।।

एवं तु गुणवाचिन्यो नार्योपिनापिकेन च।

चतुः पर्थेतु तं गच्छन् हस्यंतेनागरैर्जनैः।। 821 ।।

ता जातंति निजे चित्ते रुपं दृष्ट्वा मनोहरं।

अस्माकं हि जनाः सर्वे हसंति रूपमोहिताः।। 822 ।।

नृत्यंतोपि च गायंत्यस्तास्तु हर्षेण पूरिताः।

सत्यभामागृहं प्राप्ता नापिकेन समन्विता।। 823 ।।

रूक्मिण्यास्तु गुणग्रामं वदंत्यस्ताः पुरः स्थिताः।

दृष्ट्वाथ सत्यभामापि जगावेवं वचस्तदा।। 824।।

किं भवंत्योपि हर्षेण पूरिता हास्य संयुताः।

स्तवनं क्रियते कस्याः कथ्यतां केन हेतुना।। 825 ।।

ततस्तानापि के नामा जगुरेवं विधं वचः।

सत्यंस्तुमो वयं देवि रुक्मिणीं गुणपूरितां।। 826 ।।

वल्लभा सा तु कृष्णस्य नितान्तं प्रियवादिनी।

हर्षेणैव ददौ केषान् विनयेन समन्विताः।। 827 ।।

केन यूयं विगुप्ताभो युवत्यो मम कथ्यतां।

रे नापिक तवाप्यत्र केनछिन्नातु नासिका।। 828 ।।

सर्वासां कर्ण्ययुगलं घ्राणास्तु षिरसः कुचाः।

अंगुल्योपि च छिन्नावै केन पापेन सांप्रतं।। 829 ।।

सत्यभामावचः श्रुत्वा स्पृष्यत्योथ करैर्निजैः।

मस्तकानि च घ्राणाष्च कर्णयो युगलानि च।। 830 ।।

ज्ञातं ताभिष्च केनापि तदा सर्वं तु दुःखदं।

आच्छाद्य सकलान् अंगान् जातास्ता लज्जयाकुलाः।। 831 ।।

वेदना महती तासां बभूतव रुधिर श्रवः।

विलापं परमं चक्रुस्ताष्च दुःखेन पीडिताः।। 832 ।।

दृष्ट्वा तथा विधं वृत्त सत्यभामा रूषान्विता।

जगाद रक्तनेत्रासौ केनेदं पापिना कृतं।। 833 ।।

जगुस्तास्तां रूदंत्योपि न जानीमोवयं ध्रुवं।

तयो तोषान् परं दत्ता निजमस्तक वैणिका।। 834 ।।

माहानंदधियो जाता दृष्ट्वी तं केषवल्लरीं।

त्वद्वाक्येन चास्माभिर्ज्ञातमीषे न संषयं।। 835 ।।

तासां तद्वचनं श्रुत्वा महांतं क्रोधमागता।

प्रभवोपि पराभूताः सेवकानां पराभवे।। 836 ।।

तदा जगाद सत्या सा रूक्मिण्या नैव दूषणं ।

दूषण चापि कृष्णस्य गोपालस्या विवेकिनः।। 837 ।।

स्वामिनो वाक्यमासाद्यतयेदं निर्मितं ननु।

कृतां तस्याप्य शुद्ध्याष्च मरंति बालकानहि।। 838 ।।

दातुमिच्छति सा नैव यदिस्वां केषवल्लरीं।

तदामदीय लोकस्य कथं चक्रे विडम्बनां।। 839 ।।

मयापिज्ञायते चैवं कृष्णस्येयंतु वल्लभा।।

तथापि ममलोकस्य कर्त्तुं युक्तं न चेदृषं।। 840 ।।

एवंमुक्त्वानि निजामात्यान् सत्यभामा जगौवचः।

कथयंतु बलस्याग्रे गत्वा कृष्णसभांतरे।। 841 ।।

नीत्वा परिजनं चैनं भवंतोपि सभांतरे।

रूक्मिणी चरितं सर्वं कथयं तु बलायवै।। 842 ।।

इत्युक्ते तेन तदामात्या नीत्वा परिजनं च तं।

यावद्गच्छन्ति वेगेन यादवानां सभांप्रति।। 843 ।।

तावत् कृष्णेन तं दृष्ट्वा परिचारं विडंवितं।

सत्याया हसितं वेगादत्यंतं सभया सह।। 844 ।।

हसंतं तं तथा दृष्ट्वा सचिवैष्चिंतितं हृदि।

अवष्यं षिक्षिता तेन विष्णुना रूक्मिणी तथा।। 845 ।।

अस्याग्रेतोपियाराविः क्रियते सावृथा ध्रुवं।

तथापि बलदेवस्य कथयामो न संषयः।। 846 ।।

विमृष्यैवं समागत्य सचिवैस्तु सभांतरे।

निरूक्तं बलदेवं तैः वृत्तांतं रूक्मिणी भवं।। 847 ।।

रूक्मिण्या सत्यभामाया लोकस्येयं विडंबना।

पूर्वं कृत प्रतिज्ञाया नेतुं या तस्य वेणिका।। 848 ।।

एवं विधवचः श्रुत्वा हसितं विष्णुना तदा।

नासिका कर्णकेषानां तया छेदं कृतं कथं।। 849 ।।

दृष्यते बहवष्चैतेसया कथं विडंबिताः।

एवं कृष्णवचः श्रुत्वा कोपं प्राप्य बलो जगौ।। 850 ।।

मां तु प्रतिभुवं दत्वा सर्व यादव साक्षिकं।

अधुनाकरोति याचैवंतरत्कास्यापि शक्तित।। 851 ।।

तस्य गर्वं तु दूरेहं करोमि क्षणमात्रतः।

आमात्यान् सत्यभामाया जगौ संकर्षणस्तदा।। 852 ।।

स्वकीयं सदनं यूयं यांतु चिंता विवर्ज्जिता।

दर्शयामितु पापिन्यैरन्याय तरुजं फलं।। 853 ।।

इत्युक्त्वा प्रेषितास्तेन सचिवा मंदिरं निजं।

गताः परिजनोपेतास्तुष्ट चित्तास्तु मंत्रिणः।। 854 ।।

तदाभृत्य गणास्तेन रुक्मिणीसदनं प्रति।

प्रेषिता कोपयुक्तेन तस्याग्रेहं तु लुंटितं।। 855 ।।

अत्रांतरे तु रूक्मिण्या मदनस्यापि कथानकं।

यद् वृत्तं कथयामीह भव्याः शृणु तु सादरात्।। 856 ।।

ततस्तु सत्य भामाया विगुप्ते तु जनेगते।

निजरूपमसौनीत्वातस्थौ क्षुल्लक तेषभाक्।। 857 ।।

तथा विधं च तं दृष्ट्वा रुक्मिणी वर्णिनं जगौ।

खेटाधिप गृहे यो सौगतो वृद्धिं त्वमेवहि।। 858 ।।

संप्राप्तोनारदोनामा त्वं मे पुत्रो न संषयः।

विद्या बलं विहायात्र नान्यस्य गतिरीदृषी।। 859 ।।

हास्यं युक्तं न ते कर्त्तुं जनन्या सहसांप्रतं।

प्रकटोभव वत्स त्वं मुंचमायापुरातनीं।। 860 ।।

वषीकृता त्वया वाल्ये सर्वे खेचर भूमियाः।

षोडषलाभभागीत्वं सर्व विद्याधिपो भवात्।। 861 ।।

यस्मैहूताः श्रुतापूर्वं देव खेचर किंनराः।

त्वदर्थं प्रेषिता नूनं नारदाख्यो मुनिर्मया।। 862 ।।

ततो मातृ वचः श्रुत्वा जगाद मदनो बली।

आगतो नारदे नामायस्तु मोहं भवाभि वै।। 863 ।।

ईदृषोस्मि कुरूपोहं सर्वलक्षण वर्ज्जितः।

ईदृषेन मयामात किं कार्यं च तथैव हि।। 864 ।।

मातापितोः कुपुत्रेण लज्जा भवति निष्चितं।

देहिगंतुमतोमात यत्र कुत्र व्रजाम्यहं।। 865 ।।

रूक्मिणी तद्धचः श्रुत्वा प्रोवाच वर्णिनं प्रति।

यादृषस्तादृषो वत्स तिष्ठ तिष्ठ गृहे मम।। 866 ।।

इत्युक्ते सो निजं रूपं जग्राह परमं शुभं।

संतप्त हेम संकासं शरीरं चापि शोभनं।। 867 ।।

विकसत्पÁनेत्रं च पूर्णचन्द्रमुखं वरं।

सर्वाभरणा संयुक्तं सर्वलक्षण लक्षितः।। 868 ।।

नवयौवन सम्पन्नं कम्बु कंठं सुवक्षसं।

नरनारी जनस्यापि चित्तष्चोरण कारणं।। 869 ।।

एवं विधं निजं रूपं नीत्वा चासौ मनोभवः।

नमाम विनयेनैव जनन्याः पाद पंकजं।। 870 ।।

कामं तथा विधं दृष्ट्वा जनन्यापि प्रमोदतः।

आलिंगम् सुतवेगात् उर्ध्वं नीत्वातिवेगतः।। 871 ।।

चिरमालिंग्यमोहेन संचुंव्यचास्य मस्तकं।

नयनयोरश्रुपातं सा चकाराति च हर्षतः।। 872 ।।

पुनः पुनः समालिग्य ह्रष्टो तो जननी सुतौ।

सुखदुःखसमुद्भूतां वार्त्तां च चक्रतुः शुभां।। 873 ।।

जनन्यापि सुतं प्रोचे दृष्ट्वा विद्या विभूषितं।

तद्रुपातिशयं वीक्ष्यानुपलब्ध तृप्तिस्तदा।। 874 ।।

एवं विधस्य ते वत्स बाल्यं सर्व मनोहरं।

न दृष्टं तु यया नूनं मया भाग्य विहीनया।। 875 ।।

साधन्या खेटभूपस्य पत्नीकनकमालिका।

यया बाल्यं तु ते दृष्टं वर्द्धितस्त्वं सुपुण्यतः।। 876 ।।

धृतोदरे मया नूनं नवमासां च क्लेषतः।

प्रसूतश्चाति दुःखेन नियतं पुण्य हीनया।। 877 ।।

अथवा कस्य दोषोयं दोषोवै निजकर्मनः।

भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्।। 878 ।।

तस्याः दुःखाविलं वाक्यं समाकर्ण्य मनोभवः।

जगाद विनयोपेतो रूक्मिणीं प्रेम लालसः।। 879 ।।

यदि ते मम बाल्यत्वे दृष्टुमस्ति च कौतुकं।

तदा तद्दर्षयामीह न किंचिन्मम दुर्ल्लभं।। 880 ।।

वीक्ष्यस्व मम बाल्यत्वं परेषां यच्चदुर्लभं।

इत्युक्त्वा क्षणमात्रेण बालरूपो च भूव सः।। 881 ।।

वरांगः सुंदराकारः शुभ लक्षण लक्षिणः।

उत्तानषायीतु मुग्धो विकचांबुजवत् मुखः।। 882 ।।

चटुलौ पाणिपादौच धारयन् बद्ध मुष्टिकः।

लीलोपसर्प्यगुणवान् कुर्धन् हास्यं मनाक् मनाक्।। 883 ।।

एवं विधं सुतं दृष्ट्वा प्रहृष्टा जननी तदा।

कराभ्यां सातिवेगेन नीत्वा चक्रेस्तनंधयं।। 884 ।।

नानो विलास दक्षोसौ स्वयं तिष्ठति प्रोच्छति।

ईषत्प्रसर्प्य को जातो जानुभ्यां च क्रमेणहि।। 885 ।।

उत्थाय पतनं भूयः स्थिरान्मामातुरग्रतः।

करालं च गतिर्जातः पुनः पपात भूतले।। 886 ।।

मातु करे तु लग्नोसौ वभ्रम मणिकुट्टिमे।

रणत्झणष्च कुर्वद्भ्यां नूपुराभ्यां परिस्कृतः।। 887 ।।

किंचिदनक्षरं जल्यन् स्व मातुर्मानसं हरन्।

बालोचितैराभरणौर्भूषितासौ क्षणे क्षणे।। 888 ।।

रमित्वासौ चिरं बालः प्रदेषेः रेणुभिर्युते।

आकारितः पुनर्मात्रा दधा च मातरं प्रति।। 889 ।

रेणुना भृत गात्रोसौ मुष्ठिं भूत्वाथ रेणुना।

ददौमातुर्गलालंब सुखं बालोति वेगतः।। 890 ।।

अनेन विधिना चासौ यादव श्री विभूषितः।

बालक्रीडां चिरं कृत्वा विमृष्यापर कारणं।। 891 ।।

याचयन् विविधान्नं च त्यजन् कोयात् रूदन्मुहुः।

अन्यं ददाति त्वन्यं तुदयाचे सुखभक्षिकां।। 892 ।।

तदा तं रूक्मिणी वीक्ष्य माता प्रौचैवचोवरं।

अलं ते रुदिते नैव मया सोढुं न शक्यते।। 893 ।।

एवं मात्वचः श्रुत्वा हसित्वोचे मनोभवः।

ममैव रूदितं मातः सहते सैवखेचरी।। 894 ।।

इत्युक्त्वा चन्द्र वक्रोसौ भूत्वा यौवन भूषितः।

पपाताति प्रमोदनमातुष्चरण पंकजं ।। 895 ।।

तं तादृषं समालोक्य पुत्रं विद्या विभूषणं।

आलिंग्य चुम्बयि चाथ सुखं प्राप्ता जनन्यपि।। 896 ।।

पुत्रांगसंगत कस्य सुखं नैवोपजायते।

दृष्टं श्रुमतनुभूतं मात्रा पुत्रेण तत् तदा।। 897 ।।

परस्परं परां वार्त्तां कुर्वंतो तौ स्थितौ यदा।

तावद् भृत्य गणंस्तत्रोयात्त शस्त्र समागतः।। 898 ।।

आगच्छन्तं प्रतोत्यां तं दृष्ट्वा भृत्यगणं स्मरः।

प्रपच्छ मातरं भक्त्या कृत्वा पादाब्ज वंदनां।। 899 ।।

कस्य चोयात्त शस्त्रोयं मातःभृत्यगणपुरः।

कथ्यतां मम वेवेन भव्याकारो न दृष्यते।। 900 ।।

ततस्तु रूक्मिणी प्राह शृणु वत्स निगद्यते।

तव ताताग्रजेनायं प्रेषितो मां प्रतिक्रुधाः।। 901 ।।

सत्यभामा जनस्यात्र त्वयादत्ता विडंबना।

अयं तु प्रतिभूजातस्तत्र कर्मणिनिष्चितं।। 902 ।।

तस्मात् चक्रोधमापन्नो दृष्ट्वा तं तु विडंबितं।

प्रेषितस्तेन भृत्यानां निवहोपंचमां प्रति।। 903 ।।

तस्या वाक्यं समाकर्ण्य जगावेवं मनोभवः।

प्रेक्षतां मम कर्त्तव्यं त्वयात्र स्थीयतांबिके।। 904 ।।

बलस्या भृत्य लोकोयं त्वया जेतुं न शक्यते।

दुस्सहोयं ध्रुवं वत्स परेषां रणषालिनां।। 905 ।।

इत्युक्ते मदनः प्रोचे जननीं प्रेमलालसां।

त्वमेव मौन संयुक्ता क्षणं तिष्ठ गुणाकरे।। 906 ।।

इत्युक्त्वा प्रेषयामास निज विद्यां मनोभवः।

सापिगत्वा प्रतोलीतु द्विजवेषधरा भवत्।। 907 ।।

श्रमैण पीडितष्चांगः स्थूलोदर समन्वितः।

भुक्त्वा सत्यागहात्तत्र निःश्रृतात्मा समागतः।। 908 ।।

निपत्यद्वार देषेसौ स्थितं स्थूलोदरो द्विजः।

तावत् तत्र समायातो भटानां निवहोरयात्।। 909 ।।

स्तंभयित्वा भटान् सर्वान् स्तत्रैव द्विजवेषभाक्।

एकं मुमोच कथकं सोपिगत्वा निवेदयत्।। 910 ।।

वृत्तांतं तं समाकर्ण्य कथितं तत्सभांतरे।

बलोपि परमं कोपं जगाम रुक्मिणीं प्रति।। 911 ।।

ह्नास्यं कृत्वा जगावेवं सामान्यानैव रुक्मिणी।

नूनं तु मंत्रिका जाता कृष्णोमंत्रैर्वषीकृतः।। 912 ।।

तस्यास्तु मंत्रं महात्म्यं गत्वा पश्यामि सांप्रतं।

यैःमंत्रैः कीलितो लोका मदीय पापया तया।। 913 ।।

इत्युक्त्वा स्वयमुत्थाय कोपसंछन्नविग्रहः।

जगामवेव संयुक्तो रुक्मिणी सदनं प्रति।। 914 ।।

प्रतोल्यां यादवायातस्तावत् तत्र द्विजं बलः।

ददर्षषयिनंमार्ग्रे प्रकाम जठरं वरं।। 915 ।।

रुंधायित्वाखिल मार्गे सुप्तं दृष्ट्वा द्विजं बलः।

जगाद वचनं रम्यंमुत्तिष्ठ द्विजसत्तम।। 916 ।।

मुंच मार्गे ममात्रैव कार्यं मे वर्त्तते धनं

तवोपरिकथं विप्रवेगात् गच्छामि निष्चितं।। 917 ।।

इत्युक्तेसौ द्विजः प्राह श्रृणु क्षत्रिय नायकः।

भुक्त्वासत्यागृहे चान्नं मधुनैव समागतः।। 918 ।।

शक्तोनैकं पदं दातुं मतोहं स्थूलगात्रकः।

प्रचुरं तु मया भुक्तं पणः कृत्वा पुनः पुनः।। 919 ।।

पश्चाद्व्यावृत्य गच्छत्वं पयोत्थातुं न शक्यते।

बलभद्रस्तदा प्राह श्रूयतां भो द्विजोत्तम।। 920 ।।

ममात्रैवमहत्कार्ये गम्यते तु मयाध्रुवं।

रुध्वामार्गं स्थितस्त्वं हि भुक्त्वावैपरवेष्मनि।। 921 ।।

भांडानि परकीयानि जठरं नपरस्यहि।

लौल्यंहि द्विजवर्गस्य सहजं वर्त्तते तरां।। 922 ।।

इत्युक्ते द्विजवेषीषोबलदेव जगौ वचः।

यद्येवं त्वं तु जानासि कथं जल्यसि सांप्रतं।। 923 ।।

बलभद्रः पुनः प्राहं रे रे पाप द्विजधम।

उत्तिष्ठ देहि मे मार्गं वृथा जल्यसि किं मुधा।। 924 ।।

तदा द्विजो जगावेवं क्षत्रियाधम किं वृथा।

ददासि गालिकां मह्यं ममोपरि व्रजाधुना।। 925 ।।

इत्युक्तेकोपमासाद्य नीत्वा पादौ द्विजस्य सः।

जगाम नगरद्वारं गत्वा वेगान्निराकरोत्।। 926 ।।

पृष्ठे विलोकयामास शरीरं स्थानके स्थितं।

तदाकोपं महत्प्राय बलोथ रुक्मिणीं प्रति।। 927 ।।

मयासहात्रया विद्यां करोति च वधूटिका।

न सामान्या ध्रुवं सापि शाकिनी डाकिनी ननु।। 928 ।।

इत्युक्त्वा पुनरायाते द्वारदेषेरुषाकुलः।

तावत्तेनापि कामेन ह्रष्टोसौ कोप संयुतः।। 929 ।।

दृष्ट्वा तं पुरुषं शूरं कोपा पूरित विग्रहं।

प्रयच्छ जननीं कामः कोयं शूरतरोनरः।। 930 ।।

निवेदद्रुतंमात नरागमन कारणं।

युद्धकामः समायाति भृकुटी कुटिनाननः।। 931 ।।

इत्युक्ते जननी प्राह श्रृणुवत्स वचो मम।

पितृव्यस्तेति शूरोयं बलदेवाभिधानकः।। 932 ।।

महाविक्रम संयुक्तः प्राणातुल्यः पितुस्तव।

श्रीमान् शत्रु समूहस्य घातकः पुरुषाग्रणी।। 933 ।।

पूज्यो यादव लोकस्य नास्य तुल्यो नरोभुवि।

न कोपि वर्त्तते विष्वे योनेन सह युध्यति।। 934 ।।

इत्युक्ते मदनः प्राह कथयस्व ममांबिके।

किमस्य वल्लभं युद्धं केन युद्धं समीहते।। 935 ।।

इत्युक्ते जननी प्राह मृगेन्द्रैर्दारुणैः सह।

युद्ध रंगे परां लीलां कृत्वा प्राप्नोति निर्वृतिं।। 936 ।।

जननी मदनः प्राह श्रुत्वा वाक्यं तदोऽर्जितं।

पश्यामि क्षणमेकं तु बलमस्य रणांगणे।। 937 ।।

तदा तु जननी प्राह नैव वक्तुं तु युज्यते।

बलदेवोति बलवान् जेतुं के नात्र शक्यते।। 938 ।।

अतोगत्वा तु वेगेन पतित्वा चास्य पादयोः।

सन्तोषय द्रुतं वत्स यदि ते जीविते स्पृहां।। 939 ।।

इति मातृ वचः श्रुत्वा जगादासौ मनोभवः।

क्षणं तिष्ठात्र मौनेन मम पश्य पराक्रमं।। 940 ।।

यावत्तेनापि विप्रेण युद्धं कर्त्तुं बलो बली।

प्रतोली च समायाति कोपानल विभूषितः।। 941 ।।

तावत्संहृत्यतां मायां स्वयं तु मदनोबली।

परावृत्त्य निजं वेषं क्षणासिंहो बभूत सः।। 942 ।।

बालमृगां कदंष्ट्रं तं चन्द्राकारं मनाहरं।

व्यालोलं कुम्कुमं समं केषरालि विराजितं।। 943 ।।

मूर्द्ध स्थितेन पुच्छेन शोभमानं समंततः।

संजृंभत्य च दिग्चक्रे वैन्य दृष्टिं मनौहरां।। 944 ।।

सिंहनादं प्रकुर्वान् मागच्छंतं गृह्यंतरात्।

दृष्ट्वा तथा विधं सिंहो बलो विस्मयमागतः।। 945 ।।

राजगेहस्य मध्येयं सिंहोत्र दृष्यते हि तत्।

रुक्मिण्याष्च कृतामाया नेयं योग्याहरः पुनः।। 946 ।।

इति मत्वा निजं हस्तं दिव्योत्तरीय वेष्ठितं।

तं वामं पुरतः कृत्वात् दृढंके क्रोधपूरितः।। 947 ।।

अन्योन्य घात दक्षौतौ प्रतिघाते तथैव च ।

ताडनैर्बलानैस्तत्र तर्ज्जनोल्लंघनैस्तथा।। 948 ।।

चक्रीडतुष्चिरं शूरा उग्रकोपौ यथेच्छया।

न कोपि भंगमायाति जयं प्राप्नोति कोपिन।। 949 ।।

मदनः सिंहरूपोसौ बलमास्फाल्य वेगतः।

चपेटया नृपस्थानभुवं प्राप्तः कृतस्तदा।। 950 ।।

निजंरूपं समादाय मुरारेस्तनयः पुनः।

स्वमातुष्चरणौ गत्वा नमाम विनयान्वितः।। 951 ।।

अत्रांतरे सा नूनं रुक्मिणी विस्मयाकुला।

महाविक्रम संयुक्तं पुत्रं दृष्ट्वा च तं जगौ।। 952 ।।

नारदस्य मुनेः वार्त्तां पुत्रं त्वं मे निवेदय।

क्वासौ गतौ महाबन्धुः कारनेन विना मम।। 953 ।।

इत्युक्ते मदनः प्राह श्रृणु मात वचो मम।

विद्याधर न गाद्योवैमया सार्द्धं समागतः।। 954 ।।

सर्वैस्तिष्ठति खेनूनं द्वारिकायाः पुरोबहिः।

मृगाक्षी तववध्वा सा भयमुक्तोधुनैवहि।। 955 ।।

रुक्मिणी तु तदाप्रोचे पुत्रं तं गुण भूषितं।

प्राप्तास्नुषाकुतः प्रत्रत्वया तन्मेनिवेदया।। 956 ।।

पृष्टो व भाणकामोपि जनन्यै सुखकारणं।

श्रृणुमातस्तवाग्रेहं कथयामि समासतः। ।। 957 ।।

यादुर्योधन भूपेन प्रेषितोदधि कन्यका।

भानोर्विवाह कार्यार्थं प्रीतयेकृष्ण भूपतेः।। 958 ।।

नीत्वा शबरवेषं तु मया मार्गे ह्रताहि सा।

नारदेन समं सा च गगने तिष्ठति सुंदरी।। 959 ।।

तिरस्कृतिं तथा भानोर्वाटिकाय विनाषनं।

वनविध्वंसनं चापि रथस्यैवतु भंजनं।। 960 ।।

शोषणं वापिकायास्तु कुसुमानां तुव्यत्पयं।

वसुदेव पराभूतिं सत्यभामा विडम्बनं।। 961 ।।

तत्सर्वं कथितं तेन मदनेनापि मातरं।

पुत्रस्येष्ट वधू प्राप्तिं शत्रोष्चापि तिरस्कृतिं।। 962 ।।

एतत्सर्वं समाकर्ण्य प्रमोदं परमं गता।

जगाद मदनं साथ श्रृणु वत्स वचोमम।। 963 ।।

द्रष्टं ममास्तिवांछात्र नारदं मुनि सत्तमं।

तस्मादानीयतं शीघ्रं बान्धवं प्रेम दर्षय।। 964 ।।

इत्युक्ते मदनः प्राह कथमानीयते मया।

मिलितो न कुटंबस्य मया त्वा नीयते कथं।। 965 ।।

तदातुरुक्मिणी प्राह मिलस्व पितरं निजं।

मदनोपि पुनः प्रोचे मिलामि कथमांबिके।। 966 ।।

गत्वा सभागतं तात यादवै परिवेष्टितं।

प्रणित्य मिलस्वेति रुक्मिणी मदनं जगौ।। 967 ।।

मदनोपि पुनः प्राह योवैकुल समुद्भवः।

चिरकालेन सम्प्राप्तो गुणवान् विक्रमी भवेत्।। 968 ।।

सेनाख्यापित शक्तिस्तु स्वस्य नामस्य कीर्त्तनं।

तवपुत्रोस्म्यहं तात कथं इत्थं निवेदयत्।। 969 ।।

संयुध्य प्रथमं मातस्तस्मात्पित्राच बंधुभिः।

संतज्य विविधैर्वाग्भिर्दर्षयित्वात्म पौरुषं।। 970 ।।

कथयिष्यामि मन्नामस्वयं ज्ञास्यंति तेखिलाः।

अन्यथा तु मया मात मिलितुं नैव युज्यते।। 971 ।।

गृहे गृहे तु गत्वाहं कथ्यामि निजागमं।

तत् न युक्तं ममात्रैव तव पुत्रस्य सांप्रतं।। 972 ।।

इत्युक्ते रुक्मिणी प्राह कर्त्तुमेवं न साम्प्रतं।

यादवाः सबला वत्स जेतुं शक्याः कथं त्वया।। 973 ।।

यादवा भौजगा वत्स पांडवाष्चंड तेजस।

संग्रामे लब्ध विजयस्तु या जेतुं न शक्यते।। 974 ।।

इत्युक्ते मदनः प्रोचे किमत्र बहुभाषितै।

नेमिनाथं विहायैकं सर्वं ते दृष्यसेधुना।। 975 ।।

इत्युक्त्वा तु क्षणं स्थित्वा जगाद मातरं प्रति ।

याचयामि तवाभ्यासे किंचित्वं मे सम 976 ।।

मातापुत्रवचः श्रुत्वा जगाद वचनं वरं।

याचस्वया चितं वत्स दास्यामि तव सांप्रतं।। 977 ।।

एहिमातमयेत्यूचे विमानं लोक सुंदरं।

तत्र तेहिस्तुषासार्द्धं वर्त्तते नारदो मुनिः।। 978 ।।

कुरुप्रसादं मे मात शीघ्रमागत्यतां त्वया।

तत्रमुक्त्वा तु त्वां वेगात्करोमीह यथेसितं।। 979 ।।

विमृष्टं तु तया तत्र यदि पुत्रेण गम्यते।

अनापृच्छतिं विष्णुं तदा कथं पतिव्रता।। 980 ।।

नैव गच्छामि पुत्रेण तदायं रोषमाप्नुयात्।

रोषाद्विद्याधरे खंडे ध्रुवं यास्यति मन्मथः।। 981 ।।

अथवा यो मम स्वामी रोषं च नैव यास्यति।

करोमि पुत्र वाक्यं वै पश्चाद्बवं भविष्यति।। 982

विमृष्यैवं तु सा प्रोचे ध्रुव मेष्यामि सांप्रतं।

इत्युक्ते तत्क्षणाहर्षादुत्थाय सहसा तदा।। 983 ।।

भूषणानां तु तेजोभिः कपिलीकृतदिग्मुखं।

हस्ताभ्यां तां समुद्धृत्य मदनोविय दुर्ज्जयौ।। 984 ।।

कराभ्यां रुक्मिणीं धृत्वा यादवानां सभोपरि।

स्थित्वा जगाद मदनो बलकृष्ण पुरस्सरान्।। 985 ।।

भो यादवाः सुभोगाष्च भो पांडुसुतानृपाः।

अन्ये शूरास्तु सुभटायेस्युः कृष्ण सभांतरे।। 986 ।।

यदि यूयं सुकुलाजा यदि लब्ध जयारणे।

सावधान तया सर्वे तदा श्रृण्वंतु मद्वचः।। 987 ।।

भीष्म भूपस्य या पुत्री यातु कृष्णस्य वल्लभा।

रुक्मिणी नाम विख्याता सर्वत्र वसुधातले।। 988 ।।

दमघोषात्मजं दिनं वराकं विनिहत्यतं।

आनीता कृष्ण सारीभ्यां द्वाभ्यां कृत्वा च संयुतं।। 989 ।।

सा साध्वी खेट पुत्रेण सांप्रतं नीयते मया।

नीलाब्धदलनेत्राहि वीरेण भवतां पुरः।। 990 ।।

भवतां जीवतव्येन सर्वेषां किं प्रयोजनं।

मयाचै केन वीरेण ह्रियते रुक्मिणी यदि।। 991 ।।

भवतां यदि सर्वेषां वर्त्तते शक्तिरद्भुता।

मम हस्त गता मे नां मुंच मुच ध्रुवं तदा।। 992 ।।

सर्वे संभूय वेगेन यतध्वं भो भटोत्तमाः।

अदत्वाहं ध्रुवं युद्वं नो व्रजामीति निष्चितं।। 993 ।।

पूर्वं कृत्वा तु स्मरं हि भवद्भिः सह सांप्रतं।

पश्चात् वेष्ट पदं नूनं नेष्यामि कृष्णभामिनी।। 994 ।।

नाहं चौरो भवामीति नाहं मिछावरोनरः।

न नटो न विटोहं च निज शक्त्यानयाम्यहं।। 995 ।।

तस्य वाक्यं समाकर्ण्य यादवानां सभा तदा।

सहसा क्षोममायाता शूरवीर नरै युतः। 996 ।।

वाताहत समुद्रस्य लीलां कल्लोजलांतदा।

दधारकोप संयुक्तः किं वा वाडवसंहति।। 997 ।।

बलो मूर्छा समासाद्य पतितः क्षितिमंडले।

परितो यादवाः सर्वेसं वेष्टैचनं स्थिता यदा।। 998 ।।

तदैव तस्य वाक्येन जातोसौ मूर्छयोष्भितः।

गौरोपि रक्ततां प्रापषीरीकोपेन तत्क्षणे।। 999 ।।

ललाटे भृकुटी कृत्वा कंपमान शरीरकः।

कोवोच्युत स्वभावोहि भयात् नो जायते नरः।। 1000 ।।

यादव पांडु सुतान् सर्वान् भीमाद्याः कोपपूरिताः।

आशनेभ्यः स्वीकीयेभ्यष्चेलुस्ते वेग संयुताः।। 1001 ।।

तदायुधिष्ठिरेणै ते संज्ञयैर्वाबोधिताः।

स्थिरत्वं भवतां युद्धे ज्ञास्यामः शत्रुसंगमे।। 1002 ।।

अधुना किं वृथा कोपो भवद्भिर्द्धार्यते ध्रुवं।

अतएव स्थिरत्वं च भजध्वं भो सुपांडवाः।। 1003 ।।

केचित् वक्ष स्थलं हस्तै भृषंतः पुरुषोत्तयः।

प्रोचुर्वाक्यानि दुष्टानि कोपसंच्छन्न विग्रहाः।। 1004 ।।

अन्ये केयूरमणिभिदीप्तान बाहुतटीं स्तदा।

दंष्टाऽधरा परं जध्नुः कर ग्रैरुग्र कोपकाः।। 1005 ।।

अपरे राजपुत्रास्तु प्राप्तरोषा युयुत्सवः।

सगर्वा बहतुस्तत्र वलांगामान संयुताः।। 1006 ।।

केचित्प्रकंपिरेत्यंत क्रोधारुण निरीक्षणाः।

अंधवत् वभ्रमुः केचित् शूरा मानधरा नृपा।। 1007 ।।

अन्येषिलामया स्तब्धान् बभंजु क्रोधपूरिताः।

खङ्गा निष्काष्य कोषेभ्यष्चापरे प्रोत्थितास्तदा।। 1008 ।।

क्षुब्धेषु तेषु सर्वेषु केचिदूचुर्वचो वरं।

स्वल्पैर्जयोनवार्यं वै भवद्भिः क्षुद्र शक्ति कैः।। 1009 ।।

तस्माद्भट समूहस्य बोधनाय तुः पंडितः।

देया संग्राम भेरीं च ततो ते गम्यते ननु।। 1010 ।।

श्रुत्वा भेर्या निनादं तु सर्वे ते भटपुंगवाः।

कार्याण्यर्द्ध कृतानीह मुक्त्वा वेगाद्विनिर्युयुः।। 1011 ।।

सद्योभीता समास्वास्य रहः कांतानिजास्तदा।

सुभटाः शूरतां युक्ता कुलषील बलान्विताः।। 1012 ।।

कंकटानि निजांगेषु केचित् चक्रु भटोत्तमाः।

निजषौर्य बलोपेताः सगर्वामानषालिनः।। 1013 ।।

अपरे संग्रामतोषात् पुष्टिभा वा भटोत्तमाः।

त्रुटितानि ततस्तेषामंगेभ्यः कंटकानिचः।। 1014 ।।

हस्त्यष्वस्यंदनारुढाः कोदंडा सदायुधाः।

शंखभेर्यादिनादेन पूर्यमाणदिगंतराः।। 1015 ।।

राजांगणं समासाद्य स्थित्वा सर्वे भटोत्तमाः।

केचित्छत्रैस्तु संयुक्ताः केचित् चामर भूषिताः।। 1016 ।।

कुपथाप्तरुचोभीमाः प्रोत्तुंगाः षष्ठिहायिनः।

कर्द्दमाकृत भू भागा सदपानीय वर्षणैः।। 1017 ।।

कल्पांतस्यैव वातेन प्रेरितास्तु समागताः।

धाराधरा वा चलिता गजेन्द्रास्तु विनिर्गताः।। 1018 ।।

स्वनतः सकलां भूमि खुराग्रैः प्रेखरैस्तदा।

वाप्यमानाधरां नूनं निजाच्छादन संयुता।। 1019 ।।

निज हेस्वारवेणैव प्रति शत्रोष्च वाजिनां।

आहुयंत समायातास्तुरगा वेग शालिनः।। 1020 ।।

शस्त्रं वृंदैस्तु दिव्यास्त्रैः पूर्णमध्या मनोहराः।

चीत्काराणां तु शब्दैस्तु बधिरीकृत विष्टपः।। 1021 ।।

मरुच्चलैः केतुकरैराहुयंतो रिपुं परं।

एवं विधास्तदा चेलूरवौधा व्याप्त विष्टपं।। 1022 ।।

खड्ंखेटक संयुक्ताः कंकटैष्छन्न विग्रहाः।

आच्छाद्य सकलां पृथ्वीं निर्गतास्तु पदातयः।। 1023 ।।

शत्रोः पराजयस्यैव बन्धकाव्य शुभानि च।

निमित्तान्यथ दृष्टाप्तिचेलुः सर्वे भटोत्तमाः।। 1024 ।।

यादवा भोजगावीराः पांडवाः शौर्यषालिनः।

चलिताः क्रोध संयुक्ता योग्यायोग्य विचारकाः।। 1025।।

अथकामोपि वेगेन नीत्वा तां निजमातरं।

विमानं मुनि संयुक्तं कन्ययापरि भूषितं।। 1026 ।।

मुमोच सो हि हर्षेण मातापि विनयान्विता।

नारदं तं नमामासौ माता वध्वानता तदा।। 1027 ।।

युक्तां नारदनारीभ्यां रुक्मिणीं गुणषालिनी।

मुक्त्वा तत्र विमानेसौ समायातो धरातलं।। 1028 ।।

विषालं भूमिकां प्राप्य चक्रेसेनां तदाद्रुतं।

रथवाजिगजाकीर्णां पादांति कुल संकुलां।। 1029 ।।

केषवाद्या नराये च वर्त्तते हरि साधने। ।।

ते सर्वेपि च भूपाला जाता मदन साधने।। 1030 ।।

चिर्हानि तानि सर्वानि वेषा रूपानि तानि च।

तथा वाजित्रणिर्घोषास्तथा जल्यंति बंधिनः।। 1031 ।।

गजवाजिरथौघाष्च तथैव कृति धारिणः।

अभिधानानि तान्येवं सर्वं काम बले भवत्।। 1032 ।।

बलद्वयं समालोक्यं सर्वलक्षण लक्षतं।

रणोत्सकं सहर्षे च पौरणारी जना जगुः।। 1033 ।।

तदाहर्म्यतलारुढ़ाः पूर्णचन्द्र समानना।

यदिस्यातु समाष्चात्र तदा धन्यावयं ध्रवं।। 1034 ।।

काचित्प्रोचुरिदं तत्र कृष्णोयं ग्रथिलोभवत्।

प्रतिभाति च हे मात मम चेतसि निष्चितं।। 1035 ।।

योषाकृते भटानां यो मारणाय समुद्यतः।

शूराणां वंष जातानां नरेन्द्राणां तथैव च।। 1036 ।।

काचिज्जगादत्रैव ममायं प्रतिरुज्जितः।

सकुंतेचमरैर्युक्तः शुभयाने स्थितोवलि।। 1037 ।।

अपरातु सखीं प्रोचे ममायं पतिस टाः।

मस्तको भालके नैव राजमानोरयान्वितः।। 1038 ।।

अन्य तत्र सखीं प्रोचे ममायं प्राण वल्लभः।

चामरै वीजिते नूनं स्तूयमानोत्र बंदिभिः।। 1039 ।।

इत्यादि शुभ वाक्यानि नारीभ्यो भटसत्तमाः।

श्रृणुंतोपि तदा वेगात् संप्राप्तास्तु प्रतोलिकां।। 1040 ।।

केचिद्वा शत्रु सैन्यं तु केचित्पुर प्रतोलिकां।

संप्राप्ता भट सार्दूला वीरा लीला समन्विता।। 1041 ।।

तावत्केचिद्भटावेगात् प्रधाव्यरणमुत्सकाः।

रिपुसैन्यमाविचक्षून् नात्मीयानि तरां नपि।। 1042 ।।

राजाज्ञां तु समासाद्य प्रतीहारो भटोत्तमान्।

वारयामास वेगेन प्रचण्ड बल शालिनः।। 1043 ।।

सैन्ययो वीराणांतु रेणु घंटा मनोहराः।

काहलाः परमं शब्दं चक्रुः कोलाहलाकुलं।। 1044 ।।

भेरी भंभादि नादैष्च तूर्यनादा तथैव च।

व्यापयामासस्ते नूनं व्याप्तदिक्दषमं ततः।। 1045 ।।

तदा सैन्य पुरो रेणुर्विस्तारं परमं गतः।

समस्तं भुवनं व्याप्य तत्र किंचिन्नदृष्यते।। 1046 ।।

जानेहं वारणायैव रेणुस्तत्र समुद्यतः।

नायं शत्रु मुतो नूनं कोपोयं किं निरर्थकः।। 1047 ।।

तदा गज समूहैनां मदकोपेन संयुतः।

वारयामास तं रेणुं निजवर्षेण वेगतः।। 1048 ।।

कथं रेणु समुद्युक्तो वारणायाखिलं बलं।

नात्रप्राणीवधे नूनं विनोदोयं निवार्यते।। 1049 ।।

इत्थं तु संस्थिते सैन्ये हरि मन्मथयोस्तदा।

समासैन्ये महायोद्धैः संयुते बलषालिभिः।। 1050 ।।

गगनांगणेमासाद्य देव दैत्या जगुस्तदा।

भूयपूरित चित्तास्ते दृष्ट्वा सैन्यं ततोधिकं।। 1051 ।।

वयं विद्या नीत नूनं कस्यात्कौत्र विजेष्यति।

तावत्कौतुक संयुक्ता स्तस्थूस्ते गगनांगणे।। 1052 ।।

पादं वक्षसि संनिधाय चलिना सत्यात्मजोमर्द्दितः।

सत्याया वन वाटिकादि रुचिरंध्वस्तं समस्तं क्षणात्।। 1053 ।।

मातुः कार्यमनेकधासु विहितं कामेन ते नामुना।

तत्सर्वं जिनधर्मतः शुभतमं ध्येयं सदाप्राणिभिः।। 1054 ।।

धर्मतः सकल मंगलावली धर्मतः स्वजन बंधुसंगम।

सोमसौम्यममलं मनोहरं धर्म एव तदहो विधीयतां।। 1055 ।।

***इति श्रीप्रद्युम्नचरिते आचार्यश्रीसोमकीर्त्तिविरचिते श्रीप्रद्युम्नमातुर्मिलनं**

सैन्यारोपनवर्णनो नाम

दशमसर्गः। *

एकादशसर्गः

अथ कृष्ण मनोजस्य सैन्ययोस्तत्र संगमे।

यद्यदृवृत्तं च तत् सर्वमधुना तन्निगद्यते।। 01 ।।

सैन्ययोरुग्रयोधैस्तु कल्पांता धेस्तु तुल्ययोः।

अंतरालेहि संघट्टस्तदा जातोति वेगतः।। 02 ।।

गर्जंमाती भटाः सर्वे धैर्य वीर समन्विताः।

पतियुद्धं परं चक्रुर्देव दैत्य भयापहं।। 03 ।।

गजोगजेन संलग्नस्तुरगस्तुरगेण हि।

योधायोधैः समं लग्नाः स्पदनैत्स्पदनाः सह।। 04 ।।

सर्वेभट समूहैस्ते योधं कर्त्तुं समुद्यताः।

हेतुं विनापितद्वैरं निर्निमित्तं तु तं रणं।। 05 ।।

शायकेर्भिन्न मात्राहि पेतु भूमौ भटोत्तमाः।

दंतिनो दंतिभिर्भिन्नाः पतितास्तुरणांगणे।। 06 ।।

रथिनोरथभिः भिन्नास्तुरगोस्तुरगैस्तथा।

एवं तत् च महायुद्धं भीममासीद्रणांगणे।। 07 ।।

खङ्गखेटधराः शूराः खङ्ग[ksVd /kfjdS%

ये च वृक्षायुधालग्ना ये च वृक्षा युधैः समं।। 08।।

केषाःकेषैः परं लग्नाः संकुताः कुंतकै सह।

मुष्ठिकामुष्ठिकैः सार्द्धं युद्धं चक्रेतुरुत्कटं।। 09 ।।

कष्चित् कस्यापि नागस्य यावत् विच्छेद प्रछदं।

तावन्नागस्य नाथेन परमानीय दीयते।। 10 ।।

तावदेव परं वेगात् मुक्त्वा बाणं महाषुभं।

जघान कुंभयोरस्य पिछवर्ज्जं भटाग्रणीः।। 11 ।।

योजयित्वा तदा हस्तैर्हस्तांष्च गजनायकाः।

दंतादंतैस्तु संयोज्य कुंचिताग्र पदाहगत।। 12 ।।

कंपयंता धरापीठं भूरि कोपेन संयुताः।

लीलयाषोभ मानास्ते चक्रुर्युधं परस्परं।। 13 ।।

अन्येतत्र गजारेजुछिन्नाशस्त्र समूहकैः

तदारुधिरधाराभिर्वर्षतोमी रणांगणे।। 14 ।।

पर्वतानां परां शोभां युक्तानां धातुवारिभिः।

दधाना वसुधापीठे निष्चलत्वं समागतः।। 15 ।।

चक्रे छिन्ना निजान् वीरान् पाणिपादाष्च वेगतः।

गृहीत्वाथ रिपुं हत्वा समं पेतु भटोत्तमाः।। 16 ।।

कीर्त्तोहि लुब्ध चित्ताये स्वामि कार्यपराग्रणीः।

तेषां निःसार देहेपि ममत्व नैव विद्यते।। 17 ।।

एवं विधे तदा तत्र जयमाने महाहवे।

यादवीर्यै बलंध्वस्तं कामपालस्य वेगतः।। 18 ।।

कामदेव भटैस्तावच्चटित्वा समरांगणे।

नाषितं चाति वेगेन वैष्णवं बलमुत्कटं।। 19 ।।

पलायतं समालोक्य निजं सैन्यं तदा हरिः।

बलदेवेन संयुक्तताः पांडवाद्याविसर्ज्जयत्।। 20 ।।

यावत्तैः सुभटैः सर्वैंध्वंस्यते मन्मथं बलं।

तावत् च मदने नापि दृष्टंध्वस्तं निजं बलं।। 21 ।।

बलभद्रेण संयुक्ताः पांडवाद्या महाभटाः।

प्रेषिते कृष्ण सैन्यंते चक्रु युद्धं परस्परं।। 22 ।।

स्वयं स्वनाम संयुक्तं भटवाहूय सद्भटः।

मायायुद्धं परं चक्रुः भटस्तै वै परस्परं।। 23 ।।

वृंहितैर्वा करीणां च हयानां चापि हेषितै।

तूर्याणां च निनादैस्तु विस्फारैर्द्धनुषां तथा ।। 24 ।।

भटानां सिंह नादैष्च शत्रुघातैस्तथैव च।

द्विधा भवतु कामाया भूमिर्वागगणांगने।। 25 ।।

अर्द्धेंदुव चक्र बाणैष्च लूनेदंडे तु मूलतः।

छत्राणि पेतु गगने वातेन प्रेरितानि हि।। 26 ।।

तानि दृष्ट्वा तु संकेहं चन्द्र विम्बानि कौतुकात्।

दृष्टं समागतानीह युद्ध यज्ञं मनोहरं।। 27 ।।

वीरं वीरो जगौ तत्र शंका त्वं मा कृथा वृथा।

मुंचगाढं प्रहारं भो त्यज कंपं तथा भयं।। 28 ।।

केषान् शीघ्रं तु संयम्प नीत्वा वस्त्रं धरागतं।

गृहानवेगतः शस्त्रं पष्चाद्युद्धं करोम्यहं।। 29 ।।

अन्योपरं जगावेवं श्रृणु वीर वचोमम।

युध्वानो प्राप्यते स्वर्गो नैव मोक्षो कदाचनाः।। 30 ।।

किं साध्यं तव कीर्त्याहि तन्मेसत्यं निरूपय।

भार्यां चन्द्रमुखीं मुक्त्वा युद्धं मा त्वं कृथा मुधा।। 31 ।।

अन्योन्यालाप दक्षास्ते नरेन्द्रामान शालिनः।

मायायुद्धै समं युद्धं च क्रुरेवं तदोत्कटं।। 32 ।।

धीरामानो बलेयष्च शत्रून् जध्नुस्तदाभृषं।

चित्रषस्त्रात्रजालैष्च प्रतिकर्म निपंडितः।। 33 ।।

गजैः शैलेन्द्र संकाषैः पतितैः क्षितिमंडलं।

दुस्सचारं रणं जातं तत्रभग्नै महारथैः।। 34 ।।

भल्लूनां तफेतकारैर्वेतालैरंत्र भूषणैः।

नटद्भिस्द्रणं जातं तत्र भग्नैः महारथैः।। 35 ।।

इत्थं युद्धं महज्जाते पांडवाद्या नरोत्तमाः।

बलदेवादि सुयंक्ता मायाया मन्मथैर्हताः।। 36 ।।

ध्वस्तन्योधान् समकर्ण्य स्वयं वीक्ष जनार्दनः।

सरोषादॅजमुत्सृज्य रथेस्थित्वा रणोन्मुखः।। 37 ।।

विष्वं हि छादयन् बाणैः संप्रचेलु रिपुंप्रति।

दाराबंधु वियोगेन हंतु कामोरिपुंवलान्।। 38 ।।

वैलक्षभाव संयुक्तं तातं दृष्ट्वा मनोभवः।

मंदमंद रथं निन्ये तातं तु विन्यान्वितः।। 39 ।।

तावत् च दक्षिणं चक्षुस्तथा बाहुं च दक्षिणं।

स्पंदनेस्मपरं विष्णोरिष्टांषंसिर्न संषयः।। 40 ।।

सारथिं च तदा कृष्णो जगाद वचनं वरं।

क्षीणे च सकले सैन्ये बंधुवर्गे क्षयं गता।। 41 ।।

युध्वासीडेथ शत्रौ च नेत्रं किं स्पंदने मम।।

अद्यापिभद्र किं भद्रं प्रेक्षणीयं भविष्यति।। 42 ।।

प्राहस्मैवं च चोरम्यं सारथिंष्चक्रिणं प्रति।

यन्नेत्रं स्पंदते नाथ कथवामि तदेवहि।। 43 ।।

संग्रामे वैरिणं जित्वा लब्धा कीर्त्ति जयोर्ज्जितां।

प्रास्यसि त्वं प्रियां नाथ मा विषादं कृथा वृथा।। 44 ।।

विष्णोष्च सारथिरचापि तुष्टचित्तौ परस्परं।

भाषमाणै वचष्चेत्थं संप्राप्तौ शत्रुसन्निधिं।। 45 ।।

आटोयेन समायुक्तं शत्रुं वीक्ष्य नरोत्तमाः।

जगौ स्नेह भराक्रांतो वाक्यं चाति मनोहरं।। 46 ।।

भो भो शत्रोमदीयं हि शृणु वाक्यं विचक्षण।

रामाया मम हर्त्ता त्वं बंधूनां चापि घातकः।। 47 ।।

दुःकृतस्य विकृतात्वं तथापि त्वयि निष्चितं।

अंतरंगं महास्नेहो जृंभिते किं करोम्यहं।। 48 ।।

तस्मात्समर्प्य वेगेन भार्यां मे गुण शालिनीं।

त्वं याहि जीवमानः सन्क्षेमे नैव ममाग्रतः।। 49 ।।

इत्युक्ते मदनः प्रोचे हसित्वा केषवं प्रति।

स्नेहस्यवसरः कोयं वर्त्तते हे भटोत्तमा।। 50 ।।

बंधूनां तवहंतहं हर्त्ता तु तव योषितः।

ईदृषेमयि स्नेहष्चेत् शत्रुः स्यात् तव कीदृषः।। 51 ।।

यदि योद्धं न शक्तोसि तदेवं पदमां प्रति।

भार्यां षिक्षां तुदं मह्यं वीर धीर समर्प्यय ।। 52 ।।

शत्रोर्वाक्यं समाकर्ण्य केषवः कोप पूरितः।

शाङठे मुंचडली कृत्वा प्राप्य शत्रुं मदोद्धतं।। 53 ।।

आकाशे च तथा भूमिं दिक्कं च जनार्द्दनः।

वाणौघैः स्छादयामास कोपसंछन्न विग्रहः।। 54 ।।

छादयंतं समालोक्य वाणैर्विष्वं ततोहरेः।

अर्द्धचन्द्रैण चिछेद धनुरस्य मनोभव।। 55 ।।

अपरं धनुरादाय हरिः कोपेन पूरितः।

यावन्मुचति वाणं तं तावत्तेनापि किं कृतं।। 56 ।।

छित्वा तदति चापं तं जगाद मधुसूदन।

ईदृषं चाप कौषल्यमर्ज्जितं भवता कुतः।। 57 ।।

ख्याताये यादवा भूमौ भोजाद्याः पांडवास्तथा।

तेषां मध्ये भवान् विष्णोः शस्त्र विद्या विषारदः।। 58 ।।

धानुधीर्यं मयाज्ञातं तवात्र युद्धकर्मणि।

रक्षितुं नैव शक्तो यो निजं चापं महाहवे।। 59 ।।

युद्धं कर्तुं न जानाति योवै भूपति वेष भाक्।

स्वेच्छाचारी तु सो भूत्वा जीवनं लभते कथं।। 60 ।।

अथवा बांधवैः सर्वैः किं वा कार्यं तु भार्यया।

सुखान् भुंजस्व ते गेहे जीवन् यादि ममाग्रतः।। 61 ।।

इत्यादि हास्य वाक्यैष्च शार्ङ्ठिणं ताडयन् स्मरः।

नारायणोपरं चापं नीत्वात मदनं प्रति।। 62 ।।

ममो च वाण निकरं मर्म भेद करं परं।

मायाविनोस्य कामस्य भिन्न सैन्यं तदाखिलं।। 63 ।।

पातयामासछत्रं च ध्वजं च सारथिं तथा। – युग्मं

तुरंगांष्चापरिजनं कामदेवस्य केषवः।

तावदन्यं समारुह्यं रथं वेगान्मनोभवः।

गुरुमात्मसमं चक्रे मायया किं न साध्यते।। 65 ।।

दिव्यं स्पंदनमारुह्य हरिर्वाहयदुत्तमः।

क्रोधादाहूय सद्विद्यां मुमोचहुद्धुकं शर।। 66 ।।

स गत्वाथ शरोदिव्यं प्रलयानलसन्निभः।

दहियमान्मथं सैन्यं परिवेष्ट्वा समं ततः।। 67 ।।

सछीत्कारं क्वचिद्वर्ः करोत्याश्रश्य शक्तितः।

ष्मत्कारं च क्व चिद्भीमं स्फुलिंगाणुनिरुद्धदिक्।। 68 ।।

कटकांतं स्फुटोद्दीप्तेह गद्वाटक भूषणः।

प्रपद्यमानमालोक्य पावकं मजमस्तदा।। 69 ।।

सस्मारवारुणं बाणं वाणासन परिग्रहः।

शरासनगतं वेगात् चिक्षेप च रिपुं प्रति।। 70 ।।

युग्मं– सोपिगत्वा महामेद्यः शक्तचाप विभूषितः।

गर्ज्जन् सो दामिनी युक्तो विमुंचणभतोषनि।। 71 ।।

मुसलाकारधारेभिः प्रवर्षणभता जलं।

नाषयन्मास वेगेन कृषानुमकृषत्विषं।। 72 ।।

अग्नि बाणमथात्मीयमव लोक्यापसारितं। – युग्मं

वायव्यस्त्रं महावेगं मुमोच मधुसूदनः।

तेनक्षिप्ता नरेभाष्वरथाष्चापि विदूरतः।।

छात्रकेतु ध्वजै सार्द्धं पत्र संघाइव क्षणात्।। 74।।

ततष्चिक्षेप कामोस्त्रं ताप संमोह कारणं

भृंगाभं कज्जल समं नीलं लोलमितस्ततः।। 75 ।।

तत्चक्रे खलवृत्तिर्वा समं सर्वं भुवस्तलं।

व्योमोः त्पादिकवृत्तिस्तस्तामसानां स्वभावतः।। 76 ।।

एवमादिभिरित्युग्रेर्द्रिव्यास्त्रैरितरैरपि।

प्रहरंतौ तावत्कार्यं विस्मयं खेटनायकं।। 77 ।।

यद्यदस्त्रं हरिः कामं चिक्षेप समरांगणे।

व्यर्थं बभूव तत्सर्वममोघमपि सत्वर।। 78 ।।

आष्चर्यमथ वा नात्र ये ये दिव्याषरारिह।

स्वस्मिन् कुलेन ते नूनं प्रभवंति कदाचना।। 79 ।।

रणैस्तु निष्फलैर्जातैः विलक्षोसौ जनार्द्दनः।

निज सैन्य विनाषेन चिन्तयामास चेतस।। 80 ।।

नैव शक्योन्यथा जेतुं दुर्ज्जयोयं पुरोरिपुः।

मल्लयुद्धं विहायैकं तत्करोमीति निष्चयं।। 81 ।।

दृढंपरिकर बध्वा विधिस्तु बाहु संगरं।

अवतीर्थ रथाद्भमौ तदा नारायनो बली।। 82 ।।

पाद घातेनत्राभूद्भूत तलं विवरैर्युतं।

संधयः पर्वतानां च प्राप्ता षिथिलतां परां।। 83 ।।

उनिद्रांवुज संकाष दिव्यरुप धरोवरः।

ताम्रदृष्टि दृढोकेंतमुग्र वाक् कोपपूरितः।। 84 ।।

कामोपि जनकं दृष्ट्वा बद्धः परिकरं तदा।

रथादुत्तीर्य वेगेन सन्मुखं चलितस्तदा।। 85 ।।

द्वि करीन्द्र समाकारौ द्धौयौद्धौ युद्धमुद्यतौ।

वीक्षतौ मातृ भार्याभ्यां मल्लवेष धरौ परौ।। 86 ।।

ताभ्यां तु नारदं प्रोचे भो भो नारद नारद।

त्वं गत्वा चाति वेगेन द्वावेतौ विनिवारयन् ।। 87 ।।

अस्माकं सर्वथा हानि रणयोर्युद्ध कामयोः।

अनयोर्विधिना तात किंचिन्नोगरति ध्रुवं।। 88 ।।

ताभ्यां तु नारदो वेगात् प्रेषितोत्र समागतः।

यावतौ बलातः शूरौ तयोर्मध्यमुपागतः।। 89 ।।

आगत्य माधवं प्राह भो भो माधव माधव।

सांप्रतं किमिदं भूप प्रारब्धं निजनंदने।। 90 ।।

कालसंवर गेहेयो वृद्धिं प्राप्ता गुणालयः।

नीत्वा षोडष वर्षाष्च षोडषाब्दे समागतः।। 91 ।।

मिलितुं जनकं हर्षात् त्वयातु क्रियते रणं।

निजपुत्रे रणं कर्तुं नैव युक्तं जनार्दनः।। 92 ।।

इत्युक्त्वा मदनं प्राह नारदो मुनि सत्तमाः।

भो भो काम निजे ताते किं तुया क्रियतेधुना।। 93 ।।

ताते तु जगतां पूज्य मल्लस्नेह हराविव।

मुचियित्वान्य चेष्टां त्वं पुत्र कार्यां वरं कुरु।। 94 ।।

इति साधो वचः श्रुत्वा माधवोत्यंत प्रेमतः।

संत्यज्यमल्ल चेष्टां तां स्नेहात् च सन्मुखं ययौ।। 95 ।।

पुत्रागमन हर्षेण शोकेन चल नाषनं।

द्रुतं मंद गतिर्विष्णु मदनाभि मुखं ययौ।। 96 ।।

जल्यन् कामं तदा कृष्णः शीघ्रं वत्सै हि सांप्रतं।

निजभुजवरगाढ़ स्नेह सौख्यं प्रयच्छभो।। 97 ।।

वाक्यं तात्स्य श्रुत्वासौ स्नेह गर्व मनोभवः।

कर्णयोः सुखदं रम्यं तुष्टचित्तौति हर्षतः।। 98 ।।

त्यक्त्वा वेगेन तं वेषं विनयात् नममस्तकं।

केषवःपादभि पद्मंसन नाम क्षितिमंडले।। 99 ।।

केष्वोप्यथ बाहुभ्यां उर्ध्वं भूत्वा निजं सुतं।

आलिंग्यचाति हर्षेण तस्थौमीलित लोचनः।। 100 ।।

पुलकौधचितौ द्वौहि शुचितां तः प्रमोदकौ।

निष्चलत्वं समासाद्य स्थितौ सं मिलिताविव।। 101 ।।

चिरं तथा विधौ दृष्ट्वा पूर्णचित्तोमुनिस्तदा।

जगाद ता विदं वाक्यं हसित्वानंद पूरितः।। 102 ।।

अकार्यं तिष्ठतोद्यापि किं भो वीरौ वनांतरे।

प्रवेषो द्वारिकायांहि कथं न क्रियतेधुना।। 103 ।।

लोकाः सतुत्सकाः सर्वे नरनारीगण ध्रुवं।

महोत्सवेन संयुक्तौ गच्छथः पुरमुत्तमं।। 104 ।।

इत्युक्तं तं समाकर्ण्य निस्वस्यासौ जनार्दनः।

नारदं प्रति प्रोवाच दुःख गदगदया गिरा।। 105 ।।

श्रृणु नारद वाक्यं मे जातौ सैन्य विवर्ज्जितौ।

पुत्रस्तु मिलितोयच्च जलं भव्यं तदेव हि।। 106 ।।

बंधुभिस्तु विहीनोहि द्वावेव नर नायको।

समस्तायातु पुर्यां वै स्थितौ सैन्य विवर्ज्जितौ।। 107 ।।

धारयावः कथं शोभां विषंतौ मुनिनायकः।

कस्योपारि ध्रुवं छात्रं धारयिष्यति सांप्रतं।। 108 ।।

इति दीनं वचः श्रुत्वा माधवस्य मुखोदϭतं।

हसित्वा नारद प्राहः विष्णोदुःखं निवारयः।। 109 ।।

मन्मथेन रणे नूनं न कोपि सांप्रतं हतः।

पीडितानैव कोप्यत्र गजवाजि पदादिषु ।। 110 ।।

यो वहन्ति ध्रुवं शत्रून् निष्चयेन मनोभवः।

हनिष्यति कथं विष्णोः निज तात वलं स च।। 111 ।।

मा कुरु त्वं वृथा दुःखं सैन्यनाष समुद्भवं।

नारायणं तदेत्युक्त्वा पुनः प्रोचे मनोभवं।। 112 ।।
किं भो काम त्वमद्यापि चेष्टां बाल जनादृतां।
विदधासि निजे ताते चिरं हास्यं न शोभते।। 113 ।।
हास्यं तु क्षणमेकंहि योग्यायोग्यवतां नृणां।
अतोनिवार्य हास्यं त्वं कुरुचेष्टां मनोहरां।। 114 ।।
उत्थाय सकलं सैन्यं कृष्णं हर्षेण पूरयन्।
इतिनारद वाक्येन मदनस्य तथा कृतं।। 115 ।।
उत्थापितं तदा सैन्यं गजवाजि समाकुलं।
सुप्तोत्थितमिवा भाति तत्र भूमौ निरंतरं।। 116 ।।
प्रोत्थिता यदुवीरास्ते प्रोच्चरंतो वचोवरं।
ध्नं तु गृष्णं तु वेगेन शत्रुं पापं रणांगणे।। 117 ।।
युद्धकामस्तदा दृष्ट्वा केषवोपि निजान् भटान्।
हसित्वा वचनं प्राह पूर्यतां पूर्यतां इति।। 118 ।।
ज्ञातं वः सकलं शौर्यं समरे भटसत्तमाः।
एकेनमम पुत्रेण कामपालेन मारिताः।। 119 ।।
सीरीतु पांडवा सर्वे विस्मयं परमं गतः।
श्रुत्वा नारायणस्येदं वाक्यं सर्वमनोहरं।। 120 ।।
पुनर्ज्जगाद कृष्णस्तान् बल पांडव पूर्वकान्।
अयं विद्या धराधीषः सर्वविद्या निधान भूः।। 121 ।।
मा यया सकलं विष्वं जेतु शूरो मनोलवः।
सांप्रतं मम पुत्रोयं मिलनार्थं समागतः।। 122 ।।
नारायण वचः श्रुत्वा भीमार्ज्जुन पुरस्सराः।
गजवाजि रथारुढा उत्तीर्णा वेगतो भुवि।। 123 ।।
मिलिताः कामदेवस्य स्नेहेन परिपूरिताः।

प्रणुताकामदेवेन यथा योग्यं तु बांधवाः।। 124 ।।

समुद्रविजयाद्यापि बलभद्र पुरस्सरः।

नमिता मस्तके नेह क्षतिसंलुलितेनहि।। 125 ।।

अपरै भूमिपालैस्तु प्रणुतो मदनस्तदा।

आष्लिष्यचाति हर्षेण कुषल प्रष्न पूर्वकं।। 126 ।।

प्रमोदं परमं प्राप्ता मदनं वीक्ष्य बान्धवाः।

योग्येन स्वजने दृष्टे कास्य तोषो न जायते।। 127 ।।

निःसृत्य चागतो भानुः सैन्य मध्येत्तदाद्रुतं।

गत्वा चासौ निजं गेहं मातरं तत् निवेदयत्।। 128 ।।

कामस्या गमनं यावत् भानुर्जल्यति मातरं।

तावत् तत्र समायाता रावयोप्यखिलाननु।। 129 ।।

वाटिका या वनस्यैव वापिकाया रथस्य चः।

पुष्पाणां प्रकरस्यैव कन्यया हरणस्य च।। 130 ।।

श्रुत्वा सा तु विषया भूत् सत्यभामा सुतेन च।

तदुःखं गदितुं शक्यं केन केवलिन विना।। 131 ।।

अथनारायणः प्रोचे मदनं प्रेम लालसः।

आनयस्वर द्रुंत वत्स त्वदीयामंबिका मिह।। 132 ।।

इत्युक्ते सावधो भागं यदापष्यति मन्मथः।

पुनः प्रोवाच विष्णुस्तं कथं नानीयते त्वया।। 133 ।।

कृष्णस्य वचनं श्रुत्वा नारदोपि जगाविदं।

निजनारी तु सर्वेषां वल्लभा वसुधातले।। 134 ।।

तत्कथमित्युक्ते तेन नारदः प्राहतं तदा।

स्वमातरं च युवतिं वेगादानीयतामिति।। 135 ।।

इति वाक्यं कथं कृष्ण भवता जल्यितं नहि।

तेन वा कारणोनायमधोबक्रोव तिष्ठते।। 136 ।।

इत्युक्ते तु हरिः प्राह क्वा प्राप्तावधूटिक।

नारदोथ हरिं प्राह श्रुणुवाक्यं जनार्दन।। 137 ।।

दुर्योधनेन या पुत्री भानुर्विवाह कर्मणि।

प्रेषितोदधिसंज्ञाहि सा ह्वतामदनेन तु।। 138 ।।

शावरं वेषमाधाय जित्वा कौरवपुंगवान्।

साधुना वर्त्तते नूनं विमाने रुक्मिणी युता।। 139 ।।

तेन वाक्येन संतुष्टो हरिः प्रोचे मनोभवः।

भार्यां च जननीं प्राह समानयद्रुतं सुतः।। 140 ।।

तेन वाक्येन कामेन विमानं क्षिति मंडले।

सामाह्वतं तु वेगेन माता भार्या समन्विताः।। 141 ।।

विमानं तं समालोक्य सर्वे यादव पुंगवाः।

प्रहष्टाः सहसा नूनमपूर्वस्य विलोकयन्।। 142 ।।

रुक्मिणी तुस्तुषा सार्द्धमुत्तीर्य गगनांगणात्।

विष्णोः पद युगं भक्त्या नमामि विनयान्विता।। 143 ।।

सा तुषां रुक्मिणी दृष्ट्वा संतुष्टो हरिरुक्तवान्।

अमात्यैस्त्वं पुरीं गत्वा विधेहि सोत्सवां पुरीं।। 144 ।।

कृष्णवाक्येन संतुष्टो रुक्मिणीं सचिवैः समं।

गत्वा महोत्सवं चक्रे पुत्रागमन सूचकं।। 145 ।।

सन्मार्य नगरीं सर्वां सृछंद्य चंदनांभसा।

पुष्पैरागुल्फपर्यन्तं पूरिता सातिसुंदरैः।। 146 ।।

हट्टानां रचिता शोभकेतु जालैस्तु तोरणैः।

श्रृंगार्य विविधैर्वेषै रुक्मिणी प्रेमपूरिता।। 147 ।।

अमात्यैः कृष्ण भूपालं विनयानतमस्तका।

भक्त्या विज्ञापयामासपुरीं श्रृंगारिता विभो।। 148 ।।

तेन वाक्येन तुष्टो सौ पटुपटह नादकैः।

वाजित्रैर्विविधैर्युक्तो नृत्यद्भि कामिनी जनैः।। 149 ।।

महोत्सवने महता विप्रवेष पुरं यदा।

समुद्र विजयाद्यैष्च भूपालैर्बहुभिर्वृतः।। 150 ।।

नरनारीजनास्ता च दृष्टु कामाः समागताः।

विपरीत्य निजं रूपं चेष्टां चक्रु रथांगना।। 151 ।।

कज्जलेनमुखं लिप्त्वा नेत्रेतु कुंकुमेन हि।

नूपुरं कर्णयोष्चक्रु कर्णाभरण पादयो।। 152 ।।

इतिनानाविधं चेष्टां कुर्वन्त्यः पुरयोषितः।

त्यक्त्वा चार्द्ध कृतं कार्यं वेगात्तत्र समागताः।। 153 ।।

कामदेवस्य तं रूपं दृष्ट्वा तुष्टा स्वमानसे।

कामिन्यो मिलितास्तत्र जगुरेवं परस्परं।। 154 ।।

कामदेवेन तुल्यष्चेत् नरोनोभवितायदि।

अपरै काष्टरूपैष्च पुरुषै किं प्रयोजनं।। 155 ।।

तत्रापराऽबला प्रोचे यदिस्यात् नंदनोमम।

तदा तु काम देवेन तुल्यो भवतुनान्यथा।। 156 ।।

रुक्मिणी तु ध्रुव धन्या ययायमुदरे धृतः।

धन्योत्र वासुदेवोयं यस्य गेहे समुदõõr%AA 157 AA

अपरा कामिनी प्रोचे ध्न्या सा कनकस्रजा।

ययायंवर्द्धितो वाल्येपयःपानं तु कामिनी।। 158 ।।

यादवानां कुलस्यैव पुण्यं जगति विश्रुतं।

द्वारिकाया महत् भाग्यं यत्रायं विचरष्यति।। 159 ।।

सवथोदधिकन्याया प्रषस्यं पुण्यमेव हि।

रमिष्यति हयानूनं अस्यैवांक निवर्त्तिनी ।। 160 ।।

परस्परं परा प्रोचे कामिनी कामिनीं प्रति।

पष्य पष्य सखेचायं मदनोत्र समागतः।। 161 ।।

एषेनारायणस्यै बाल्येयोरिपुणा ह्रताः।

खदिरवनमध्ये हि षिलयापिहितः कृतः।। 162 ।।

आगत्य खेटनाथेन निष्कास्य निजविद्यया।

वृर्द्धितोयो गृहं नीत्वा विद्यया परिभूषितः।। 163 ।।

लाभांष्च विविधां नीत्वा विद्यां विद्याधरोद्भवां।

पितृगेहं समायाता रुक्मिण्याः पूर्व पुण्यतः।। 164 ।।

रिपुस्तु परमो बंधु जातोस्य पुण्य योगतः।

यद्यत्रैव कुमारोयं वर्द्धते च गुणाकरः।। 165 ।।

क्व चास्य विविधालाभाः क्व चास्य नभसोगतिः।

क्वः प्राप्तिः पुष्पचास्य क्व कीर्त्तिः क्षितिमंडले।। 166 ।।

वहवो पादवाः संति पुर्यांतु कुल संभवाः।

एकस्याप्यभिधानं हि ज्ञायते केन चिन्नहि।। 167 ।।

अपराजगाद किं मूढे जल्यसीत्थं पुनः पुनः।

पुण्येन प्राप्यते सर्वं विद्या कोषोधनंयषं।। 168 ।।

पूरा जन्मनि चान्येन चरितं दुष्चिरंतपः।

सत्या तेभ्यः परं दानं दत्तं भावयुतेनहि।। 169 ।।

पूजा श्रीजिनचन्द्रणां कृता भावेन जन्मनि।

भचारित्रं निर्मलं चाथ पालितं चान्यथा कुतः।। 170 ।।

एवं विधान्यथा विद्याषौर्यं चापि मनोहरं।

शक्ति गुरुजने रम्या लक्ष्मीस्यात् कथमन्यथा।। 171 ।।

जनोक्तं नितरां कामः श्रृणु नाना विधां तदा।

गजारुढः सित छत्रोवीज्यं मानोपि चामरैः।। 172 ।।

सीमंतिलीजनस्यासौंनेत्र कैरवचन्द्रमाः।

पित्रासमं जनन्यापि प्रापवैष्म कृतोत्सवः।। 173 ।।

पुत्रं दृष्ट्वा समायातं सर्वलक्षणा लक्षितं।

अर्घपाद्यादि पूर्वं सा माता चक्रे सुमंगलं।। 174 ।।

मदने तत्र समायाते सर्वेषां सोत्सवो भवत्।

सत्यभामां तथा भानुं विहायान्य जनस्य च।। 175 ।।

बल कृष्णोपि मदनष्चान्येपिनरनायकाः।

रुक्मिण्यास्तु गृहे सर्वेव भुजुः प्रेम भूषितः।। 176 ।।

किं यंतो दिवसास्तत्रतस्छुः सर्वे महीभृतः।

स्थित्वा तु कृष्ण भूपालो जगाद सचिवान् प्रति।। 177 ।।

विवाह्योमदनो नूनं महोत्सव पुरस्सरं।

इतिस्मृत्वास्मरः प्रोचे वाक्यं विनय संयुतं।। 178 ।।

कालसंवर भूपेन समं कनकमालया।

विवाहो मे ध्रुवं भावीनान्यथा तु भविष्यति।। 179 ।।

इत्युक्त्वा प्रेषयामास दूतं खेट महीधरं।

दूतो गत्वातिवेगेन प्रद्युम्नोक्तं निवेदयन्।। 180 ।।

कालसंवर भूपोपि समं कनकमालया।

विमृष्य गंतु कामो भूल्लज्जा व्याकुल मानसः।। 181 ।।

मेलयित्वा महासैन्यं नीत्वा कन्या कदंबकं।

रतिपन्नीसमं नीत्वा तां तु तत्र समागतः।। 182 ।।

आगच्छन्तं तथा श्रुत्वा खेचराणामधीष्वरं।

तातेनापि वलेनापि सन्मुखं मदनो ययौ।। 183 ।।

तस्याः पादौ नमस्कृत्य तथा कनकमालिकां।

प्रणिपत्य महास्नेहात् कृष्णोपि मिलितोमुदा।। 184 ।।

रुक्मिणीस्तु समागत्य वनमध्येति मोहतः।

तस्याः कनकमालाया मिलिता विनयान्विता।। 185 ।।

कृष्णोमहोत्सवेनैव प्रविवेष पुरीं मुदा।

भक्त्यासंतोषयामास महोत्सव पुरस्सरं।। 186 ।।

पुर्यांमहोत्सवो जातो वाद्यद्वाद्य मनोहरः।

नृत्यत्सोवासिनी रम्या गीत गान समन्वितः ।। 187।।

क्वचित् च वाद्यन्निर्घोषः श्रूयंते भ्रमरैः कृताः।

क्वचिदतिषयं नृत्यं दृष्यते स्त्रीजनैः कृतं।। 188 ।।

क्वचित्याकिनीवृंदं क्वचिद्वारत्नतोरणं।

हयानां निवहा क्वापि गजवृंदं क्वचिद्य्वनं।। 189 ।।

क्वचिद्रथसमूहाष्च छत्र संघाः क्वचित्पराः।

उत्सवै विविधैस्तत्र युक्ता जाता पुरी तदा।। 190 ।।

चिंतिताप स्थितायां तु विभूत्यां मदनोवरः।

अष्टविधाभिरर्च्चाभिः संपूज्य श्री जिनेष्वरां।। 191 ।।

मिलितेषु सवेभूपेषु जगाद वचनं स्मरः।

सत्याया वेणिकां वेगादानीयतां मम।। 192 ।।

तस्योपरि पदं दत्वा हयारुढो भवाम्यहं।

बलदेव समक्षं हि प्रतिज्ञेयं पुरस्कृता।। 193 ।।

रुक्मिणी तद्वचः श्रुत्वा जनानां वदनाः ध्रवुं।

समागत्य सुतं प्राह नैवं वक्तुं प्रयुज्यते।। 194 ।।

त्वय्यत्रैव समायाते सत्याया मुंडितं षिरः।

शतधा तु खरारुढा विगुप्ताः किं विगोप्यते।। 195 ।।

रुक्मिण्यावारितः कामष्चटितोसौ हयोत्तमेः।

पूरयन याचकानां च वांछा कल्पद्रुमोपमः।। 196 ।।

कालसंवर खेटेन कृष्णेन सबलेन च।

उत्सवैर्विविधैर्युक्तो जगामासौ वनं मुदा।। 197 ।।

कामरत्योर्विवाहो भूत् तत्रैव सुंदरं वनं।

आनन्दः स्वजनानां च जात्येत्यं तं सुखां वहं।। 198 ।।

पंचषत्यष्ठ संख्याष्च सुररामासमास्तुयाः।

प्राप्तास्तेनैव कामेन कन्या उदधिपूर्वकाः।। 199 ।।

परीणीय महाभूत्या विवेष नगरीं स्मरः।

खेचरै रेव विहितो विवाहो विष्णु वाक्यतः।। 200 ।।

स्वजनापरिजनौघाः पूजितास्तु यथा क्रमं।

कियत्कालं स्थितास्तत्र खेचरौघाः सुखान्विताः।। 201 ।।

एकदा तु हरिं प्राह कालसंवर भूपतिः।

विनयं परमं कृत्वा संकोच्यकर संपुटं।। 202 ।।

यदि विष्णोर्ममादेषं ददाषि कृपया विभो।

गच्छामि स्वजनैर्युक्तोस्तदाहं नगरं निजं।। 203 ।।

गंतुकामे खेटेष जगावेवं जनार्दनः।

दर्षयित्वापरं स्नेहं सभायां बांधवैर्युतः।। 204 ।।

वद्धितोयं त्वया मित्र नीत्वा तु निजमंदिरे।

तस्मात्कमोपिते पुत्र प्रथमं चरामं ममः।। 205 ।।

एवं विचिंत्य खेटेषत्वयेपि मदने सुते।

यथाहितु विधेयंहि रुक्मिण्यपि तथा जगौ।। 206 ।।

तथा कनकमालां च संतोष्यविधिपूर्वकं।

वस्त्राष्चाभरणैसर्वैः संतोष्य च पुनः पुनः।। 207 ।।

सर्वे ते खेचरास्तेन विष्णुनादर पूर्वकं।

तोषिता प्रेषितागेहं निजं खेट महीधरं।। 208 ।।

संप्रेष्य चलितो विष्णु रुक्मिण्यास्तु समन्वितः।

खेचराणां कथां कुर्वन् जगाममनिमंदिरं।। 209 ।।

मदनोपि ययौ सार्द्धं पितृभ्यो मोह संयुतः।

कियत्दूरं ततो गत्वा नत्वा तु पदपंकजं।। 210 ।।

संतोष्यविनयं कृत्वा चलितो चालितस्तदा।

चलित्वा नगरीं प्रापसौत्सवैः यादवैर्युतं।। 211 ।।

ततोथ सुखिनोजाता यादवा भोजगादयः।

माता पित्रोः परं सौख्यं जातं विवाहः दर्षनात्।। 212 ।।

नारदोपि सुखीजाताः सोत्सवां रुक्मिणीं तदा।

मन्यमानः परं दृष्ट्वा मनोर्थं सफलं निजं।। 213 ।।

सत्यायास्तु परं दुःखं दृष्ट्वातोषं परं गतः।

जगाम स्वेच्छया स्थानं नारदः प्रमदान्वितः।। 214 ।।

नारीवक्र सरोजेषु मधुपो मदनस्तदा।

सुखसागर मध्येस्थोपित्रोर्भक्तिभरानतः।। 215 ।।

विवुधैः सेव्यमानोसौ षट् सुकर्मसु तत्परः।

परमाÈाद संयुक्तो गतं कालं विवेदन।। 216 ।।

अथ सा सत्यभामापि काम विवाह दर्षनात्।

अति दुःखाकुला जाता निमग्नादुःख सागरे।। 217 ।।

याचायित्वान्य कन्यौघान् सर्वलक्षण लक्षितान् ।

अनायाभानुपुत्रेण विवाहमकरोद्वरं।। 218 ।।

तदाभानु कुमारोपि बुभुजे सुखमुत्तमं।

ताभिरामाभि संयुक्तो मातुर्भक्तो गुणालय।। 219 ।।

जाताकाममयी कीर्त्तिः सर्वत्रवसुधातले।

चतुः पथेथ पुर्याचतदेव हि कथानक।। 220 ।।

निजपुण्य प्रभावेन प्राप्तं तेन बलीय सा।

चिंतितं भुवने नर्ध्यं तत्सर्वं पुण्यहेतु जं।। 221 ।।

प्राप्यते स्वजन संगम नरैष्चिंतितार्थं मनघंयदुत्तमं।

सेव्यते सुरनरैर्दिवानिषं पुण्यभूरुह फलं विबुध्यतां।। 222 ।।

धर्मात्सौख्यमनेकधा शुचितरं धर्माद्यषो निर्मलं।

सौजन्यं स्वजने जयं रिपुजले विद्याविवेकादयः।। 223 ।।

सेवध्वं जिन भाषितं शुभतमं धर्मा यतः प्राप्यते।

संसार व्यसनादि तापहरणे सोमेव सौम्यं बुधाः।। 224 ।।

***इति श्री प्रद्युम्नचरित्रे आचार्यसोमकीर्त्तिविरचिते प्रद्युम्न**

युद्धस्वजनसंगविवाहोत्सव वर्णनोनाम

एकादशमः सर्गः। *

द्वादश सर्गः

अथकामेस्थिते तत्र सुख सागर वर्त्तिनिं।

रचितं कथयामीह दिव्यं षंबु यषस्विनः।। 01 ।।

अथैकदासुरष्चासौ यः स्थितः षोडषे दिवि।

कैटभस्य चरोनूनं मनुजो मदनस्य च।। 02 ।।

विबुधैः सेव्यमानो हि विमाने विमले स्थितः।

जाता जिनेष्वरं नत्वा मतिरस्य महामुनैः।। 03 ।।

भक्त्या परमयायुक्तः शुभभाववषीकृतः।

मेरोस्तु पूर्व दिग्भागे क्षेत्रे विदेह संज्ञके।। 04 ।।

पुर्यां तु पुंडरीकिण्यां प्रसिद्धायां क्षितौ सदा।

पद्मनाभ नरेन्द्रेण पालितायां दिवानिषं।। 05 ।।

गत्वा तत्र परं भक्त्या नमाम जिन पादयोः।

सुश्रावचजिनेन्द्रोक्तं धर्मं दुःख विनाषकं।। 06 ।।

अपसरंतु समासाद्य पुनर्नत्वा जिनेष्वरं।

भवं प्रपच्छ चात्मीयं विबुधोसौपुरातनः।। 07 ।।

विष्वनाथ जगात्याल विष्व वल्लभ चेष्टितः।

कथयस्य कृपां कृत्वा भवान्मम गुणाकरः।। 08 ।।

तस्य वाक्यं समाकर्ण्य जगाद जिननायकः।

श्रूयतां विबुधाधीष कथयामि समासतः।। 09 ।।

द्विजस्य भवदारभ्य विबुधां तं जिनोत्तमः।

कथयामास साभिज्ञं नारदोयं यथापुर।। 10 ।।

श्रुत्वा निज भवान् सर्वान् जगादमरनायकः।

क्व वर्त्तते जिनाधीष मम भ्राता सहोदरः।। 11 ।।

तदाप्रोक्तं जिनेन्द्रेन द्वारिकायां जनार्दन् ।

रुक्मिणी तनु संभूतो वर्त्तते मदनाभिधाः।। 12 ।।

इति श्रुत्वा सुरः प्राहः श्रृणुनाथ वचो मम।

अग्रजेन च संयोगो भविष्यतिथ वानहि।। 13 ।।

प्रत्युत्तरं जिनः प्राह श्रूयतां विबुधाधियः।

अवस्यं युवयोस्तत्र संयोगो वै भविष्यति।। 14 ।।

कृष्णस्य तनस्त्वं हि भविष्यसि न संषयः।

इति जैन वचः श्रुत्वा प्रमोदं विबुधोगतः।। 15 ।।

प्रणम्य परया भक्त्या तीर्थराजं पुनः पुनः ।

निसृत्य चातिहर्षेण द्वारिकां नगरींगतः।। 16 ।।

सभां संप्राप्य विष्णोष्च प्रणमादौ जनार्दनः।

जगाद परया भक्त्या विकषन्नयनाबुजः।। 17 ।।

श्रृणु केषव मद्वाक्यं सावधान तुया विभो।

भविष्याम्य चिरेणैव तव पुत्रो न संषयः।। 18 ।।

कामवद्वल्लभो नृणां प्रमदाजनचित्तमुट्।

अमुके च दिने पक्षे स्थातव्यं योषिता सह।। 19 ।।

समर्पितस्ततस्तेन हारोस्मैमणिभासुरः।

तेजसा दीप्यमानोहि सूर्य कोटि समं प्रभः।। 20 ।।

दातव्यो यं त्वया कृष्णमज्जनन्यै मनोहरः।

सदैव सुमुहूर्त्ते हि हारोन्य जन दुर्ल्लभः।। 21 ।।

इत्युक्त्वासौ विमानं स्वजगाम प्रमुदान्वितः।

गतेथविबुधे तस्मिन् कृष्णोभूत हर्षपूरितः।। 22 ।।

चिंतयामास तत्कार्यां ज्ञात्वा तं मदनानुजं।

अवतारयामि पुत्रं क्व चैनं गुणसागरं।। 23 ।।

एवं विचिंत्यमानेस्मिन् बुद्धिरेखा समुद्गता।

कामस्य सत्यभामाया विद्वेषो वर्त्तते तरां।। 24 ।।

अवतारयामि तस्मात् सत्याया जरे सुते।

सत्यायामदनेनातः प्रराांप्रीतिर्भविष्यति।। 25 ।।

विमृष्यैव ध्रुवं चित्ते कृत्वा काम भयास्थितः।

न कस्यापिहितद~*xq*ह्य*a rsu* तत्र निवेदितं।। 26 ।।

कथंचिद्दैव योगेन वृत्तं तत् मदनैनहि।

जातं भ्रातृ भवं सर्वंहारादिकं समर्पिण। 27 ।।

ततोपि जननी गेहं गत्वै कांते निवेदयन्

परमंतु विनयं कृत्वा पुत्रोत्सवेतु मोहिनीं।। 28 ।।

श्रृणुमात मदीयं हि वाक्यं सर्व मनोहरं।

सप्रभवान् मयासार्द्धे भ्रमितोयो ममानुजः।। 29 ।।

सोधुना वर्त्तते स्वर्गे षोडषे सुरनायकः।

कृष्णस्य तनयत्वेन सचात्रोवतरिष्यति।। 30 ।।

अवस्यं कृष्ण जायाया जिनोक्तं न मृषा भवेत्।

अतस्त्वं सत्य भामायाः कृष्णो दातुं समीहते।। 31 ।।

यदि वांछसि ते देवं सर्वगुणाकरं।

अवतारयामि तेहं जठरेवं न संषयः।। 32 ।।

इत्युक्ते रुक्मिणी प्राह त्वयेदं क्रियते कथं।

त्वदायन्तं न कार्यं हि चैतत्पुत्र कदाचन।। 33 ।।

इत्युक्ते मदनः प्राह सत्यभामादिने तव।

कृत्वा तु कृतिमं रूपं प्रेषयामि तवांविके।। 34 ।।

रुक्मिण्यायिस्मितं कृत्वा जगाद मदनं प्रति।

पुत्र वाक्येन संतुष्टा शृणुपुत्रो वचो मम।। 35 ।।

पूर्यतां मम पुत्रेण कष्ट रूपेण सांप्रतं।

तव तुल्यस्त्वमेवात्र किंरवेस्तु समोपरं।। 36 ।।

यदि त्वं मम पुत्रोसि तदा मद्भणितं कुरु।

इयं जाम्बुवती वत्स सपत्न्यापि मम प्रिया।। 37 ।।

अस्योदरं सुतं रंतुमवतारय निष्चितं।

तस्याः कृष्णेन सार्द्धं हि विरोधो वर्त्तते परं।। 38 ।।

उत्तमानां विभूतिस्त्रुपरोपकृतये क्षमा।

येनकेनोप्युपायेन तस्या दुःख निवारया।। 39 ।।

जनन्यांः वचनं सर्वं करिष्यामीति निष्चितं।

इत्युक्त्वा जननीं नत्वा जाम्बवती गृहंगतः।। 40 ।।

तत्र गत्वा तु तां नत्वा चैकांते तन्निवेदयत्।

ततः सा मदनं प्राह विरोधो विष्णुना नमः।। 41 ।।

त्वं तु पुत्रोसि हे वत्स कथंमसुत संभवः।

ततो विद्यामयं सर्वं निजं तस्यै निवेदयन्।। 42 ।।

तेन वाक्येन सा तुष्टा जगाद मदनं प्रति।

त्वं मुत्तमो सिंहे पुत्र यथा ते रुचिरं कुरु।। 43 ।।

तेन वाक्येन तुष्टोगान्निजगेहं मनोभवः।

स्थितोस्तत्रैकचित्तेन सोपितत्समयं प्रति।। 44 ।।

अत्रांतरे समायातो वसंतो लोक वल्लभः।

चूतां मंजरिता सर्वे चक्रुः शब्दं तु कोकिला।। 45 ।।

पुष्पताः किंषुकास्तत्र चेतांसीव वियोगिनां।

संजाता मधुपाला यामानिनीमान भंजकाः।। 46 ।।

कृष्णोपि चैव मासस्य शुक्ले हि दषमीदिने।

निवेद्य सत्यभामायै स्वयं रंतुं वने गतः।। 47 ।।

गिरौरैवतकेनाम्नि कृत्वा पुष्पगृहं परं।

स्थितोदिनत्रयं तत्र कृष्णस्तु पुत्रवांछया।। 48 ।।

सत्यभामाप्रमोदेन पूरिता तु तदा जनि।

दिनत्रयं गतं ज्ञात्वा गंतुकामावने भवत्।। 49 ।।

अतरांतरे कामोपि गत्वा जाम्बवती गृहं।

रूप प्रावर्त्तिकां दिव्यं ददावस्यै स्वमुद्रिकां।। 50 ।।

सा मुद्रिका प्रभावेन विकृत्यं च निजं तदा।

दधारसत्यभामाया रूपं विस्मय कारकं।। 51 ।।

दृष्ट्वा तं दर्प्पणे रूपं निजं सत्याकृतिं वरां।

सन्तोषं परमं प्राप्ता मदनं तुष्ट मानसा।। 52 ।।

मदनोपि तदा प्राह शृणु मात वचो मम।

सिद्धेकार्येत्वया ग्राह्यं निजं प्रकृतिजंतनुं।। 53 ।।

इत्युक्त्वा षिविकारुढां कृत्वा तातु मनोभवः।

स्वल्पैः परिजनैः सार्द्धां प्रेषयामास सत्वरं।। 54 ।।

मुद्रयामुद्रितासाथ गत्वा रैवतकं गिरिं।

मिलिताघोष जस्यैषानता पादांबुजद्वयं।। 55 ।।

कृष्णोपितां समालोक्य प्रमोदं परमं गतः।

जगादचस्मितं कृत्वा ज्ञात्वां सत्यकां तदा।। 56 ।।

भव्यं कृतं त्वया देवि यदत्रत्वं समागतः।

कामानुजष्च ते नूनं जठरेव तरिष्यति।। 57 ।।

न ज्ञाता मदने नत्वामागच्छन्ती वने वरे।

सुरस्यापि च वृत्तांतं न ज्ञातं तेन निष्चितं।। 58 ।।

इत्युक्त्वा तु तथा सार्द्धं क्रीडां चक्रे जनार्दनः।

हाव भाव विलासाद्यैः सापि कृष्णेन चारमत्।। 59 ।।

सुरतांते सुरः सोपि ततष्च्युत्वा सुरालयात्।

अस्योदरे समृत्पन्नः पुण्यात्किं किं न वाप्यते।। 60 ।।

ततोथ कृष्ण भूपेन हारस्तस्यै समर्पितः।

सापि तं हारमादायं कंठे चक्रेन्यदुर्लभं।। 61 ।।

परिधाय च तं हारमुत्तार्य मुद्रिकांगुले।

निजं जांबवती रूपं जग्राह सहजं तदा।। 62 ।।

तस्या जाम्बवती रूपं दृष्ट्वा कृष्ण महीपतिः।

विस्मयं परमं प्राप्ताष्चितयष्य मुहुर्मुहुः।। 63 ।।

तदा जाम्बवती प्राह मदनः किं मिलितस्तव।

निजविद्या प्रभावेन येनेदं निर्मितं तनुं।। 64 ।।

ततो जाम्बवती प्राह नत्वास्य चरणांबुजं।

कृपां कुरु कृपाधार मुंच कोप पुरातनं।। 65 ।।

इत्युक्तेथ हरिः प्राहमुक्तकोपस्त्रिया सह।

अद्य प्रभृतित्वंमेसि प्राणेभ्यौतिष्य वल्लभः।

दैवेनापिकृतं सर्वमन्यथा त्वं क्षणात्पुनः।। 67 ।।

किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः।

है वोयस्य छलान्वेषी करोति विफला क्रियां।। 68 ।।

तव पुण्येन मे नूनं पुत्रोयं सुर नायकः।

शंबुनामाति विख्यातो भविष्यति जगन्नुतः।। 69 ।।

इत्युक्त्वा तातु संतोष्य कृष्णो जाम्बवती मुदाः।

प्रेषया मास वेगेन निजंगेहं भयाकुलः।। 70 ।।

सत्यभामाथ गर्वेन प्रमोदंदधतीपरं।

भूषणां मज्जनं स्नानं चक्रे गर्व समन्वितः।। 71 ।।

स्वं विभूष्य यथा शक्त्या शेखरादि विभूषणैः।

आरुह्य षिबिकां दिव्यां निर्गता बहुभिर्जनैः।। 72 ।।

यावन्मार्गे समायाति सत्यभामा जनैर्युताः।

तावदग्रे तु मिलिता नूनं जाम्बवती च सा।। 73 ।।

प्रपछपरिजनं साथ सत्यभामा निजं तदा।

केयं हि षिबिका रम्यं समायाति पुरो मम।। 74 ।।

परिवारेण तत्रोक्तं मियं जाम्बवती तनुः।

सत्यभामा ततः प्राह क्वेयं निर्न्नामिकागता।। 75 ।।

सत्यं जाम्बवती प्राह वामतो गच्छ पापिनीं।

ततो जाम्बवती प्राह गर्व गेह खल श्रृणु।। 76 ।।

पूरिते हिरितिक्तं वयस्तु मिलति सन्मुखं।

अपसरतेहिरिक्तं स्थाने तिष्ठति पूरितं।। 77 ।।

कालक्षेप भयात्रां हि मुक्त्वा तत्रैवस्थानके।

जगाम सत्यभामापि समीपं कृष्ण भूपते।। 78 ।।

कृष्णोरति गृहे यावत् स्थितोमार्गं तु पष्यति।

तावत् तत्र समायाता सत्या बहु जनान्विता।। 79 ।।

सापि संभोगमासाद्य कूजितर्भाषितेस्तथा।

पुष्पस्यसंस्तरे दिव्ये हरिणा तु शची समा।। 80 ।।

शषिरेणमारुतेनापि नूनं परिश्रमा मधु।

मदारुणनेत्राणां चरणान्मणि विभूषणा।। 81 ।।

कामविकार संयुक्तै क्वणितैः सुसितैस्तथा।

स्वदबिन्दु समायुक्ता रमिता रमण प्रिया।। 82 ।।

ततः स्वर्गात्सुर कोपिच्युत्वास्य जठरे पुनः।

अवत्ततार तत्रैव समये पूर्व पुण्यतः।। 83 ।।

कृष्णेन सत्यभामयाः कोपिहारः समर्पितः।

तं नीत्वा परिधायांगे सत्याभूत्तुष्ट मानसा।। 84 ।।

भाग्यानुसारि सर्वं हि प्राप्यते प्राणिभिः सदा।

कृष्णोथ दयिता युक्तोः पुरीं प्राप्तो महोत्सवैः।। 85 ।।

गर्भौतौवर्द्धमानौहि प्रियरामा समुद्भवौ।

सर्वेषां यादवानां तु जातौ चित्तहरोपरौ।। 86 ।।

कामेन भानुना चापि पूर्यंतेहि मनोरथः।

सत्यायाजांबवत्याष्च गर्भयोर्वर्द्धमानयो।। 87 ।।

विभूतिः परमावृद्धिं प्राप्ता यादवा मंदिरे।

मुखं हर्षेधनं धान्यं तयोस्तु वर्द्धमानयोः।। 88 ।।

जाम्बवत्याः परं गर्भं श्रुत्वाथ सत्यभामिका।

चिन्तयामास गर्वेन कोपि कष्चिद्भविष्यति।। 89 ।।

च्युत्वायो षोडषात्स्वर्गात् संजातो वै महोदरे।

सामान्येनापरेणापि किं कार्यं च सुतेनहि।। 90 ।।

अन्यच्च चिंतयामास यद्ययं मदनानुजाः।

ममोदरेसमुत्पन्नः कथं कामोनभक्ति भाक्।। 91 ।।

एंव विचिन्त्यमाना सा स्थिता गेहं निजं यदा।

तदा तु नवमासाहि तयोर्ज्जातास्त गर्भयोः।। 92 ।।

सुमुहुर्त्ते शुभेयोगे सुलग्नेच शुभे दिने।

असूततनयं तन्वी रम्यं जाम्बवती शुभं।। 93 ।।

स्फुरन्मणि समाकारं नीलरोचिं मनोहरं।

सर्वलक्षण संपूर्णा सर्वावयसुंदरं।। 94 ।।

समयेथतास्मिन्नेव कृष्णभूपस्य सारथेः।

पद्मनाभेष्च पुत्रो भूत्सुधारक समाद्वयः।। 95 ।।

वीराभिधो महामन्त्री तस्यैव कृष्णभूपतेः।

तत्रैव समये तस्य पुत्रो भूत् बुद्धिसेनकः।। 96 ।।

गरुडकेतुरितिख्यातः तस्यैवच चमूपतिः।

जयसेनाभिधः पुत्र संजातः समये वरे।। 97 ।।

त्रिभिरेकदिनोद्भूतैः र्ववृधे मदनानुजः।

महोत्सवः परं जातो दान पूजा पुरस्सरः।। 98 ।।

वंदिनां वंदिमोक्षो भूत् तस्मिन् जाते सुतोत्तमः।

शम्बुस्तु स्वजनैः सर्वैः स्ततो नाम प्रतिष्ठितं।। 99 ।।

सत्यभामा सुतं रम्यमसूत शुभ लक्षणं।

जितभानुं शुभानुं च तस्य नाम प्रतिष्ठितं।। 100 ।।

सर्वलोक प्रियौरम्यौ शुभ वेष धरौ परौ।

संपूर्ण चन्द्रवदनो पद्म नेत्रौ मनोहरौ।। 101 ।।

सर्वासां यदुनारीणां करपंकज वासिनौ।

नेत्रचित्त हरौबालौ दृष्यतेषद्यदौयद्य।। 102 ।।

कराच्चकरसंचारं लालितौ लक्षणान्वितौ।

भूषणैर्विविधैयुक्तौ कामभानु समर्पितैः।। 103 ।।

रणन्नूपुर संयुक्तौ किंकिणीभिः विराजितौ।

ललितानि पदानीह दातुं तत्र समुद्यतौ।। 104 ।।

कामभान्वनुजौवीरौ क्रमात् वृद्धिंमुपागतौ।

कामः शम्बुकुमारं च पाठयामास प्रत्यहं।। 105 ।।

भानुः सुभानुतोमानमनुजं वर लक्षणं ।

पाठयामास सिद्विद्यां कला कौषलमात्मनः।। 106 ।।

कलागुण विदग्द्यौ तौ जातौ द्वोच कुमार कौ।

ललितं बाल्यवेषं हि व्यतिलंध्यगुणोद्वलौ।। 107 ।।

रममानो सहोद्भूतैर्मि तत्रैस्तौ परिवेष्टितौ।

एकदा तु समायातौ तौ हि कृष्ण सभांतरे।। 108 ।।

विचित्र कुसुमैर्युक्ते भू वृंदैस्तुतपूरिते।

बलपांडु सुतादीनां समूहैस्तु विराजिते।। 109 ।।

कृष्णस्य चरणौ नत्वा तथा पूज्य जनस्य च।

सभामध्ये निविष्टोपि तथा पूज्य योग्यं विचक्षणौ।। 110 ।।

एकस्तुमदनः स्यांते द्वितीयोभानु सन्निधिं।

निविष्टौ यदा तत्र दृष्टौ सर्व सभाजनै।। 111 ।।

तावद्यूतमयीं पूर्वं क्रीडातत्र प्रवर्त्ततो।

बलस्यपांडवैः सार्द्धं पष्यमाने हरादपि।। 112 ।।

पांडवैः बलदेवेन तौ दृष्ट्वा वरवेषकौ।

प्रोक्तुं तु वचनं रम्यं कुमारो क्रीडतामिह।। 113 ।।

नत्वा ताभ्यां तदा प्रोक्त मावयो र्योग्यतानहि।

भवत्सु क्रीडमानेषु पूज्य पादेषु सांप्रतं।। 114 ।।

अत्याग्रह वषेनैवतौ च शम्बुसुभानुकौ।

कामभान्व्योर्मुखं बालौ पष्यमानौ वभूव तुः।। 115 ।।

ताभ्यां तत्र समुदिष्टौ तौतद्यूतस्य कर्मणि।

रतुंलग्नो यदूनां हि समक्षंतु हरेस्तदा।। 116 ।।

पुणास्तत्र कृतस्ताभ्यां प्रथमं स्वर्णकोटितः।

जितः शम्बुकुमारेण भानोष्चापि सहोदरः।। 117 ।।

तदातु मदने नोक्तमानीय रम्यतां पुनः।

द्यूतस्यनियतं मार्गो गृहीत्वा रम्यते पुनः।। 118 ।।

इत्युक्ते भानुनाद्रव्यं सत्यभामा समीपतेः।

कोटिप्रमानमानीयदैत्तं तत्रैव वेगतः।। 119 ।।

स्वर्णकोटि धनं भामागतं वीक्ष्यविलघीः।

साहंकार सभांते सा कुकुटं प्रेषयन्निजं।। 120 ।।

मदीयं कुकुटं शम्बोयदि येष्यति सांप्रतं।

कोटि द्वयं हीरणस्य तदा दास्यामि निष्चितं।। 121 ।।

शंबुः कामसुकं तत्र लोकयामास वेगतः।

कामो विद्यामयं रम्यं कुकुटं तु समानयन्।। 122 ।।

कुकुटं सत्यभामायाः कुकुटी विरहाकुलं।

सभायास्तु समक्षंहि तयोर्युद्धं तदाजनि।। 123 ।।

शम्बोस्य कुकुटेनैव सत्ययाः कुकुटोजितः।

कोटिद्वयं हिरणस्यजिग्ये शम्बुः संभातरे।। 124 ।।

नीत्वा कोटिद्वयं तच्चमदनस्यैव शासनान्।

दत्तं तु याचकेभ्यो हि सत्यभामाधनं तदा।। 125 ।।

बिनक्षा सत्यभामापि फलमेकं नियोजयत्।

सुगंधटि सुरूपं चापरेषामति दुर्ल्लभं।। 126 ।।

चतुः कोटि हिरणस्य दीयते तत्र मया ध्रुवं।

यद्येनं तु फलं शंबो जेतु शक्तो भविष्यति।। 127 ।।

जितं कामबलेनेदं फलं शंबुना सत्वरं।

चतुः कोटि धनं नीत्वा दत्तं तदपि तत्क्षिणं।। 128 ।।

प्रेषितं वस्त्र युग्मं च सत्यायाथ विलक्षया।

अष्ट कोटि हिरणस्य दास्याम्यस्य जये ध्रुवं।। 129 ।।

शम्बुर्विलोकयामास कामस्य मुख पंकजं।

कामेनापि तदादत्तं वस्त्र युग्मं मनोहरं।। 130 ।।

प्राप्तं हुताषने कुंडे स्वर्णतं तु विनिर्मितं।

जितं तेनात्र सत्याया व वस्त्रस्य युगलं परं।। 131 ।।

अष्ठ कोटि हिरणस्य दत्तायाः सत्यभामया।

तत्र शम्बुकुमारेण तच्चसर्वं समर्पितं।। 132 ।।

हारंतु प्रेषय सत्या कोटिष्चापि हि षोडषा।

सोपिहारेण तं हारं जिग्ये काम प्रषादत्तः।। 133 ।।

कुण्डले प्रेषयामास सत्यभामा सभांतरे।

द्वात्रिंष कोटि संख्येन धनेनापि समन्विते।। 134 ।।

जितेकाम प्रसादेन शम्बुनापि सुकुंडले।

तद्वचसं सर्व लोकेभ्यो ददौ शम्बुः स्मराज्ञया।। 135 ।।

कौस्तुभं सत्यभामापि सभांते प्रेषयस्तदा।

चतुः षष्ठिष्चकोद्योवैः धनस्यापिहि प्रेषितः।। 136 ।।

कामबुद्धि बलेनैव शंबुर्जिग्येथ कौस्तुभं।

तद्धनं सर्वलोकेभ्यो ददौ कीर्त्तिः समीहया।। 137 ।।

सर्वेषामपि लोकानां प्रयोभूषंबु संज्ञिकः।

कस्यचात्रोबलो हि दानस्याच्चै वल्लभः।। 138 ।।

अष्वंतु सुंदरं सत्या सभांते प्रेषयत् तदा।

द्विगुणोनधनेनैव सार्द्धंच सर्वसाक्षिकं।। 139 ।।

कामोविद्या बलेनैव हयं तत्र मनोहरं।

अनयामास वेगेन सर्वलक्षण लक्षितं।। 140 ।।

कामस्य तुरगेणापि जितः सत्यातुरंगमः।

ददौ सत्यंधनं सर्वं कुमारः शंबु संज्ञिकं।। 141 ।।

ततः सत्यावरं प्रेष्य समांतस्थं मनोभवं।

मायासैन्यं तु शंबोयं जयंतु चेतिसा व्रतीतु।। 142 ।।

इत्युक्ते शम्बुनामासौम्लानस्योथ बभूवच्।

शम्बुम्लान मुखं दृष्ट्वा मदनो विद्यकांबरं।। 143 ।।

ददौ षंबु कुमाराय बल दर्षन हेतवे।

पुरीबाह्ये गतौ तौ हि कामभानु सहोदरौ।। 144 ।।

सर्वलोकेस्तु संयुक्तौ कृतं माया मयं बलं।

शुभानौ प्रथमं सैन्यं दृष्ट्वा शंबुस्ततो करो।। 145 ।।

न क्वापि दृष्यतेचांते गजवाजिरथादिषु।

भटानां च विमानानां संज्ञातत्रण ज्ञायते।। 146 ।।

सुभानो शम्बु सैन्येहि निगग्नं दृष्यते नहि।

तयोर्युद्धमभूत् तत्र माया भूतक्षयावहं।। 147 ।।

गजागजैर्हयाष्चाष्चैरथारथैर्भटा भटैः।

महद्युद्धं ततः कृत्वा शंबु सैन्येन तद्बलं।। 148 ।।

सैन्यं शुभानु संभूतं जितं वेगात् न संषयः।

जितं शम्बुना लोकानां सर्वेष्यं पुरतस्तदा।। 149 ।।

हिरण्यकोद्यस्तु पूर्वोक्तात् द्विगुणास्तत्र समागताः।

ददौ सर्वाष्च लोकेभ्यः शम्बुः कामनिदेषतः।। 150 ।।

हारयित्वा धनं सर्वं सत्यभामा ततः स्थिता।

जाता तत्र पुरे रण्ये सर्वत्र शम्बुया कथा।। 151 ।।

दातारः सर्वलोकेभ्यो वल्लभः क्षितिमंडले।

सत्यभामा जगौ शम्बुः किं मद्यापि धनं तव।। 152 ।।

तदा सत्यास्थिता मौनं जेयाये च पुण्यतः।

ततः कामप्रसादेन शम्बुष्च श्रुसुभेतरां।। 153 ।।

ततोपि बलदेवेन युधिष्ठिर महीभुजाः।

भीमाद्यैः सर्व भूपालैः मिलित्वा बोधितोहरिः।। 154 ।।

अमानुषं कृतं कर्म शम्बुनात्र महद्विभो।

अतष्च्यैनं तु या कृत्वा प्रौढ़ कुरु जनार्दनः।। 155 ।।

त्वादृषीतु त्वयादेया शम्बुवे सुखभक्षिकः।

इत्याग्रहवषेनाथ विमृष्टं हरिणातदा।। 156 ।।

किमस्यै दीयते दानं योग्योयं सर्वकर्मसु।

ततोस्मै हरिणाराज्यं दत्तं तं मासैकं निजं।। 157 ।।

सिंहासने समागत्य ततोसौ द्वितीये दिने।

उपविष्ठः प्रमोदेन सर्व भूपे समन्वितः।। 158 ।।

प्रणुतः सर्वभूपैष्च बल काम पुरस्सरैः।

पांडवैरपरैष्चापि ततो भानुसुभानुभिः।। 159 ।।

शम्बुष्चैक दिनोद्भूतैर्मित्रैः सह तदा सुखं।

भुंजनहृषीक्संभूतं परेषामति दुर्ल्लभं।। 160 ।।

ततस्तु कुलनारीणां चक्रेषील विखंडनां।

बलात्कारेण मित्रेष्च गत्वागेहं तदा शठाः।। 161 ।।

नरान् सं प्रेष्य संप्रेष्य तासां रूपं शुभाशुभं।

रात्रौगत्वा ग्रहं प्राप्य चक्रे शील विखंडनां।। 162 ।।

अनेन विधिमालोकाः सर्वेपुरी निवासिनः।

अत्यंतं दुःखिता जाता दुःखं स्यात् किमतः परं।। 163 ।।

ततः शंभूय सर्वेपि लोकाराजगृहं गता।

नत्वा कृष्ण महीपाल विज्ञाप्तिते समुद्यताः।। 164 ।।

श्रृणु नाथ महीपाल शम्बुनापिहि यत्कृतं।

बलाच्चयं कुलस्त्रीणां शीलनाषं करोति वै।। 165 ।।

अतोवयं पुरी त्यक्त्वा स्यामोनवयसांप्रतं।

त्वया राज्ये तु संप्राप्ते समेष्यामो वयं विभो।। 166 ।।

ततस्तुहरिणा प्रोक्तं भो शृणुं तु महाजनः।

स्वल्पं कालं भवंतोहि तिष्ठंतु निजमंदिरे।। 167 ।।

महायत्नेन संयुक्ता तिष्ठंतु तावदेव हि।

यावत्प्राप्नोम्यहं राज्यं निजं वाक्या समर्पितं।। 168 ।।

सभायामपि संप्राप्ते ततो भ्रदं भविष्यति।

इत्युक्ते तु गतालोकाः स्थितास्तु निजमंदिरे।। 169 ।।

गते मासे समायातो वासुदेव सभांगणे।

निजं राज्यं तु सं प्राप्य शम्बु प्रति जगाविति।। 170 ।।

ममराज्ये त्वया पापस्थातव्यं न कदाचना त्वया।

तत्रैव गन्तव्यं नोभिधानं तु श्रूयते।। 171 ।।

इत्युक्त्वा कृष्ण भूपेन सत्पत्रितयबीटकं।

शंबुपि बीटकं नीत्वा निःससार सभांतरात्।। 172 ।।

तदातु मदनेनोक्तं शृणु तात वचो मम।

शंबोस्यागमनं नाथ वादाचिद्वा भविष्यति।। 173 ।।

तदा तु विष्णुना प्रोक्तं शृणुकामवचो मम।

यदातु सत्यभामाहि गजमारुह्य सन्मुखं।। 174 ।।

गत्वा महोत्सवेनात्र समानयति भक्तितः।

तदाषम्बुः समायातनानिथा सन्निधौ मम।। 175 ।।

प्रणम्यजननीं सोपि निःसृतोथगतोवनं।

सुन्दरं सत्यभामाया कामादेष वसानुगः।। 176 ।।

तत्र गत्वा तु संपूर्ण यौवनं स्त्री विभूषणं।

जग्राह तरुणी रुपं सर्वलक्षण लक्षितं।। 177 ।।

रूप सौभाग्य संयुक्तं नव यौवन भूषितं।

सर्वावयव संपूर्णं सर्वाभरण भूषितं। 178 ।।

एवं विधं निजंरूपं कृत्वाथ विजने वने।

स्थितः शम्बुकुमारासौतावत्सत्य समागतः।। 179 ।।

तत्रागत्य च तां दृष्ट्वा विस्मयं परमं गता।

तस्याः पार्ष्वं समागत्य जगाद वचनं च सा।। 180 ।।

ईदृषेविजनोरण्ये कथमे कामिनी सुते।

त्वं तु तिष्ठसि हे कन्ये देवकन्येव सांप्रतं।। 181 ।।

तदा जगाद सा बाला शृणुमात बचो मम।

अहं तु राजपुत्री वैगतामातुल मन्दिरं।। 182 ।।

तत्रैव यौवनं प्राप्तापितातत्र समागतः।

ममैवानयनार्थं हि मात विवाह हेतवे।। 183 ।।

मातुषिबिकारुढां सकृत्वाचाद्यनिषागमे।

समागत्य स्थिता चात्र सैन्येन महतायुतः।। 184 ।।

सर्वोपिषयितो लोकोरात्रौ निद्रा समाकुलः।

मातुले स्मृति मायाते गतानिद्राखिलामम।। 185 ।।

सिबिकायाः समुत्तीर्य भूमौ तु शयिता यदा।

तदापष्चिमरात्रोहि मम निद्रा समागता।। 186 ।।

ततोपि सह सैन्येन निषाया विरमेगतः।

अज्ञान वाच्चमांमुक्त्वा सुप्तांतु विजनेवने।। 187 ।।

न जानापि गत क्वापि केन मार्गेण वापुनः।

इति कारणतोमातस्थितारुढास्मि सांप्रतं। ।। 188 ।।

सुरूपां लक्षणोपेतां दृष्ट्वा तां सत्यभामिका।

जगादी वचनं रम्यमुपविष्य समीपतः।। 189 ।।

सुभानोर्मम पुत्रस्य चेत् परिणयसे नघे।

तदात्मं मंदिरे नीत्वा बहुभक्ति करोम्यहं।। 190 ।।

तदालज्जाकुलो भूत्वा कन्या प्रोचे वचो वरं।

अन्यत्रापि च मे ताते मां च दास्यति निष्चयात्।। 191 ।।

त्वं तु कृष्ण महीपष्य वर्त्तसेपहनारिका।

कोदोषोस्तव पुत्रस्य मम विवाह कर्मणि।। 192 ।।

तस्यवाक्ये समाकर्ण्य नीत्वा तां निजमंदिरं।

सूश्रुषां परमां चक्रे सत्यभामां दिने दिने।। 193 ।।

आसनैः शयनद्यैष्च भोजनैष्च विलेपनैः।

सुखेनास्थापिता सात्र गतं कालं न वेदति।। 194 ।।

व्यतीतेषु च तत्रैव केषुचित् च दिनष्वथ।

वसन्तसमयेः प्राप्य कामिनां कामवर्द्धकः।। 195 ।।

मदनोदीप्यनां जाता वसंतस्योत्सवेपरं।

पुष्पिताः सह कारासु किंषुकः कुसुमैष्चिता।। 196 ।।

ष्भं कृतः मधुपानां तु कोकिलायास्वनैस्तथाः।

वियोगिनी जनस्यात्रः दुःखं जातां निरंकुषः।। 197 ।।

जानेतत् तापषांत्यर्थं ववौ मलयमारुतः।

गताः लज्जातु लोकानां दीप्यमानेस्मरेनले।। 198 ।।

जृंभिमानेवधावेवं ततो भानु सहोदरः।

मित्रवृंदुवनेरंतु गतायानै समन्वितः।। 199 ।।

बंदिभिस्तूर्यमानोसौ वसंतस्यैव सांप्रतं।

विलोकितुं वने गत्वा यावत्तिष्ठति तत्र सः।। 200 ।।

तावत् नारीजनैस्तत्रोपविष्यां दोलके शुभे।

गीतमानं ततः कर्त्तुमारब्धं कामदीपकं।। 201 ।।

विकारैर्विविधैर्युक्तं तारस्वर मनोहरं।

नरनारीजनस्यापि मानिनामान भंजनं।। 202 ।।

नारीजन मुखोद्भूतं गीतं सर्वमनोहरं।

कामस्य विषखैर्विद्धः श्रुत्वा भानुसहोदरः।। 203 ।।

मुषितष्चलितोवापि मूर्च्छितो वावनांतरे।

कथितं सत्यभायागृहे नीत्वा विचेतनं।। 204 ।।

तं दृष्ट्वा सत्यभामापि ज्ञात्वा तत्कारणं परं।

पुत्रोविरह योग्योयं जाता वै सांप्रतं मम।। 205 ।।

चिंतयित्वा चिरं चित्ते निजमात्य जनान् जगौ।

भवंतो मायया गत्वा याचयित्वा तु कन्यका।। 206 ।।

समागच्छतु वेगेण यथा कोपि न विदंति।

इत्युक्त्वा प्रेषिता गत्वा समायातास्तुमंत्रिण।। 207 ।।

तदासर्वजनै ज्ञातं सत्यभामा सुतस्य च।

विवाहो मिलितो नूनं सुभानुपुण्यवाणिह।। 208 ।।

प्रछन्नं तु पुरो बाह्ये मुक्त्वा तां वरकन्यकां।

स्वयं गजसमारुह्य नेतुं काम भयादठता।। 209 ।।

निजंकेतु विवेष्यैनां महोत्सवपुरस्सर।

चतुः पथेन संभूय समानीकगृहं निजं।। 210 ।।

प्रतोली मध्यमानीय स्थापिता सा गृहांतरे।

लग्नस्य समयो जातः सुभानुस्तोरणं गतः।। 211 ।।

ततः परिजनैस्तस्याः कृतमंगलसत्क्रिया।

करग्रहण वेलायां रूपं व्याघ्रमयं कृतं।। 212 ।।

चपेटया समास्फाल्य व्याघ्र रूपेन तेन सः।

मूर्छया धरणीं नीतस्तदा भानु सहोदरः।। 213 ।।

सर्वेपरिजनास्त्रस्ता पतिताक्षिति मंडले।

त ते हसन् समायातः शम्बुः कृष्णः सभांतरे।। 214 ।।

कृष्णोथ विस्मयं प्राप ज्ञात्वा काम विचेष्टितं।

समास्वास्य प्रमोदेनं स्थापितास्तत्र तेन सः।। 215 ।।

शम्बस्य जननी जाता प्रमोदन प्रपूरिता।

विमदा सत्यभामा भूल्लज्जाम्लानमुखांबुजा।। 216 ।।

सत्याया निज तातस्य प्रेषित्वा वरमुत्तमं।

समाचारं तदा सर्वं कामस्यैव निवेदितं।। 217 ।।

प्रेषिताः खेटनाथेन कन्यकाः सतसुंदरीः।

महोत्सवेन ताः सर्वाः परिणीताः सुभानुना।। 218 ।।

शतवधूनां वर तां प्राप्य भानुसहोदरः।

मदंधधार चित्तेन रममानादिवानिषं।। 219 ।।

कामुषम्बुकुमाराय निजमातुल देहजां।

श्रुत्वा लोक मुखादिव्यां याचत्वानैव लब्धवान्।। 220 ।।

कामक्रोधेन संपूर्णो जातास्तं रुक्मिणं प्रति।

नीत्वा मातं गवेषोतौ शम्बुनामा मनोभवौ।। 221 ।।

वेगा कुंडनपुरं गत्वा प्रविष्टौतौ सभांतरे।

तदातुरुक्मण भूपस्य मनोज्ञवेष धारिणौ।। 222 ।।

वाद्यमानौ पिनाकी च गीतं गातुं समुद्यतौ।

रंजितः सकलोलोकंस्तत्र भूपेन संयुतः।। 223 ।।

तदा दानपरोजातः कुमारो रुपसंज्ञिकः।

रंजियित्वाखिलं लोकं चक्रतुस्तन्मयस्तदा।। 224 ।।

मदनेन निजां विद्यां प्रेषयित्वा नृपं गृहे।

निजविद्या प्रभावेन हृता कन्या क्षणात् ततः।

कन्यकां गगने नीत्वा कामषम्बौ सभांतरात्।

निर्गत्य गगने गत्वा प्रोचतुस्ताविदं वचः।। 226 ।।

शृणु वाक्यं मदीयं हि भो भीष्मनृपात्मज।

त्वदीयेयं तु दुहितां कृष्णजेनमयाहृता।। 227 ।।

त्वया तु सर्व सैन्येन संयुगे ममपार्ष्वतः।

मोचनीयां तु शक्तिष्चेन्नदत्ता याचितासत।। 228 ।।

इत्युक्त्वा सर्व सैन्येन निर्गतो भीष्मनंदनः।

अमात्यैस्तु ततो वृद्धै वारयित्वा पुनः पुनः।। 229 ।।

पुरमध्येथनीतोसौबोधित्वा च नृपात्मजः।

तां नीत्वा तु समायातौ पुरीद्वारवतीं च तौ।। 230 ।।

महोत्सवेन कामोपि कन्यकानां शतद्वयं ।

तयासार्द्धं तु शंबस्यचक्रे विवाहमुक्तमं।। 231 ।।

विवाह्य विधिना शम्बं महोत्सव पुरःस्सरं।

सखी तु कामदेवो भूत् सिद्धेकार्ये मुखं सदा।। 232 ।।

सर्वयादव लोकानां नित्यं चित्तहरस्मरः।

कामिनीजन संतोष जनय दर्षनादपि।। 233 ।।

मकरध्वजोति लोकानां सर्वेषां प्राणवल्लभः।

तस्मादपि रति नार्यां पुत्रो जातोति सुंदरः।। 234 ।।

अनिरुद्धाभिधो भूमौ प्रसिद्धोरूपसागरः।

यौवनंचक्रमात्प्राप सर्व विद्या विभूषितः।। 235 ।।

शंबस्यापि परं पुत्रा जातास्तुषसि संख्यकाः।

तैः पुत्रै निजपुत्रैष्चरे मे कामो यथा सुखं।। 236 ।।

सेव्यमानाः खगौघैष्च भूभुजैर्विवुधैस्तथा।

नदीनदतडागेषु वनेषु विविधेषु च।। 237 ।।

कैलासेनिषिधै चापिनीले चामर पर्वते।

सौमनस्य पांडुवनेनंदके कदलीवने।। 238 ।।

कामोरामादिभिः सार्द्धं सर्वलोक मनोहरः।

बुभुजे परमं सौख्यं चिंतितोपस्थितं सदा।। 239 ।।

कृतु षट्सु कामोपि यथा योग्यं यथा क्रमं।

तथा परिजनैर्युक्तष्चिंतितं सुखमन्वत्।। 240 ।।

हिसेथषिषिरेचापि वसंते ग्रीष्म संज्ञिके।

वर्षासरित्सुकृतुषु कामिनीजन चित्तमुट्।। 241 ।।

हिमागमे शुभस्थाने निर्वतेसीत वर्ज्जिते।

कृष्णागुरु सुकर्पूर धूर्पौधैद्धूपिते गृहे।। 242 ।।

कामिनीजनं संयुक्तो वुभुजे सुखमुत्तमं।

इतरेषां तु लोकानां दर्च्यंयन् पुण्यजं फलं।। 243 ।।

रुकाभृतैस्तु वस्त्रौघैरुष्ण भोजनं मैथुनैः।

सुगंधैर्वस्तुभिः सार्द्धं तथा वह्नेष्च सैवनैः।। 244 ।

रूपयौवन मत्ताभिः विद्धाभिः कामसायकैः।

एवं विधाभिर्नारीभिः सेव्यमानो दिवानिषं।। 245 ।।

षिषिरे बुभुजे सौख्यं नव यौवन संभवं।

पुण्योद्भवमिदं सौख्यं दर्षयन्निवप्राणिनां।। 246 ।।

वसंतेचापि संप्राप्ते मानिनीमानः भंजके।

सपुष्पोपायनेपेते मदनस्यैव सेवया।। 247 ।।

वकुलैः कमलैष्चापि चंपकाषोक किषुकैः।

भूषिते त्वपरैर्वृक्षै वने गत्वा मनोहरे।। 248 ।।

कामिनीजनं संघैष्च सुगंधे दीर्घिकाजले।

वनविहार कां लीलां बुभुजे प्रत्यहं स्मरः।। 249 ।।

चंदनैः कुंकुमौघैष्च सूक्ष्मवस्त्रैर्मनोहरैः।

शीतलैर्भोजनैः स्नानैस्तालवृंतैः सुगंधिभिः।। 250 ।।

भिन्नवालुकगेहेषु कामिनी जन संजुतः।

ग्रीष्मकालेपरां लीलां मदनो वुभुज वृषात्।। 251 ।।

युग्मं– वर्षाकृतौपरि प्राप्तौ निर्वाते बहुभूमिके ।

स्थितोसौमंदिरे रम्येकामिनी जन संभृते।। 252 ।।

गीतनादैष्च संयुक्ते नृत्यन्नारीकदंबके।

एवं सदा मनोजन्मा बुभुजे पुण्यजं फलं।। 253 ।।

ईषवः गालयो मुदढासरोभः क्वथितं पयः।

प्रदोषेचन्द्र ज्योत्स्नोघं सेव्यमानो मनोभव।। 254 ।।

शरत्सुसोच्च भवने कामिनीजन सेव्यतः।

दर्षयामास लोकानां फलं पुण्य समूद्भवं।। 255 ।।

युग्म– क्तुषुपद्यसु कामोपि यथेछं मानयन् सुखं।

विषदैः श्वेत छत्रौघैर्वीज्यमानस्तु चामरैः।। 256 ।।

विद्विि सुरवृंदैष्च खेटोघैर्भूमि नायकैः।

सेव्यते प्रत्यहं कामः स्नेहभार वषीकृतैः।। 257 ।।

जयजयेति शब्दौघेः स्तुति वाक्यैर्भटोदितैः।

तितादि सर्ववाद्यैष्च सेव्यते सौ मनोभवः।। 258 ।।

इतिमत्वा जना यूयं सकलं पुण्यजं फलं।

मुक्त्वा पापादिकं सर्वं कर्त्तव्योधर्म संग्रहः।। 259 ।।

बहु बंधु जनो नूनं बहु धनोति संपदः।

कामष्चोन्मत्तनारीभिः प्रत्यहं समुपोषितः।। 260 ।।

तन्नास्ति त्रिषुलोकेषु यत् च पुण्यैर्न्नवाप्यते।

विष्वसारं सुखं सारं प्राप्तं कामेन सांप्रतं।। 261 ।।

प्रत्यहं चिंतया खिन्नो निजैष्चोदर पूरणे।

क्षितिघृष्ट तनुर्नित्यं वस्त्र भोजन वर्ज्जितः।। 262 ।।

परगेहे कर्म करो रूपालावण्य वर्ज्जितः।

दीनोबंधुजनैहीनः पापेन जायते नरः।। 263 ।।

चातापेन संतप्तो बंधुभिस्तुविगर्हितः।

स्थाने स्थाने पराभूताधर्महीनो भवे नरः।। 264 ।।

इति नानाविधं सौख्यं पूर्व पुण्य समुद्भवं।

अनुवभूव कामोसौ यत्पंचेन्द्रिय गोचरं।। 265 ।।

यत्सुखं कामदेवेन तत्र भुक्त मनोमयं।

बृहस्पति समो भूमौ वक्तुकोत्र क्षमो भवेत्। 266 ।।

पुण्येनसौख्यमनघं सौजन्य सौम्यता सदा।

इति मत्वा जिनधर्मं कुर्वंतु सततंजनाः।। 267 ।।

इति श्री प्रद्युम्नचरिते सोमकीर्त्याचार्यविरचिते श्रीप्रद्युम्नफलवर्णनो नाम द्वादशः सर्गः।

त्रयोदशसर्गः

अथ कृष्ण महीसेन जरासंघ महीपतौ।

खगमानव संसेव्ये निहितेस्समरांगणे।। 01 ।।

कृते भारत संबंधे पांडवैस्तु समन्विते।

कौरवानां च घे जाते प्राप्ते चक्रे सुदर्षने।। 02 ।।

त्रिखंड सभवं राज्यं कंटकैः। परिवर्ज्जितं।

क्रियमानेथयद् वृत्तं तत्सर्वं क्रियतेधुना।। 03 ।।

अथैकदा सभां सर्वां पूरयित्वा स्थिते हरौ।

बलदेवेन संयुक्तां पूरितां मदनादिभिः।। 04 ।।

नेमिनाथः समायातो मित्रेरेकदिनोद्भवैः।

उत्थितास्तु भटाः सर्वे जिनभक्त्या समन्विता।। 05 ।।

युग्मं– समीपं कृष्ण भूपस्य नेमिनाथो जिनेष्वरः।

उपविष्टोति हर्षेण दत्ते सिंहासने वरे।। 06 ।।

तत्र भूपसमुहेषु निविष्टेषु यथा क्रमं।

निर्गता सुभटानां च वार्त्ताथबल वर्णनी।। 07 ।।

तत्र केचित् भटा प्रोचुः वसुदेवोति शक्तिमान्।

कष्चित् च पांडवानां हि बलं व्यावर्णयत् तदा।। 08 ।।

अपरेण तदा प्रोक्तं मदनोयं बलवान् ध्रवुं।

केनचित् शंमितः शंबो भानुस्त्वन्येन भू भृता।। 09 ।।

अन्योजगादतत्रैव कृष्णोवैबलवान् भुवि।

कृष्णतुल्योधरापीठेन भूतो न भविष्यति।। 10 ।।

अन्ये हि बलदेवं तु संषयमाश्रुसंसदि।

यस्यचेत्तेतुयः शूरः शंसितस्तत्र तेनसः।। 11 ।।

बलदेवोपि तत्रो चेधुनयन्निज मस्तकं।

रे रे मूढा वृथा किं हि शंस्यंते त्वपरे भटाः।। 12 ।।

यत्र श्रीनेमिनाथोयं निविष्टस्तु सभांतरे।।

तत्रान्वेषा भटानां हि प्रषंसा नैव युज्यते।। 13 ।।

मेरुत्सर्षपयोर्यद्वदंतरं वर्त्तते तरां।

तद्वत्सर्व भटादीनां नेमिनाथस्य वर्त्तते।। 14 ।।

नेमिनाथ समो भूमौ शूरोवीरो भटोत्तमः।

नापरं वर्त्तते लोकेकोहं कृष्णोपरेतुके।। 15 ।।

यदासौ बलदेवेन शंसितस्तु पुनः पुनः।

अधो भागं तदासोपि वीक्ष्यमाया सलज्जया।। 16 ।।

तदा नारायणः प्रोचे नेमिनाथं कृतः स्मितं।

मल्लयुद्धं करिष्याव आवांचात् च सभातरे।। 17 ।।

बंधयित्वा दृढं कंछ प्रोत्थितोसौ जनार्दनः।

तदानेमि कुमारोचेनेदं साधु जनोचितं।। 18 ।।

पादपीठात् च पादंमेथदिवाकर्षितुं क्षमः

तदाहं सर्वयुद्धेषु जितो कृष्णेन सांप्रतं।। 19 ।।

इति तस्य वचः श्रुत्वा जिनेन्द्रस्य जनार्दनः।

दृढंपरिकरं बध्वा प्रोत्थितस्तं भटोत्तमं।। 20 ।।

वल्गितैष्चापि वेगेनपरं क्रोधेन पूरितः।

वल्गित्वासौ चिरंकालं विष्णो भूज्जनार्दनः।। 21 ।।

स्वेदेन व्याप्ततनुके स्वास पूरित गात्रके।

स्थिते जनार्दने नेमिर्जगाद वचनं शुभं।। 22 ।।

करंचाल वेगेन स्व शक्ति मधुसूदन।

तदाहं कृष्ण युद्धेषु सकलेषु त्वया जितः।। 23 ।।

पुनर्ववल्गुवर्बलवान् क्रोधेनासौ जनार्दनः।

चालितुं नैव शक्तो भूह्याकुलोभूत् तदा भृषं।। 24 ।।

विखिन्नं भ्रातरं दृष्ट्वा जगाद जिननायकः।

वामहस्त कनिष्ठां मे बालयत्वं जनार्दन।। 25 ।।

इत्युक्तेपि पुनः क्रोधात् तत्रापि वल्गितोहरिः।

द्वाभ्यामपि सहस्ताभ्यां निजषक्ति समस्तया।। 26 ।।

तदासौनेमिनाथेन चोर्द्ध्वं कृत्वा निजंकरं।

हिंदोलित सभामध्ये वासुदेवोनोदनः।। 27 ।।

तदा क्रोधेन खिन्नोसौ जगाद वचनं हरि।

मम भ्रातृर्बलं लोका यूयं पष्यंतुचोत्कटं।। 28 ।।

हसित्वा मायया कृष्णो जगाम निजमंदिरं।

जिनेन्द्रोपि निजं स्थानं जगाम स्वजनैः सह।। 29 ।।

विखिन्नोसौ बलोनामा चिंतयामास मानसे।

हरिष्यति निजं राज्यं बलवान् जिननायकः।। 30 ।।

नैमित्तिकं तु चैकांते समाहूयाति वेगतः।

पृष्ठोसौवलकृष्णाभ्यां वृत्तं सर्वं जिनोद्भवं।। 31 ।।

तदा तेनापि तत्रोक्तं मा कृथास्त्वं भयं हरे।

पालयिष्यति नो राज्यं प्रापयिष्यति संषयं।। 32 ।।

दृष्ट्वा जंव विनाषं च त्यक्त्वा राज्यं परिच्छेदं।

कुर्ज्जयंतं गिरिं प्राप्य निर्वाणं यास्यति ध्रुवं।। 33 ।।

तावत् तत्र समायातो वसंत समयोवरः।

मा कंद मंजरी युक्ता कोकिलाप सूचिता।। 24 ।।

वसंसानंक शब्देन बोधयित्वाखिलं जिनं।।

कामिनीभि युतो विष्णुर्वनंरेतुंत्सुकः।। 35 ।।

कामिनीनां तु संकेतं दत्वा नेमिजिनं प्रति।

गजारुढो जनैर्युक्तो जगामासौ वने हरिः।। 36 ।।

रुक्मिणी सत्यभामाद्याः कृष्ण भूपस्ययोषितः।

नेमिनाथ समीपंता गत्वा प्रोचुर्वचो वरं।। 37 ।।

उत्तिष्ठत्वं जिनाधीष वसंत समयेवने।

रंतुं तु गम्यते नूनं तव भ्रातागतः पुराः।। 38 ।।

इत्युक्तेथ जगौ नेमिनागतुं युज्यते मम।

तदा ताभिर्वलान्नीतो वनमध्ये जिनेष्वरः।। 39 ।।

गोप्योपि विष्णुना सार्द्धं कौतु कौतुकेरमिताष्चिरं।

तासां षिक्षायनंदत्वा यातो विष्णुवनांतरे।। 40 ।।

गोप्यौघनेमिनासार्द्धं क्रीडां चक्रु मनोहरां।

कुंकुमैष्चंदनोघैष्च जलयंत्रैर्विषेषतः।। 41 ।।

पुष्पादान मिषेनैव वृक्षेभ्योपि वरांगणा।

कुचाभ्यां नेमिनाथं ताज्जध्तु प्रेम भरालसा।। 42 ।।

लज्जया रहितैर्हास्यैर्हसित्वादेवरं प्रति।

हावभावादिभिः क्रीडांचक्रुर्नेमिजेनेनता।। 43 ।।

जलभिन्नं निजं वस्त्रं मुक्त्वा जांबुवतीं जिनः।

जगाद वचनं वाग्मी निर्गत्य दीर्घिका जलात्।। 44 ।।

ममवस्त्रमिदं देवि कुरुत्वं जलवर्जितं।

तेनवाक्येन रुष्टा सा जगौ च युतीजिनं।। 45 ।।

ईदृषं प्रेषणं मूढ मम दातुं न युज्यते।

अहं तु कृष्ण भूपस्य जाया माया विवर्जिता।। 46 ।।

ईदृषं प्रेषनंदातुं यदिच्छा वर्त्तते तव।

याचयित्वा वरां कन्यां विवाहं कुरुषेन किं।। 47 ।।

ममनाथोस्ति कृष्णोवैयस्तु विष्वस्य नायकः।

चक्रं सुदर्षनं नामकरणे भ्रमितुं क्षमः।। 48 ।।

करोमि मंडलाकारं सारंगा सख्यं वधूत्तमं।

नागषय्यां समारुह्य पांचजन्यं तु पूरितं।। 49 ।।

सोपिममेदृषं कर्म न ददाति कदाचन।

तेन वाक्ये रुष्टो भूत् नेमिनाथो जिनेष्वरः।। 50 ।।

रुक्मिण्यावारितासाथ मा ब्रुहि चे दृषं खले।

नेमिस्तु वलवान्नूनं त्रैलोक्ये स चराचरे।। 51 ।।

इत्युक्त्वा वस्त्रमादाय कृतं जल विवर्ज्जितं।

तस्यागर्वं जिनो ज्ञात्वा जगामायुधषालिकां।। 52 ।।

द्वारमुद्घाट्य कोपेन नीत्वा चक्रं धनुस्तथा।

शयित्वा नागषय्यां स शंखं घ्राणेन पूरयन्।। 53 ।।

चापं तं मंडली कृत्य मर्दयन् पन्नगीस्तदा।

भ्रामयत् चक्र रत्नं तं शंखं घ्राणेनपूरयन्।। 54 ।।

शंख शब्दं समाकर्ण्य हरिस्तदा समागतः।

दृष्ट्वा तथा विधं नेमिं जगाद जिननायकं।। 55 ।।

किमिदं कामिनी वाक्यात् त्वयारब्धं जिनेष्वर।

उत्तिष्ठ मुंच कोपं त्वमित्युक्तोत्थापितेजिनः।। 56 ।।

सन्तोष्य विष्णुना नेमिं नीत्वा तु निज मंदिरं।

भोजयित्वादरेणैनं स्थिताष्चिंताकुलो हरिः।। 57 ।।

मात त्वं नेमिनाथस्य यौवनेनान्वितस्यहि।

न करोषि विवाहं हितत्किं तु कारणं परं।। 58 ।।

षिवादेवी तदो प्रोचे श्रृणु वाक्यं जनार्दनः।

अस्माकं वंषमध्ये त्वं प्रधानोसि विषेषतः।। 59 ।।

तस्मात् किं पृछातेस्माकं कर्त्तव्यमखिलं त्वया।

षिवाया वचनं चैतत् श्रुत्वा यातोगृहं निजं।। 60 ।।

आगत्य बलदेवेन समंत्र्य मंत्र कारणं।

उग्रसेन गृहं गत्वा ययाचे कन्यकां वरां।। 61 ।।

कृत्वात्र कपटं कृष्णः पुनर्गेहं समागतैः।

चक्रेनेमि जिनेन्द्रस्य विवाहस्योत्सवं हरिः।। 62 ।।

आकारितास्ततस्तेन सर्वेयादव भोजगाः।

शस्त्राकास्तु समायाता द्वार वत्यांनृपौकसि।। 63 ।।

स्थाने स्थाने हि नृत्यंति यादवानां तु योषितः।। 64 ।।

तोरणानि विचित्राणि गेहे गेहे च मंडपा।

तं गेहं नैव पष्यामि यत्र सोत्सवता नहि।। 65 ।।

मर्दनैष्चीकसैष्चापि स्थानात्वापत्र जिनेष्वरः।

श्रृंगारं विविधं निन्ये नारीभिः कृत मंगलः।। 66 ।।

उग्रसेन गृहेतावद्वर्त्तते सोत्सवो महत्।

आहूतास्तेन स्वजनाः समायाता स्त्वनेकषः।। 67 ।।

नेमिनाथो वरो यत्र कन्या राजीमती तथा।

उत्सवस्यहि का तत्र वर्णना क्रियते परा।। 68 ।।

स्वकीयष्चोग्रसेनेन विभूष्य भूषनैः शुभैः।

शुयानैः प्रेषितास्तत्र वरानेतुं नरापराः।। 69 ।।

समुद्र विजयस्यैते गेहे सोत्सवपूर्वकं।

समायाताः परं हर्षान् मानिता यादवैस्तदा।। 70 ।।

प्राणितायादुनारीभि गान भोजनकैस्तथा।

निर्गता सा ततो जानियानैस्तु विविधैर्युता।। 71 ।।

षिवा च देवकी देवी रोहिणी सत्यभामिका ।

रुक्मिण्यादि च दिव्योघाष्चक्रुस्तैव मंगलं।। 72 ।।

क्रियमाने तु मांगल्ये षिवाया उपरिछदं।

दीपके तु तदा लग्नं चारितं वा महोत्सवं।। 73 ।।

रथारुढो तदानेमौमाजर्जारी मार्ग खंडनं।

कृत्वा तु चलिता चाग्रे ज्ञात्वापि चलितो जिनः।। 74 ।।

वाजित्राणां तु निर्घोषै बंदिनां जययारवैः।

गानैः सेवासिनीनां च जातः कोलाहलो महान्।। 75 ।।

समुद्र विजयो राजा वसुदेवो बलस्तथा।

अधोक्षजो नृपस्तत्र कामभानु पुरस्सरा।। 76 ।।

राजोनोबहवस्तत्र चलिता श्री जिनेनहि।

जिनोथ तोरणं प्रापयछन्दानं हि याचकान्।। 77 ।।

गवाक्षारुढया सोपिराजीमत्या निरीक्षितः।

सखीभिः कथितोद्वेषष्छत्र चामर बीज्यता।। 78 ।।

वामदक्षिण भागेहि पषुभिः पूरिताष्चयाः।

तेषां शब्दं तवानेमिः सुश्राव दिनतायुतं।। 79 ।।

उग्रसेन गृहाद्रामास्तावस्तत्र समागताः।

नीत्वा मांगल्य कुंभाष्च कर्त्तुं कर्म यथोचितं।। 80 ।।

जीवशब्दं समाकर्ण्य नेमिनाथो दयापरः।

इतस्ततो विलोक्या शुभगावेवं तु सारथिं।। 81 ।।

किमर्थं जीवनि करोमेलितोयं महीभुजा।

सारथे त्वं वेगेन निवेदय द्रुतं मम।। 82 ।।

ततः सारथिना प्रोक्तं श्रृणुनाथ वचो मम।

त्वदथें त्वद्ववाहर्थं मेलिता जीव राषयः।। 83 ।।

अद्यरात्रौनिपात्यै तान् प्रातस्ते गौरवं प्रति।

भुक्त्यर्थं यादवानां हि कृष्णोदेषेन मेलिता।। 84 ।।

तस्य वाक्य समाकर्ण्य नेमिनाथस्तदा हृदि।

चिन्तयामास पापस्य कारणं गृह बन्धनं।। 85 ।।

अहो दुष्टाषया लोका जीवानां घातकास्तुये।

जीव घातेन यास्यंति नरके घोर वेदने।। 86 ।।

हन्यंते तु कथं जीवा अपराध विवर्ज्जिताः।।

कालक्षेपंतु कुर्वन्ति वनस्थास्तृणभक्षिणः।। 87 ।।

गृÈंति कंटक भयाद्भटाष्चरण त्राणिकां।

ते तु बाणैः कथं जीवाघ्नंति पापा हि निष्ठुराः।। 88 ।।

विवाहस्योत्सवे ज्ञातं फलं संसार संभवं।

धिग् संसारमसारं पापरंभकरं परां।। 89 ।।

इति ज्ञात्वा स्वचित्तेनचार्ययित्वा रथं जिनः।

मोचयामास जीवौधान वाटकेभ्योपि तत्कृणात्।। 90 ।।

चलिते नेमिनाथे हि जाता लोकाः समाकुलाः।

द्वारिकायां समायातो देवैर्लौकांतिकैयुत।। 91 ।।

कृष्णेन चारितो नेमि तिष्ठ तिष्ठ महाबला।

विवाहं कुरु हे भ्रात कलंकं में निवारय।। 92 ।।

मातातातादिभिः सर्घैबार्यमानः पुनः पुनः।

संबोध्य सकलं लोकं निविष्टोसौ तु विष्टरे।। 93 ।।

अभिषेकः समागत्य सुरेन्द्रैष्चलिता षनै।

कृतो महोत्सवै नैव जिनभक्त्या प्रमोदितैः। 94 ।।

अनुलेप्य सुगंधैस्तु श्रीखंडैर्मलयोद्भवैः।

कल्प वृक्षोद्भवैः पुष्पैः पारिजातैस्तु पूजितः।। 95 ।।

षोडषा भरणैपितः स्तुत स्तुतिः शतैः सुरैः।

स्वयं गत्वा समारुढो षिविकां श्री जिनेष्वरः।। 96 ।।

पदानि सप्त भूपालै नीता सा षिविकोत्तमा ततः।

सुरवनैः नीता षिविका गगनांगणे।। 97 ।।

सर्वाद्वारावतीलोकः खेचराः भूवरास्तथा।

लग्नास्ते पृष्ठितो गंतुं श्रीमद्रैवतकं गिरिं।। 98 ।।

ततो राजीमती लग्ना पृष्टतः श्री जिनेष्वरं।

कुर्वाणा विविधा क्रंदं विलपंती पदे पदे।। 99 ।।

जिनोरैवतकं गत्वा विलोक्य सर्वतो गिरिं।

सहस्राम्रवने गत्वा कृतवान् सहसं जिनः।। 100 ।।

पंचमुष्ठिभिरुत्पाद्य केषांष्च श्रीजिनोत्तमः।

नमः सिद्धेभ्य इत्युक्त्वा त्यक्त्वा चाभरणादिकं।। 101 ।।

जिनेन्द्रोथ मुनीन्द्रो भूत् स्तूयमानः सुरासुरैः।

ध्यानं धृत्वा स्थितो योगी सहस्रराजभिर्युतः।। 102 ।।

इन्द्रोपि जिन केषांष्च घृतवान् क्षीर सागरे।

कल्याणं तृतीयं कृत्वा सुरेद्वाः स्वालयं ययुः।। 103 ।।

तृतीय दिवसे देवो द्वारिकायां समागतः।

ब्रह्मदत्त गृहे चक्रे पारणां परमेष्वरः।। 104 ।।

पुनः समागतो योगी गिरिं रैवतकाभिधं।

तस्थां ध्यानं परं मौनी कर्तुं घातिक्षयं निजं।। 105 ।।

चलित्वा तु गतं गेहं दुःखक्रान्ता नृपात्मजा।

ध्यायंती मनसा नेमिं संयममेकृत निष्चया।। 106 ।।

पित्त्रा संबोधितात्यंतं माकृथा दुःखमुत्कटं।

आनयाम्यपरं भूपं दास्यामि तव सांप्रतं।। 107 ।।

राजीमती ततः प्राह शृणु तात वचो मम।।

नेमिविहाय पुरुषास्त्वन्ये तु त्वादृषा मम।। 108 ।।

इत्युक्त्वा तु पितातस्थौदुःखं कृत्वा गृहे निजे।

नेमिनाथं हि ध्यायंती स्थिता राजीमती गृहे।। 109 ।।

अथध्याने स्थितो योगी ध्यायन्नात्मानमात्मनि।

आरुढा क्षपकश्रेण्यां चक्रेघाति क्षयं जिनः।। 110 ।।

उत्पन्नं केवल ज्ञानं लोकालोक प्रकाषकं।

निजध्यान प्रभावेन षट्पंचासमके दिने।। 111 ।।

आसनानि सुरेन्द्राणिं कंपितानि तदा ध्रुवं।

यदाज्ञातं सुरैर्नेमिः केवलर्ज्ञानमुद्भतं।। 112 ।।

विमानेषु समारुह्यानेषु विविधेषु च।

दुदुभीनां निनादैष्च पूरयंतो दिषोखिलाः।। 113 ।।

पुष्पवृष्टिं च मुंचंतो देवीनां नर्त्तनैर्युताः।

सुरेन्द्रास्तु समायाता गिरिं रेवतकाभिधं।। 114 ।।

इन्द्रादेषा कृतं तावद्धनदेन मनोहरं।

सरणं समवाद्यं च सर्वलक्षण लक्षितं।। 115 ।।

प्रथमं पीठिका बद्धा विस्तीर्ण वज्र भूमिका।

पंचसहस्र दंडास्तु गत्वा भूमेर्मनोहराः।। 116 ।।

सौपान तु सहस्रैष्च विंषातिष्च सहस्रकः।

प्राकारत्रितयं जातं रत्न हेमादि रूपकं।। 117 ।।

मानस्तम्भास्तु चत्वारि खातिका पुष्पवाटिकाः।

नाट्यषाला वनानीह वेदिका भवनानि च।। 118 ।।

राजंते जल पूर्णानि सरांस्यमलवारिभिः।

पीठत्रयेन संयुक्तं स्थापितं विष्टरं शुभं।। 119 ।।

अष्ठभिः प्रातिहार्येस्तु राजमानंसमं ततः।

कोष्ठैर्द्वादषभिर्युक्तं निर्ग्रन्थादि प्रपूरितैः।। 120 ।।

स्तूपैष्च विविधैर्युक्तं रत्ननद्धधरातलं।

तस्य मध्ये निविष्टोसौ जिनेद्रोविष्टरे शुभे।। 121 ।।

चतुः षष्ठि प्रमाणैस्तु वीज्यमानोहिचामरैः।

छत्र त्रयेन संयुक्तो वंदितौ सौसुराः सुरैः।। 122 ।।

ब्रह्मदत्तादयो जाता गणाष्चैकादषस्तथा।

इन्द्रादेषेन संजाता शरणं समवादिकं।। 123 ।।

ततोद्वारावती लोकः सकलोपि समागताः।

केवल ज्ञानमुत्पन्नं श्रुत्वा श्री जिननायके।। 124 ।।

कृष्णाद्या यादवा सर्वे समुद्र विजयादयः।

षिवा च देवकीं देवीं रुक्मिणी भामिकादयः।। 125 ।।

उग्रसेनादयस्त्वन्ये सर्वे तत्र समागताः।

दृष्ट्वा तु विस्मयं प्राप्ताः शरणं समवादिकं।। 126 ।।

त्रिः परित्यजिनं तत्र स्तुत्वा नत्वाति भावतः।

पूजयित्वा विधानेन गुरु भक्ति पुरस्सरं।। 127 ।।

यथा स्थाने निविष्टास्ते कोष्ठेतु विविधेषु च।

नारीणां पंच सहस्त्रै राजीमती समागताः।। 128 ।।

नेमिनाथ जिनं नत्वा दीक्षामंगीकृता तया।

आर्यिकाणां तु सर्वासां जातासातुमहत्तरा।। 129 ।।

श्रोतु कामेषु लोकेषु धर्मं श्री जिननायकात्।

जगाद जिननाथं सो वर दत्तो गणाग्रणी।। 130 ।।

प्रकाषय विभोधर्मं जलदो भव्य चातकान्।

पीडितास्तु पुरालोका नूनं मिथ्यात्व तृष्णया।। 131 ।।

गम्भीरां मधुरां वाणीं सप्तभंरी समन्वितां।

जगाद जलदाकारो जिनेन्द्रो भव्य नायकात्।। 132 ।।

चतुर्नियोगसारां तु द्वादषागमयावरं।

रत्नत्रयेन संयुक्तां सप्ततत्व प्रमानिकां।। 133 ।।

द्विविधं तु जिनः प्राह धर्मं संसार नाषनं

परं तपस्विनामाद्यं ततोन्यद्गृहमेधिनां ।। 134 ।।

त्रयदंष विधं तत्र चारित्रं व्योमवाससां

महाव्रतानि पंचैव पंचैव समितीं स्तथा।। 135 ।।

तथा च गुप्तयस्तिस्रो भाषिता श्री जिनेष्वरैः।

अष्टाविंषति संख्याता नूनं मूल गुणाः स्मृताः ।। 136 ।।

तथोत्तर गुणास्तत्वन्ये संतितास्तत्र सहस्रसः।

प्रत्यहं पालनीयानि तथैवावष्यकानि षट्।। 137 ।।

एवं विधं जिनेद्रोक्तं चारित्रं निर्मलं मुनिः।

पालयित्वा तु प्राप्नोति मोक्षसौक्षं हि शाष्वतं।। 138 ।।

पंचैवाणुव्रतानिस्यु स्त्रिविधं च गुणव्रतं।

षिक्षाव्रतानि चत्वारि श्रावकानां व्रतान्यमी।। 139 ।।

सम्यक्त्वा ज्ञान चारित्रं त्रितयं रत्नं परं तु।

पालनीयं सदा भव्यैः श्रावकाचारमुत्तमं।। 140 ।।

मद्य मांस मधुत्याग पंचोदुम्बर वर्ज्जनं।

अष्ठौ मूल गुणा प्रोक्ताः गृहस्थानं मुनीष्वरैः।। 141 ।।

अज्ञात भाजने भोज्यं कुपुष्प कुफलानि च।

हदृचूर्णं सदाहेयम पक्व लवनादिकं।। 142 ।।

नवनीतं स सदा त्याज्यं कंदमूलादिकं तथा।

पुष्पितं बिदलं चैव धान्यमनंत कायकं।। 143 ।।

आरणालं च तक्रंच शाकपाकादिकं तथा।

दिनद्वयगतं त्याज्यं सर्वातीचारकारकं।। 144 ।।

चर्मभांड स्थितं यच्च घृतं तैलं जलं तथा।

मांसदोषकरं तत् नग्राह्यं श्राद्धै विवेकिभिः।। 145 ।।

पानीयं तत्क्षणेगाल्यं प्राश्रुकं दोषवर्ज्जितं।

तथाज्ञात फलं त्याज्यं ग्राह्यं श्रीजिनभाषितं।। 146 ।।

मिथ्यात्वं दूरतः त्याज्यं सप्तैव व्यसनानि च।

रात्रौ तु भोजनं हेयं तथा वासर मैथुनं।। 147 ।।

कुदेवांष्च कुषास्त्राणि कुगुरुन् कुधर्मं तथा।

मनसापिन चिंतव्यमेतत् संसार वर्द्धनं।

देवपूजादि षट्कर्म कर्त्तव्यं प्रत्यहं बुधैः।

दुर्लभं त्रिषु लोकेषु धर्मं श्रीजिन भाषितं।। 149 ।।

इति श्रुत्वा जिनेन्द्रोक्तं धर्मं सर्व नरामरा।

सन्तोष परमं प्राप्यनमताः श्रीजिनेष्वरं।। 150 ।।

ततो वाजित्र निर्घोषं गीतानां ध्वनयस्तथा।

इतिकृत्वा तु भव्यैधाः केचित्दीक्षां श्रितास्तदा।। 151 ।।

केचित् जिनेन्द्र पूजायाः केचिन्मौनादिकं तथा।

प्राप्ताः केचित् च सम्यक्त्वं परेचाणुव्रतानि च।। 152 ।।

निजभाग्यानुसारेण भव्य जीवैरनेकषः।

नियमास्तु तत्र नीता जिनवाक्य प्रमोदितैः।। 153 ।।

संबोध्य परमं प्राप्य नृसुरासुरकोटयः।

नत्वा जिनेष्वरं भक्त्या यथा स्थानं यथा यथं।। 154 ।।

ततोथ यादवाः सर्वे जिनं नत्वा विषेषतः।

निजां द्वारावतीं याता जिनधर्मरता ध्रवुं।। 155 ।।

जिनेष्वरस्य वार्त्तान्ते कुर्वेतो भव्य राषयः।

प्रत्यहं तु समागत्य नमंतिस्म जिनेष्वरं।। 156 ।।

विहारार्थं जिनेन्द्रोपि श्रीमद्रैवतकाचर्लत्।

सुरासुरैर्गुणैर्युक्त उत्तराषातिवेगतः।। 157 ।।

मार्गे वायुकुमाराष्च तृण कीटकनाषनं।

अग्रतस्तु प्रकुर्वंति जिन भक्त्या प्रमोदिता।। 158 ।।

ततोमेघ कुमारास्तु सगन्धोदक वर्षणं।

कुर्घंति जिनभक्त्यावै जिनेष्वर पुरस्तदा।। 159 ।।

यत्र यत्र पदानीह धत्तेचासौ जिनेष्वरः।

कल्पंनि तत्र पद्मानि सुरा स्वर्णमयानि च।। 160 ।।

चतुः शतानि गव्यूति शुभिक्षं सर्वतो ध्रुवं।

न हिंसा न च शीतं तु नातापोति पीडनं।। 161 ।।

न क्षुद्रोपद्रवं देषे यत्र याति जिनेष्वरः।

अग्रतस्तु सुराः सर्वे कुर्वंतीह जयं जयं।। 162 ।।

शाल्यादिनां तु शस्यानां समूहैर्भातिमेदिनी।

दिषोनिर्मलता नूनं सुगन्ध पृष्टितो मरुत्।। 163 ।।

सर्वेषां चापि वेगेन सुराः शक्राज्ञयाखिलाः।

आह्वानं यंति लोकानां वंदनाय जिनेष्वरं।। 164 ।।

धर्मचक्रं हि पुरतो याति पापक्षयंतिकः।

मिथ्यात्वोन्मूलने दक्षं जिनधर्म प्रभावकं।। 165 ।।

अनेन विधिना देवो विजहाराखिलां भुवं।

यत्र यत्र जिनोयाति शुभं तत्र समादिषेत्।। 166 ।।

महाराष्ट्रं च तैलंगं च कर्णाटकं द्राविड़ तथा।

अंग बंग कलिंगं च सूरसेनं च मागधं।। 167 ।।

कन्नोजं कुंकण चापि सौराष्ट्रमुत्तरं तथा

मालवं गुर्ज्जर चैव पांचालं तु महेष्वरं।। 168 ।।

संबोध्य नेमिनाथोपि देषात् नाना विधांस्तथा।

पुरंभद्दिलि संज्ञं तु समायातो जिनेष्वरः।। 169 ।।

अलकाया गृहे तत्र वसुदेव शरीरजाः।

वर्त्तन्ते त्रीणि युग्मानि मुक्तानि च सुरैः पुरा।। 170 ।।

भूपालोतु समायातो तेपि तत्र समागतः।

प्रत्येकं प्रणीतास्तेव द्वात्रिंषत् च वरांगणाः।। 171 ।।

जिनवाक्यं समाकर्ण्य तेहि षडपि भ्रातरः।

वैराग्यं परमं प्राप्यनिः पुजैनेष्वर व्रतं।। 172 ।।

पठने पाठने चापिध्याने योगे तथै क्व।

कुर्वन्ति भ्रातरः सार्द्धं पारणं प्रोषधं तथा।। 173 ।।

एवं सम्बोध्य देवोसौ रैवतकं पुरागतः।

कृतं तथैव विबुधैः शरणं समवादिकं।। 174 ।।

श्रुत्वाच्च द्वारिका लोका वेगात् तत्र समागताः।

कृष्णाद्या यादवास्तत्र सत्य भामादि योषितः।। 175 ।।

प्रणम्यं च जिनं नत्वा पूजयित्वाति भक्तितः।

निविष्टास्ते तथा स्थानं निजे कोष्ठे सुरासुराः।। 176 ।।

धर्मं जिनेष्वरः प्रोचे तृषितान् भव्य चातकान्।

तृष्टास्ते त्वखिला लोका धर्मं श्रुत्वा जिनोदिनां।। 177 ।।

अवसरं समासाद्य देवकी तु जिनं जगौ।

विनयं परमं कृत्वा विस्मयं च समाश्रिता।। 178 ।।

भगवान्मम गृहेचाद्यमुनि युग्मं समागतं।

आहारं विधिनानीतं तेनैव च पुनः पुनः।। 179 ।।

एवं वार त्रयं नाथ समायातं तदेवहि।

मयातु पुत्रमोहेन भक्त्याहारं समर्पितं।। 180 ।।

जिनेन्द्रषासने जाताय तयोये दिगम्बराः।

एकस्मिन् दिनमध्येते भुंजंते किं पुनः पुनः।। 181 ।।

इति पृष्टो जिनोवोचत् शृणुमात वचो मम।

आषांबरधराणां हि भोजनं न पुनः पुनः।। 182 ।।

युग्म त्रयं तु तेषां हि विद्धिषडपि भ्रातरः।

त्वदीया देहजाष्चामीजन्मकालेह्वताः सुरैः।। 183 ।।

देवकी जिन वाक्यं तु समाकर्ण्य मनोहरं।

सकुटम्बं समुत्थाय प्रणनाम मुनीष्वरान्।। 184 ।।

मुनयो भग्नसंदेहा जाता श्री जिनवाक्यतः।

परस्परं निजां वार्त्तां चक्रुर्माता तु देहजान्।। 185 ।।

सर्वे हि यादवास्तुष्टा दृष्ट्वा कृष्ण सहोदराः।

उत्सवस्तु महान् जातः सर्वेषां तत्र संगमे।। 186 ।।

सत्यभामादि वेवीभिः ततः पृष्टो जिनेष्वरः।

अष्ठाभिर्निज भवान् जिनेनापि निवेदितान्।। 187 ।।

संतुष्टा यादवाष्चैवं पुनर्जाता गृहं निजं।

पुनर्नेमिजिनेन्द्रोपि विहाराभि मुखो ययौ।। 188 ।।

संबोधयति देषांष्च विविधान् जिननायकः।

दीक्षां ददाति जैनेन्द्री भव्यानां मोक्ष हेतवे।। 189 ।।

ये ये भव्य जना जिनेन्द्र चरितं श्रृण्वंति चित्तादरात्।

विवाहादि महोत्सवैः परियुतं वैराग्यमेवामलं ।। 190 ।।

दीक्षा ध्यान विषेषतोषि विमलं ज्ञानं च सद्देषनां।

सौम्यत्वं गुणगेहता चतुरता तेषां गृहे सर्वदा।। 191 ।।

इति श्री प्रद्युम्नचरिते सोमकीर्त्त्याचार्यविरचिते श्रीनेमिनाथविवाहवैराग्यदीक्षाज्ञान––समवशरणदेशनाविहारादि वर्णनोनाम त्रयोदशः सर्गः।

चतुर्दशसर्गः।

पल्लवाक्षं विहत्याथ देषं नेमिजिनेष्वरा।

उर्ल्लयंतं पुन प्रापसुरासुर नमस्कृतः।। 01 ।।

जिने तत्र समायाते सरणं समवादिकं।

चकार धनदो भक्त्या पाक शासन शासनात्।। 02 ।।

स्थितं तत्र विदित्वा तं सर्वज्ञं बिवुधाधिपा।

प्रापुर्भक्ति भरा नम्राषिरस्थ करकुद्मलाः।। 03 ।।

श्रुत्वा समागतं नेमिं बंधु प्रीत्या जनार्दनः।

चचाल वंदनायास्य दापयित्वाथ घोषणां।। 04 ।।

कामपालस्तथा शंबो भानुरन्येपि यादवाः।

सत्याद्याः सर्वदेव्योपि स्व वाहस्थाः प्रतिस्थिरे।। 05 ।।

आसाः प्रध्वानयं स्तूर्येः प्लावयन् गजमदैर्मही।

रजस्तुरगोत्कीर्ण दिक्षु सर्वासुविक्षयन्।। 06 ।।

विपन्नवातापं विष्वं मात पत्रैर्निरंतरं।

नष्टदृष्टादिषः कुर्वन् क्षीणं चामरवीजितैः।। 07 ।।

बंदि वृंदर वौद्यैस्तु पूरयन्नखिलादिषः।

पदातिभिर्महीपीवा विमुंचन् प्रतिभामिव्।। 08 ।

एवं जगत् तृणी कुर्वन् त्रिखंडाधिपति श्रिया।

उर्ज्जयंत गिरिं दूरादपस्यदति सादरं।। 09 ।।

कुलकं आलापमिव कुर्वतमत्त कोकिलनिः स्वनैः।

फलभारनतै भक्त्या नमंतमिवभू रुहैः।। 10 ।।

अतीरवावर भ्रांत्याश्रुतायस्य हयारवे।

अलिमालाकुलं शृंगमाश्रयंति सुनिर्ब्भरं।। 11 ।।

सुवंषमुन्नतं सौम्यं बहु सत्व समाकुलं।

अनेक पत्रसंकीर्णस्वमिवापर महीधरं।। 12 ।।

दूरात् च राजचिन्हं समुक्त्वा कृष्णमहीपति।

छत्रचामर संयुक्तं गजवाजिरथादिकं।। 13 ।।

प्रायजैनं महाभूत्या कतिचिद्राज पुंगवैः।

विनीतैर्विस्मयोपेतैः शरणं समवादिकं।। 14 ।।

मानस्तम्भैः सरोभिष्च नाट्यषाला समन्वितं।

उल्लोच्चैष्चामरैष्छत्रैः भृंगाराद्यैः सुमंगलैः।। 15 ।।

पुष्पमाला मृगेन्द्रादि ध्वजमाला समाकुलं।

महोत्सवैः समायुक्तं प्रविवेष जनार्दनः।। 16 ।।

तत्र नेमिं समालोक्य स्थितं सिंहासने वरे।

छत्र त्रये संयुक्तं चामरैः वीज्यमानकं।। 17 ।।

त्रिः परीत्य जिनं तत्र पूजयित्वा विधानतः।

प्रणम्यपरया भक्त्या स्तुतिं कर्त्तुं समुद्यतः।। 18 ।।

त्वमधीषस्त्रिजगतां ज्ञानवानस्तृणयोष्मितः।

क्षांतिः श्री धृतः कीर्त्यादि सततं त्वं विभूषितः।। 19 ।।

खेचरैर्भूचरैर्देवैर्नतपादांबुजः सदा।

स्तूयसे प्रत्यहं तैस्तु परं भक्त्या प्रमोदितेः।। 20 ।।

शक्तिहीनावयं नाथस्तुतिं कुर्मोकथं तव।

स्वार्थसिध्यै वयं नूनं लज्जयामोन सांप्रतं।। 21 ।।

संसार बंधनं छित्वाज्ञानं प्राप्तोसि निर्मलं।

राजीमत्यादि राज्यं च त्वया दूरे निराकृतं।। 22 ।।

मायामोह तथा कामक्रोधलोभादि शत्रवः।

जितास्त्वया विभो सर्वे निज ध्यानस्य योगतः।। 23 ।।

लोकालोकस्य सर्वस्य भानुस्त्वमसि निष्चितं।

निर्दोषो विजड़ो धीरो निष्कलंकोस्य चन्द्रमाः।। 24 ।।

आत्मतत्वं त्वया ज्ञातं पृथुकात्मा विचिंतने।

त्वमागीत्वं परं तत्वं वाण्यास प्रविभंगया।। 25 ।।

अज्ञानतिमिरांधानं ज्ञानांजन शलाकया।

चक्षुरुन्मीलकोसित्वं भव्यानां भवतारकः।। 26 ।।

एवं विधानते नूनं नेमिनाथाय सांप्रतं।

भूयो भूयो नमस्यामि त्रैलोक्य गुरुवे ध्रुवं।। 27 ।।

इतिस्तुत्वा जिनं नत्वा भक्त्या चासौजनार्दनः।

करांजलिपुटं कृत्वा धर्म प्रपछ निर्मलं।। 28 ।।

जिनेन्द्रैण तदाख्यातं धर्मं संसार तारकं।

परंतपस्विनामाद्यं ततोपि गृहमेधिनां।। 29 ।।

जीवाजीवादि तत्वानि सप्तैव जिनषासने।

प्रसिद्धातु परंलोके पदार्था नव संमता।। 30 ।।

पंचास्तिकायिका नूनं षट्द्रव्याणि तथैव च।

पृथुकात्मा पृथृक्कर्मपृथक देहो न संषयः।। 31 ।।

निजात्माज्ञान वान् लोके कर्म पाषेन वेष्टितः।

तत्वातत्वं न जानाति यथा भ्रेष्चन्द्र भास्करौ।। 32 ।।

षट्लेष्या जिनैरुक्तास्तस्त्रयस्त्रषुभामताः।

पीत पद्मां च शुक्ला च लेष्यावै भव्य प्राणिनां।। 33 ।।

कृष्णानीलाच कपोता अभव्यानां मता सदा।

तास्तु भाग्य विषेषेण जायंते प्राणिनां सदा।। 34 ।।

तथा चत्वारि ध्यानानि कथितानि जिनेष्वरः।

आर्त्तरौद्रं तु संत्यज्य धर्मे शुक्लं तु गृह्यते।। 35 ।।

गुणास्थानानि प्रोक्तानि चतुर्दष जिनेष्वरैः।

तथाच्चैव समुदिष्टा मार्गणाष्च चतुर्दष।। 36 ।।

दषलाक्षिणि को धर्मो जिनेन्द्रैः प्रतिपादितः।

तपो द्वादष भेदं तु बाह्याभ्यंतर योगतः ।। 37 ।।

इति जैनं वचः श्रुत्वा त्रिषष्टि पुरुषोद्भवं।

प्रपछ चारितं कृष्णः कृत्वा करपुटं निजं।। 38 ।।

जिनेन्द्रेण तदा प्रोक्तं प×चकल्याणं संयुतं।

गुरवोपि पुराणीह नाम स्वर्ग पुरातनं।। 39 ।।

नगराणि पितामाता नक्षत्राणि तथैव च।

उत्सेधं वर्णभेदंतु वंषो राज्यं तथैव च।। 40 ।।

तपो ज्ञानं तु निर्वाणं स्थानं भूपतिभिः समं।

प्रत्येकं षट्चत्वारिंषत् भेदा प्रोक्ता जिनेषिनां।। 41 ।।

षट् खण्ड भूमिपतयष्चक्र नाथास्तु द्वादष।

वदेवास्तु हरयस्तथैव प्रतिषत्रवः।। 42 ।।

तेषां पुराण वंषोपि पिता माता तथैव च।

यस्यतीर्थे समुत्पन्नास्तत् सर्वं प्रतिपादितः।। 43 ।।

उत्पत्तिं च प्रबुद्धिं च मरणं च तथैवहि।

इति श्रुत्वा सभा जाता वैराग्येन विभूषिता।। 44 ।।

तत्रस्थोपि हरे भ्राता कुमारो गज संज्ञकः।

वैराग्यं परमं प्राप्य स्वयमुत्थाय वेगतः।। 45 ।।

गिरेस्तु षिखरे गत्वा कृत्वा लोचं स्वयं निजं।

जिनादेष वषादीक्षां नीत्वा ध्याने स्थितो यदा।। 46 ।।

तस्य च स्वसुरे विप्र सोमषर्माभिधानकः।

श्रुत्वासोथ समायातस्तत्रैव मुनि सन्निधौ।। 47 ।।

वचोभिर्विविधैः सोपिबोधयामास तं मुनिं।

यदामुमोचनध्यानं तदा क्रोधेन पूरितः।। 48 ।।

हूताषनमयीं पापो उत्तमांगे च दग्धकां।

ममोच दह्यमानापि योगी ध्यान निजंनहि।। 49 ।।

यदाकंठगत प्राणो जातोसौ मुनिनायकः।

तदातुकेवलज्ञान मुत्पन्नं ध्यानयोगतः।। 50 ।।

तदेव हि च निर्वाणमुपसर्ग जयस्तप तत्रस्था।

विबुधाः सर्वेप्रोत्थितास्तं मुनिं प्रति।। 51 ।।

तदातु विष्णुना प्रष्टो जिनेन्द्रस्तं च कारणं

क्वोत्थिता विबुधाः नाथ कुर्वंतुमी जयस्वनं।। 52 ।।

तदानेमीष्वरः प्राह शृणु कृष्ण निगद्यते।

मुनेर्गज कुमारस्य केवलज्ञानमुदõतं।। 53 ।।

तत्रायं सकलो लोकोयाति देवैः समन्वितः।

निर्वाणंचथा जातमुपसर्ग जयेनहि।। 54 ।।

इतिस्ततो विलोक्या सुभ्रातरं तं गजाद्वयं।

प्रपछकारणं कृष्ण जिनेनापि निवेदितं।। 55 ।।

विलोक्य च तत् वृतान्तं श्रुत्वा श्रीजिनभाषितं।

केचिद्वैराग्यमापन्ना दीक्षां जैनेष्वरीं श्रिताः।। 56 ।।

अनुव्रतानि तत्रान्ये जाताः शीलव्रतान्विताः।

षट्कर्माणि गृहस्थानां निन्पुरन्पेतु प्रत्यहं।। 57 ।।

संतुष्टा जिन वाक्येन तत्र सर्वे नरामराः।

सम्यक्त्वं परमं प्रापुर्मिथ्यात्व मथनं शुभं।। 58 ।।

कृष्णेनापि ततो ज्ञातं संसारं सार वर्ज्जितं।

त्रिषष्ठि पुरुषाः सर्वे जाता नष्टा इति श्रुता।। 59 ।।

कर्णांजलिपुटैः पीत्वा तज्जिनेन्द्र वचोमृतं।

हृष्टः सर्वेहली चैवं प्रपछ निज वांछितं।। 60 ।।

अनाद्यं कृत कं नाथ जातस्य ध्रवुं मतिः।

अतोद्वारावतीनाषो मरणं च हरे कुतः।। 61

इति पृष्टो जगौ नेमिः पुरीमद्येन हेतुना।

साधोः द्वीपायनादस्माद्य वषावे च विनस्यति।। 62 ।।

मृगया व्यसन स्थाच्च कौषांब वनमाश्रितात्।

जरत्कुमार तो विष्णुः मृतिस्यादिषुघाततः।। 63 ।।

श्रुत्वै तज्जिन वाक्यं हि सर्वे जाता भयकुलाः।

यथा संपदि सौख्यं स्यात् तथा विपदि दुःखतः।। 64 ।।

केचितत्र नराभीत्या पुरांतरमुपागताः।

अन्येवैराग्यमापन्ना सर्वज्ञ शरणं ययुः।। 65 ।।

सर्वज्ञवचनं मिथ्या कर्त्तु द्वीपायनोमुनिः।

वैराग्यं द्विगुणं प्राप्य विदेषं गतवान् द्रुतं।। 66 ।।

नमन्नखिल सामां तं मौलिमार्च्चित क्रमः।

म्रियते यदि मत्तोपि हरिः किंसाध्यमत्रमे।। 67 ।।

इति त्वम जरास्नरपास्य विषयान् पुरं।

सोदरैर्हियमानोपि विवेष विजनं वनं।। 68 ।।

मद्यांगैर्मद्य संधानं त्यजतेतियदूत्तमः।

पुर्यामदापयषीघ्रं तथा पिपटहं भयात्।। 69 ।।

प्रियाममांगजो भ्राता यदि कष्चिजिनोदितं।

तपोगृहीति गृÉा तु वारयामिनर्निष्चितं।। 70 ।।

भावि भीत्या कुरुधर्मं द्वारिकामथ भान् मान्।

विनिंदित्वोदय प्रियं रक्तोप्यासीत्पराङमुखः।। 71 ।।

हरे दुःखं तथा भावि नूनं द्रष्टु मुनीष्वरः।

अस्ताचल तटाद्भानु पपाता परवारिधौ।। 72 ।।

तमुदंतं समाकर्ण्य दुःखिते वा कमलिनी परं।

म्लानांबुज मुखारोदीत् करुणैर्मधुपः स्वनैः।। 73 ।।

संध्यासिंदूर कौसुम्भ किंषुकातति सन्निभा।

आविरासी तु पुरो हंतु सूचयंतीव भाविनां।। 74 ।।

परलोक गतेभानौ शकुंतार्त्तरबा शुचा।

संध्यारक्ताम्बरायासीत् विनाषमिवतत्क्षणात्।। 75 ।।

ततस्तमोणवोदिक्षु प्रसर्यतो विरेजिरे।

धूमां सा इव संभूता दहनैर्भाविनोघना।। 76 ।।

अविवेक निरुत्साहं मनोभ्रमयदुत्पथे।

मोहजालोपमं जातं तमोथेष विषेषतः।। 77 ।।

ततस्तारागणः स्पष्टः समभूत्तमसि क्षणात्।

प्रायेणाल्पमतिर्भातितमस्येष विषेषतः।। 78 ।।

उन्मूलयंस्तमोजालं कुमुदंपरिवर्द्धयन्।

उदियाय निषानाथः प्रोषित स्त्री भयंकरः।। 79 ।।

कृतांगमंडनोभर्त्तुरपराध पराङ्मुखः।

ह्नतीप्रेषण कमाणि प्रारभेवनिताजनः।। 80 ।।

संवृत्ते रति संभोगे यथानुक्रमतस्ततः।

विरक्ता काम भोगेषुकेचिदेवमचिंतिषु।। 81 ।।

राजराजेनया पूर्वं पाक शासनतः क्षता।

साप्यनित्यापुरीचेत्स्यात् किं नित्यं भुवनोदरे।। 82 ।।

कंसादिमत्तमातंग केषरीयः पुराभवत्।

हरिस्तस्यापुरीं कष्चिद्वक्षतीति महाद्भुतं।। 83 ।।

स्वप्नेन्द्रजालफेनाभं मृगतृष्णतडित्समं।

सर्वेषां समदोत्पंत्यं जीवितं च शरीरिणां।। 84 ।।

कायारोगालयो नूनं भोगादेहि भयावहाः।

योषितो दोष देहाभा अर्थानर्थकरो नृणां।। 85 ।।

मैत्री न शाष्वती भूम्यां संयोगः सविपर्ययः।

इतिध्यात्वा जनैः कार्यं तपोवन निषेवणं।। 86 ।।

इति चिंतयतां तेषां रागद्वेषादि चागमत्।

परावृत्तिं कृपानाथः क्षिपया सहसाकवत्।। 87 ।।

ततः प्राभातसंषूचीतांम्रचूडः स्वनैः सह।

उद्भूत्पटहस्वानः प्रबुद्धः जनवल्लभः।। 88 ।।

प्रबुद्धाः सकलालोकास्तेन तूर्य रवेणवै।

गंधर्वाणां तु गीतैष्च बंदिनां तु जयारवैः।। 89 ।।

दोषांनाषयन् वेगाकृमोदूरं निराकरन्।

उदयाय तदा भानुरुदयाचल मस्तके।। 90 ।।

सिन्दूरारुणावर्णोवंद्यं लोकस्य ज्योतिषां नाथः।

सौम्योगिरि षिर वाषीदहोद्भीतोयथा भाति।। 91 ।।

***इति श्रीप्रद्युम्नचरिते श्रीसोमकीर्त्याचार्यविरजिते श्रीबलभद्र प्रश्न**

जिनेन्द्रदेवकृत भविष्यनिरूपण वर्णोनाम

चतुर्दशसर्गः। *

पञ्चिदशसर्गः

अथैकदा सभामध्ये निविष्टो मधुसूदनः।

सेव्यमानो जनौद्यैस्तु पाकषासन सन्निभः।। 01 ।।

पूरयित्वा सभां दिव्यां यादवोधैः समंततः।

किंचित् च शंकया युक्तो दिव्ये सिंहासनेमुदा।। 02 ।।

सामन्तैः सचिवैः सर्धैस्तथा विद्याधरैरपि।

बलभद्रादि भूपैस्तु परीतो रवि सन्निभः।। 03 ।।

गंगातरंग संकाषैः वीज्यमानसुचामरैः।

षोडषाभरणोपेतो कौस्तुभालं कृतोह्वदि।। 04 ।।

पुष्पत्पयोजव वनष्चात्र शोभित मस्तकः।

नानाकलाविनोदैष्च लोकै रंजित मानसः।। 05 ।।

कुलकं अत्रांतरे समागत्य राजपुत्रैः समन्वितः।

शांतोगुण षतैः पूर्णः सर्वविद्या समन्वितः।। 06 ।।

विषयेभ्योविरक्तात्मा कृष्णस्या स्थान मंडपं।

नत्वा हरिं निविष्टोसौ मदनो विष्टरे वरे।। 07 ।।

क्षणमेकं ततः स्थित्वा लब्धा कथावसानकं। – युग्मं

स्नेहं सुदुस्त्यहंत्यक्त्वा वैराग्याहत चेतसा।। 08 ।।

ललाटे स्वांजलिं कृत्वा विनयान मस्तकः।

याचयित्वा भयं कामो जगाद मधुसूदनं।। 09 ।।

स्वामिंस्तव प्रसादेन जातिरूपकुलादिकं। – युग्मं

सर्वभोगोपभोगास्तु लब्धा सौख्य करामया।। 10 ।।

भुक्त्वा विलोकिता सर्वे दृष्यतेत न शाष्वताः।

नित्यतारहिता तात साः वा सांसारिकी स्थिति।। 11 ।।

कुरु प्रसाद मधुनादेहि त्वाज्ञां मम प्रभो।

मोक्षसौख्याय यद्यन्नं करोमि कृपया तव।। 12 ।।

दीक्षांजैनेष्वरीं तात गृहणामि भवनाषिनीं।

असारं सर्व संसार वर्त्तते दुःख कारकं।। 13 ।।

तस्योदितं समाकर्ण्य वसुदेव पुरस्सराः।

कृष्णाद्यायादवाः सर्वे शोकात् निष्चलतांगता।। 14 ।।

मूर्छा प्राप्यनृपाः सर्वे काष्ट रूपाः स्थितास्तदा।

मूर्छया मरणं तेषां रुद्धं जानामि निष्चितं।। 15 ।।

आप्रबोधास्तदा प्रोचुः मदनं स्नेह पूरिता।

वत्साद्य कठिनो जातः किं नो भवसि पूर्वकः।। 16 ।।

त्वं च स्नेहोष्भितं वाक्यं बंधुवर्गस्यता पदं।

कथं तव मुखाद्वत्स निर्गतं कठिनं वचः।

कोयं वीर गुणाधार समयः संयमस्यहि।

त्वं युवा रूपसंयुक्तो भोगोयोग्योसि सांप्रतं।। 18 ।।

यत्प्रोक्तं जिननाथेन तत् को जानाति निष्चियं।

भविष्यत्पथवानो हि त्वं प्राप्तोसि कथं भयं।। 19 ।।

वीरोसि वीरगर्वेषु धीरोधीरेषु निष्चितं।

योधेषु योधबर्योसि तथा मंत्री च मंत्रिषु।। 20 ।।

विद्यावानसि विहत्सुभागी भोगिषु सुंदर।

दयावान् सर्वजीवेषु सदाबंधुषु मोहवान्।। 21 ।।

विदग्धष्चतुरोसि त्वं योग्यायोग्य विदोसि वै।

तवदीक्षामयं वाक्यं युक्तमुक्तं न सांप्रतं।। 22 ।।

ज्ञात्वाथ मोहवषगान् म्लान मुखांबुजान्।

जगाद मदनो वाक्यं स्नेहेन परिवर्ज्जितः।। 23 ।।

नूनं केवलिनोवाक्यं पूज्या नैवान्यथा भवेत्।

भ्रांतिस्तत्र न कर्त्तव्या भव्यैः दर्षन भूषितैः।। 24 ।।

नो भयं मम कस्यापि सर्वत्र वसुधातले।।

मुक्त्वा पुरातनं कर्म न किंचित्प्राणिनां भवेत्।। 25 ।।

न कोपि स्वजनोबंधुर्नकोपि दुर्ज्जयो रिपुः।

दातुं कोपि समर्थो न कोपि नेतुं न सांप्रतं।। 26 ।।

अनादिनिधनो जीवः संसारे सार वर्ज्जिते।

स्नेहोत्र क्रियते पूज्याः कियद्भिर्बन्धुभिः समं।। 27 ।।

इति ज्ञात्वा तु पूज्यौधैस्त्याज्यः शोकोतिदुःखकृत्।

एवं कामवचः श्रुत्वा कृष्णो दुःखेन पूरित।। 28 ।।

शोकेन गदगद गिरं तातं वीक्ष्य मनोभवः।

जगाद वचनं वाग्मी श्रणु तात वचोमम।। 29 ।।

किंशोच्यषे वृथा तात त्वं तु सर्वोपदेषकः।

दीयते किं तु सूर्याय प्रकाषाय प्रदीपकः।। 30 ।।

न बालं न कुमारं वा विदग्धं रूप संयुतं।

मेधावि न सुषीलं तु गुणिनं शील वर्ज्जितं।। 31 ।।

सषूरः कातरं चापि युवानं वृद्धमेव चा।

गृÉाति नियतं मृत्युः प्राणिनां चायुषः क्षये।। 32 ।।

सुलोचनापतिः श्रीमान् चक्रवर्त्ति सुतोमलः। – युग्मं

क्वासौ मेघेष्वरोजातः कीमिनी प्राणवल्लभः।। 33 ।।

आदिनाथस्य यः सूनुष्चकीभरत संज्ञकः।

आदित्य कीर्त्तिराद्याये क्व गतास्ते नराधिपाः।। 34 ।।

बाहूबलितिनामायो वृषभस्य सुतो बली।

क्व चान्येपिगता भूपाः खेचरानमिपूर्वकाः।। 35 ।।

इत्यादि विविधैर्वाद्यैरुक्त्वा तातं निजं स्मरः।

शम्बंनिजपदेन्यस्य जगाम जननी गृहं।। 36 ।।

जगाद जननीं कामोनत्वास्याः पादपंकजं।

वाल्यादारभ्ययन्मात मया दुर्निष्टितं कृतं।। 37।।

क्षंतव्यं सकलं नूनं तन्मे बालस्य सांप्रतं।

प्रसादं परमं कृत्वा पूज्याः क्षांतिकराध्रुवं।। 38 ।।

निःषेष कर्म कक्षस्य दहनैक दावानलं।

शालीरु रत्न जलधिं गुणानां मंदिरं परं।। 39 ।।

आश्रितं पूर्वं पुरुषैर्वनं दिग्वाससां वृतं।

आश्रयामि ध्रुवं माता त्वया वाच्यं नकिंचनं।। 40 ।।

इत्थं पुत्रवचः श्रुत्वा गुरु दुःखभरालसाः।

मूर्छामासाद्य सा माता पपात वसुधातले।। 41 ।।

छिन्नमूला यथा वल्ली भूमौपततिनिः प्रभा।

पतित्वा तु तथा चेयं संज्ञामाप्य जगाविति।। 42 ।।

आः पुत्र किंव्यवसितुं ते युक्त मधुनापरं।

मातरं दुःखिनीं मुक्त्वा गंतुं ते युज्यते कथं।। 43 ।।

श्रृणुष्वु मम वाक्यं हि यदि धर्मोद्यतोसि वै।

मातरं दुःखितं कस्मात् कुरुषेचे दयापरः।। 44 ।।

इति शोकाकुलां दृष्ट्वा मातरं तु मनोभवः।।

पुनर्जगाद विजयी शास्त्र दृष्टांत दर्षकः।। 45 ।।

मातः संसाररूपत्वं सत्यं जानास्य निंदिते।

एकाकी जायते जंतुः म्रियते च तथा विध।। 46 ।।

एककीकर्मबंधनति भुंक्ते च तत्फलं तथा।

अतः शोको न कर्त्तव्यो विवेकादि गुणान्वितैः।। 47 ।।

मोहो दुःखप्रदो नूनं प्राणिनां तु भवे भवे।

यावन्मात्रोभवेन्मोहो दुःखं स्यात् च ततोधिकं।। 48 ।।

जन्मस्तु मरणाक्रांतो जराक्रांतो च यौवनं।

स्नेहोदुःख भराक्रांतो विषयासन्निभाः।। 49 ।।

तिक्त्वाचैवं विधं मोहं यतंतं सुकृतेनरं।

योवैवारयते मूढः सत्षतुर्नात्र संषयः।। 50 ।।

इतिज्ञात्वा शुचं मुंच प्रसादं कुरु सांप्रतं।

किं बहुनोक्ते हे मातादेषं देषकसेस्महं।। 51 ।।

एवं पुत्रस्य वाक्येन मोहं त्यक्त्वा तु रुक्मिणी।

जगाद मदनं तुष्टा क्व विबुद्धा विषयान् प्रति।। 52 ।।

स्तुषापुत्रस्य मोहेनामोहिताहं त्वया सुत।

बोधितास्मिगुणाधार सांप्रतं गुरुवत् ध्रुवं।। 53 ।।

शुष्कपत्रस्य संघातो वातनुन्नोयथा व्रजेत्।

तथा स्वजन संयोगोविद्ध नूनं मनोभव।। 54 ।।

यथा जलद संघाता दृष्यंते गगनांगणै।

वातनुन्नाक्षयं यांति संपदोति तथा सुत।। 55 ।।

मायोपमाध्रुवं रत्याष्वावष्यं तु विनाषिका।

सुखं दुःख समाक्रांतं विषयाविषसन्निभाः।। 56 ।।

संसार विषयेष्वेवं यदि स्यात् क्त्वापि सारता।

तदानाभेयपूर्वास्तु त्यजंति विषयान् कथं।। 57 ।।

नित्यास्यात् स्वजनानां तु संगतिः स्वजनैः सह।

भरताद्या महीनाथा किंस्युस्तपसि तत्पराः।। 58 ।।

संसारस्य ध्रुवं ज्ञात्वा वृत्तान्तं सार वर्ज्जितं।

कुरुष्कयत्नमेवात्र युक्तौ त्वं शाष्वतेसुखे ।। 59 ।।

नाहं त्वां वारयामीति गच्छन्ति नियमादपि।

सन्मार्गा चरणं रक्तं विरक्त कृत्रिमे सुखे।। 60 ।।

अहं तु स्नेहमुक्त्वा हि प्रविषामि तपोवनां।

संसार सागरस्यैव भारणेपोत सन्निभं।। 61 ।।

इयं तं समयं वत्स स्थिता गेहे सुखेरता।

तव मोहवषेनैव नापरं मम करणं।। 62 ।।

इति मातृ वचः श्रुत्वा संतुष्टो मदनस्तदा।

हर्षात् जगाम शुद्धां तं वैराग्या रक्तमानसः।। 63 ।।

जगाद महिला वृंदं विरक्तो मदनस्तदा।

श्रृण्वंतु वचनं नार्यो मदीयं हितकारणं।। 64 ।।

भ्रमन् प्राणी तु संसारे चिरं दुःख समाकुले।

कथंचित् दैव योगेन मानुष्यं लभते ध्रुवं।। 65 ।।

तत्रापि सुकुले जन्मः दुःखप्रापं भवकोटिषु।

तत्प्राप्यापि राज्यं हि दुर्ल्लभं च धनं तथा।। 66 ।।

संसारे दुर्लभं यच्चतत्रत् प्राप्तं मया ननु।

अधुना निज कर्त्तव्ये करिष्ये यत्नतापरा।। 67 ।।

दीक्षां जैनेष्वरी रम्यां मोक्षसौख्यप्रदायिकां।

गृÉामि भवतीभिष्च विवार्योहंनसांप्रतं।। 68 ।।

प्राणीयोषाकृते नूनं किं किं करोति न क्वचित्।

विषयैर्वि×ली भूतो यातिमृत्युमुखेनरः।। 69 ।।

गजवाजिरथैर्युक्ते रणे रक्तापगाकुले।

विषंति प्राणिनो नूनमर्थ लुब्धान संषयं।। 70 ।।

केचिद्भीमं वनंद्रौद्रं व्याघ्र सिंह समाकुलं।

विंषति धनलोभेन विंध्यादि पर्वतांतरे।। 71 ।।

अगाधं सागरं घोरं मच्छ कच्छ समाकुलं।

योषितां भोगमुदिष्य धनार्थेन विषंति किं।। 72 ।।

बहुनाभाषितेनात्र वर्त्तते किं प्रयोजनं।

यद्यच्चदुष्करं कर्म नार्यर्थे क्रियते नरैः।। 73 ।।

भुक्त्वा भोगामयानेका भवतीभिः समं सदा।

तृप्तिस्तथापिनाभूत् तदा किं स्थीयते गृहे।। 74 ।।

गंतुकामोस्म्यहं नूनं जिनेन्द्राणां तयोवनं।

भवः तीभिः क्षमाकार्या मयामायुवती जनाः।। 75 ।।

इतिवाक्यं समाकर्ण्य कामस्यराग वर्जितं

रत्याद्यायोषितः सर्वा प्रोचुर्दुःख समाकुला।। 76 ।।

किंचिद्वैराग्य सम्पन्ना करयो युग्म मस्तके।

प्रणामं च तदा कृत्वा विनयेन विभूषिताः।। 77 ।।

श्रृणुनाथ वचोस्माकं कथयामोत्र सांप्रतं। – युग्मं

सर्वासां शरणं नूनं त्वमेव हि न संषय।। 78 ।।

आश्रयस्तु त्वमेवात्र मित्रं बंधु जनास्तथा।

मुखं दुःखं त्वया सार्द्धं करिष्यामस्तपोनघं।। 79 ।।

भुक्त्वा भोगास्त्वया सार्द्धमस्माभिस्त्वं तवर्जितां।

नीत्वा दीक्षां त्वयासार्द्धं करिष्यामस्तपोनघं।। 80 ।।

येनवै तपसा कृत्वा सुराणां मंदिरै ध्रुवं।

भुजिष्माः मः सुखं गत्वा त्वत्प्रसादाद्वयंविभो।। 81 ।।

अतो गृहान जैनेन्द्रीं दीक्षां कर्म विनाषिनीं।

त्वयासार्द्धे गृहीष्मामोवयं जैनं व्रतं विभो।। 82 ।।

यदि तिष्टसि त्वं गेहे भोग लुब्धो नराधिप।

तदा गेहं स्थिता स्वामिन् भुंजिष्यामो वयं सुखं।। 83 ।।

वंदिष्यामो जिनं नेमि त्वत्प्रसादाद्वयं विभो।

असारं विद्धि संसारं मुंचमुंचप्रभेध्रुवं।। 84 ।।

विधूतमत्सरा नूनं त्यक्त्वा रागं सुदुर्ज्जयं ।

कामषत्रुं ध्रुवं हत्वा कृत्वा स्थाने निजं मनः।। 85 ।।

राजीमत्या समीपेहि शुद्धैकवसनावृता।

भवामष्चार्यिका नाथ करिष्यामो वरं तपः।। 86 ।।

इत्थं निषांमिवाक्येन तुष्टोभून्मदनस्तदा।

मन्यमानास्वमात्मानं निर्गतं भवषंजरात्।। 87 ।।

स्वयं ये वर्द्धिता पूर्वं राजपुत्रो स्त्वनेकषः।

मदनेनात्मनासार्द्धं बाल्यादारभ्य वंषजा।। 88 ।।

तैः समं गजमारुह्य गेह वासाद्विनिर्ययौ।

पुरमध्येजनैःदृष्टस्तदा प्रेम भरालसै।। 89 ।।

प्रषसंसुर्जनास्ते हि वाक्यैर्नानाविधैस्मरं।

अहो यस्य पिता विष्णुः सर्वषत्रु विमर्दकः।। 90 ।।

त्रैलोक्य सुन्दरीणांहि रूपं जित्वा तु यास्थिता।

रुक्मिणी भुविविख्याता माता चास्य गरीयसी।। 91 ।।

शत्रुतुल्यमिदं राज्यं सौराष्ट्र विषयोद्भवं।

अनोपमं परं रूपं सुराणामपि दुर्ल्लभं।। 92 ।।

रूपलावण्य संयुक्ताः सर्वलक्षण लक्षिताः।

कलाविज्ञान सम्पन्नाः कामिन्योस्य त्वनेकषः।। 93 ।।

एवं विधेहि सौक्षेहि विद्यमानेपि मन्मथः।

तपः कर्त्तुं समुद्युक्तौ वांछति किमतः परं।। 94 ।।

ततो पिहि जगौ तत्र केचित्संतो वचोवरं।

श्रृण्वंतु येन कार्येण तपस्तयति मन्मथः।। 95 ।।

सर्वलोकांतिगं सारं जरा जन्म विवर्जितं।

मोक्षं गंतु स्पृहां कृत्वामुक्त्वा वैकृत्रिमं सुखं।। 96 ।।

तपः कर्त्तुं समुद्युक्तो वैराग्येण विभूषितः।

वांछयन् शाष्वतं सौख्यं मदनः श्रुतपारगः।

एवं कृत्वा समालोपं लोकाः सर्वे परस्परं।

शुभं वाक्यं तदा प्रोचु कामं प्रेम भरालसाः।। 98 ।।

जयजीवचिरं नंद वर्द्धस्व गुणसागर।

कुरुकार्यं निजं वत्स स्मर नित्यमनित्यतां।। 99 ।।

एवं लोकवचः श्रृण्वन् मदनः पुरमध्यतः।

सोत्सवोथ विनिर्गत्य गिरिंरैवतकं गतः।। 100 ।।

तत्रैव जिननाथस्य शरणं समवादिकं।

मानस्तम्भैर्युतं दृष्टं मदनेन क्षमावता।। 101 ।।

मानांगणं समासाद्यमुक्त्वा यानादिकं तदा।

छत्रचामर संयुक्तं राज्य विभव भूषितं।। 102 ।।

तथा षोडषलाभांष्व विद्यास्ताःपूर्वमार्जिताः।

सर्वाक्षमय्प कामेन कामिन्य इवमोचिताः।। 103 ।।

भूयोपि जिनं लोके संषक्षमय पुनः पुनः।

विवेषनेमिनाथस्य शरणंसमवादिकं।। 104 ।।

निर्गच्छद्विषमानैष्व पूरितं तु सुरासुरैः।

तत्र गत्वा जिनं दृष्ट्वा प्रणम्य प्रजगाविति।। 105 ।।

करांजलिपुटं कृत्वा श्रृणु नाथ वचो मम।

भव्यानां तारकोसि त्वं नूनं संसार सागरात्।। 106 ।।

मह्यं जिनेन्द्रवरद प्रणुतार्त्ति निवारकः।

संसार नाषिनीं दीक्षा प्रयछ कृपया विभो।। 107 ।।

इत्युक्त्वा पादयोर्नत्वा नेमिनाथस्य मन्मथः।

वस्त्राणि भूषणादीनिमुक्त्वा निज परिग्रहं।। 108 ।।

पंचमुष्ठिभिरुत्पाद्य निजान् केषान्मनोभवः।

त्यक्त्वा सावद्ययोगं समुक्त्वा सर्वपरिग्रहं।। 109 ।।

दीक्षां जग्राह जैनेन्द्री भूरिभिर्भूमिपैः सह।

महावैराग्य संयुक्तो मोक्षकामो गुणाकरः।। 110 ।।

ततो भानुकुमारोपि वैराग्य रंगलालसः।

मातापित्रादिकं सर्वं पृष्ट्वा बंधुजनं निजं।। 111 ।।

मुक्त्वा राज्यस्य चिंता च राजपुत्रैः समन्वितः।

विलोक्य सर्वलोकौधै दीक्षां जग्राह निर्मलां।। 112 ।।

गृहीते सति चारित्रै भानुनामकुमरेणहि।

दुःखितास्तत्र संजाता लोकाहरि समन्विता।। 113 ।।

सत्यभामा तथा भीष्म तनया गुण पूरिता।

जांबुवत्यादयोदेव्यो गत्वा जिनसभांतरे।। 114 ।।

तत्रगत्वा जिनं देवं राजीमत्या समीपके।

धूतरागाः स्त्रियाः सर्वादधुदीक्षां मनोहरां।। 115 ।।

नीत्वा दीक्षा च ताः सर्वाः सितवस्त्र समन्विताः।

समुद्यतास्तयो घोरं तप्तुं वैराग्य संयुताः।। 116 ।।

चारित्रमेवं रतिनायकोपि नीत्वा चक्रे परमं तपस्तु।

सम्बन्धं ते सौ स्वजनैपरैष्च सोमेव सौम्याजगतां हिताय।। 117 ।।

***इति श्रीप्रद्युम्नचरितेसोमकीर्त्याचार्यविरचिते श्रीप्रद्युम्न अष्टपट्टमहिषीदीक्षाग्रहणं नाम पञ्चिदशमसर्गः। ***

षोडशसर्गः

अथ कामं महाघोरं कुर्वन्तमुत्कटं तपः।

तपसां तु श्रियायुक्तं वैराग्येण विभूषितं।। 01 ।।

दृष्ट्वा कृष्ण बलाद्याष्च भूत्वा शोकेन पीडिताः।

प्रणम्य सदनं यातास्तत्र दत्वा निजं मनः।। 02 ।।

इतोपिकामदेवोसौ सुमुनिभ्योति दुःकरं।

विनयेनैव संयुक्तष्चकार विविधंतपः।। 03 ।।

देवषास्त्र गुरुणांहि भक्तिं कुर्वन् त्रिधाध्रुवं।

व्याधदृष्टि गुणैर्युक्तो नाना लब्धनिवास भूः।। 04 ।।

एकांतरेण मदनष्चकार पारणं परां।

द्व्यंतरें त्र्यंतरेचापि चतुर्थे षष्ठमेदिने।। 05 ।।

अष्टमे पक्ष मासे सा चक्रेसौ पारणांमुनिः।

उपवासान् बहूस्तत्र विधाय विविधान् शुभान्।। 06 ।।

रागद्वेष विनिर्मुक्तोनमुक्तो गुण संपदा।

कामक्रोधादि रहितो विषयेष्वपि निस्पृहः।। 07 ।।

जिनागमे प्रसिद्धायेनराणां कवलाद्विका।

दिनाधिकास्त्रिंषदंता वृद्धिहान्यादि भेदतः।। 08 ।।

उनोदरं तपष्चापि नाना भेदंच काससः।

जिनमार्गेसमुदिष्टं सिंह विक्रीडनादिकं।। 09 ।।

हारबंधं विधाने नवज्रमध्यमयं तथा।

धर्मा चक्रादिबालांतंकैयक्ले शकरं परं।। 10 ।।

विषेषैर्विविधैयुक्तं चकारासौ तपोनघं।

यत्कृतं कामदेवेन तद्वक्तुनैव शक्यते।। 11 ।।

गुडं च घृत तैलं चदधि क्षीरं तथैव च।

शर्करा लवणं चापितेन मुक्तं तपाष्विना।। 12 ।।

सर्वदोष विनिर्मुक्तं स च सावद्य वर्ज्जितं।

निन्यै विरक्तचित्तोसावाहारंदेह रक्षणे।। 13 ।।

प्राश्रुकेचोत्तमे स्थानेमृतादिजंतु वर्ज्जिते।

विविक्तषय्याषनाख्यां तप चक्रे मुनीष्वरः।। 14 ।।

वर्षा कालेथ योगीन्द्रो वृक्ष दुरासहे।

नीत्वा योगं त्रिधा नूनं तत्र तिष्ठति निष्चलः।

शीतलेथ संप्राप्ते नद्यास्तीरेथ दुःसहे।

रात्रौ नीत्वा परं योगं ध्याने तिष्ठति धीरधीः।। 16 ।।

ग्रीष्मकाले तथा चाग्रे गत्वा वै गिरि मस्तके।

षिलायाः फलकेस्थित्वा सह ते तापमुत्कटं।। 17 ।।

मनसा वचसा तन्वाभेदाभेदं प्रमादतः।

त्रपार्यं तं तु यत्पापमतीचारं तथेतरं।। 18 ।।

तस्यवैसौघनायासौ बाह्याभ्यंतर योगतः।

ततोघोरतंर चक्रे प्रमाद रहिता मुनिः।। 19 ।।

जिन सिद्धादि शूराणां पाठकानां तथैव च।

साधूनां निः प्रमादेन भक्तिं चक्रे मुनीष्वरः।। 20 ।।

सम्यक्त्वालंकृतो योगी विनयेन विभूषितः।

वैयावृत्यं तुदषधाचक्रे भक्तिं भरान्वितः।। 21 ।।

जिनेन्द्र वदनाद्यच्च निर्गतं श्रुतमुज्वलं।

पदाक्षरादि संयुक्तं द्वादषांग सुविस्तरं।। 22 ।।

निः प्रमाद तया योगी गुरुभक्ति परायणः।

पपाठ परया युक्त्या दयादम क्षमान्वितः।। 23 ।।

बाह्याभ्यंतर योगेन सर्वसंग विवर्ज्जितः।

संस्कारं तु शरीरेपिनैव चक्रे निरादरः।। 24 ।।

आर्त्तिरौद्रादि कुध्यानं त्रिघातत्याजसन्मुनिः।

धर्म शुक्लादिभेदेन चक्रे ध्यानं महादरः। 25 ।।

आवष्यकं चकारासौ मनोभव मुनीष्वरः।

कायोत्सर्गेण रात्रौतु ध्यानी मौनी हि तिष्ठति।। 26 ।।

लोकाक्रोसकै रुद्रैष्च तथैव ताडनैरपि।

आदरेणनिर्मुक्तै भाषणैर्भर्त्सनैस्तथा।। 27 ।।

अचालितांतःकरणो विवेकीहि क्षमायुतः।

निष्चलोमेरुणातुल्यः कामदेवोमुनीष्वरः।। 28 ।।

प्रस्थाने शयने स्थाने भोजने तु विलोकने।

विमर्षने तु सच्चेष्टे पठने पाठने तथा।। 29 ।।

प्रषांत हृदये योगी शुभ चेष्टा समन्वितः।

मार्दवं परमं विभ्रद्रराज शुभ चेष्टया।। 30 ।।

मनोवचः शरीस्य विचारे प्रत्यहं मुनिः।

विविक्तं चिंतयामास प्रकृष्टार्ज्जवसंयुतः।। 31 ।।

धीर्यः धुर्यः सुवीर्याद्यो योगी योगीष्वरार्च्चितः।

विचारं कुरुते नित्यं शरीरात्मा पृथक् पृथक्।। 32 ।।

स शौचं संयमं धत्ते लक्षणैः परिपूजितं।

तपस्त्यागादिभिर्युक्तं सत्याचार विभूषितं।। 33 ।।

निर्लोभत्वं शरीरेपि ब्रह्मचर्याभिर्गुणैः।

दषप्रकारकं धर्म जिनेन्द्रैः प्रतिपादितं।। 34 ।।

बभार परमं सत्यं मोक्ष मार्गस्य देषकं।

जैनं सर्व गुणोपेतं संसारार्णवषोषकं।। 35 ।।

जितान्य लोकान् विषमान् परीषहगणान् परान्।

क्षुधातृषादिकान् सर्वान् क्षुद्रलोक प्रतारकान्।। 36 ।।

पूर्वं रिपु गणान् सर्वान् मदनेन यथा जितान्।

तथा विर्जितवान् नेता दुष्टान् पापाछलार्थिनः।। 37 ।।

कामदेवोपि यः पूर्वं वृत विवर्ज्जितैः।

निर्मिते क्षौमसंछन्नेसंस्तरे सोपधानके।। 38 ।।

अषेयत स एवात्र साधुवृत्या समन्वितः।

तृणकर्करकैर्युक्ते स्थले शय्यां तु सेवते।। 39 ।।

श्वेतछत्रादिभिः पूर्वं कृत धर्म निवारणः।

तथा चन्दनपंकेन प्रलिप्त ह्रदयोपि यः 40 ।।

रवेष्चोष्ण करान् दुष्टान् सोधुनागिरिमस्तके।

सहतेध्यानवान् योगी संसार क्षय हेतवे।। 41 ।।

दिव्यान् सदन्नपानान्यः सद्व्चं जन समन्वितान्।

षड्साधिक संपन्नान् कामिनीभिः सुसोधितान्।। 42 ।।

अभुक्त स्वाद संयुक्तान् यो सौ कामसमाßयः।

सोपवासैस्तु खिन्नांगः कोद्रवान्नम भुंक्तवान्।। 43 ।।

पुराभूपतिवृंदैर्यः सेव्यमानोर्प्यहर्निषं।

विमुच्य सकलां लक्ष्मीं तपोवनमसिश्रियत्।। 44 ।।

स एव मुनिनाथोत्रमोनीध्यानी गुणाधिकः।

वंदितो मरणाथोस्याः विजहार भुवस्तलं।। 45 ।।

विद्याधर नरेन्द्राणां भूभुजां देहजांवधूं।

भुक्त्वा त्यक्त्वा तु वेगेन शश्रियेयो तपोवनं।। 46 ।।

सोपिकांतिं च कीर्त्तिं च क्षमां बुद्धिं तथा दयां।

न त्याजेति मे चित्ते विस्मयः प्रतिभासते।। 47 ।।

षोडषाभरणोपेतं श्रृंगार सर्वभूभुजां।

लोकाष्चर्य करं भेजे कामः कामरसाधिकः।। 48 ।।

सोधुनारागनिर्मुक्तो द्वादषांगैः विभूषितः।

अतोप्यनंग चेष्टाहि लोकैर्ज्ञानं न शक्यते।। 49 ।।

योषितां गीत नृत्यौधैर्निन्पेयो वासरान् पुरा।

तं तादिसुषिरतैष्च वाद्य वृंदैः विमोहितः।। 50 ।।

सोधुना भीमगहणे षिवादैष्च विभीषणे।

कालं नयति योगीन्द्रो धर्मध्यान रसान्वित।। 51 ।।

गजेन्द्रैस्तुरगौधैर्यो रथैष्चन्द्र रथोपमैः।

सेवकैः सेवकैः सेव्य बभ्राम निजलीलया।। 52 ।।

युगांत दृष्टि योगीषोगुप्ति त्रय परायणः।

विजहार महीपूतामात्मकार्ये परं रतः।। 53 ।।

विदग्धाभिस्तु नारीभि गाथा दोहकसंयुतं।

सरसं स्नेह संपूर्णः सत्यासत्यमभाषतः।। 54 ।।

सोत्रषास्त्रानुसारेण मितं सर्वजने हितं।

प्रतिबाधंजमौ योगी सर्वं त्वानुकंपकः।। 55 ।।

स्वर्णरत्नादि पात्रेषु पुत्रभार्यादि संयुतः।

बुभुजे षड्रसैर्युक्तमाहारं योति लीलया।। 56 ।।

सोथदोषैर्विनिर्मुक्तं त्रिषुद्धोक्ति विधानतः।

जग्राह पिंड रक्षार्थमाहारं जिन भाषितं।। 57 ।।

पुत्रैः सर्वगुणोपेतैष्चंचलैष्चित्त हारिभिः।

मुग्धैः प्राणप्रियैरेमे स्नेह युक्तोथयः पुरा।। 58 ।।

एकाकी निस्पृहः शांतो वैराग्यं परमं वहन्।

निरंजनोव सन्नित्यं वनेष्चित्त सहायक।। 59 ।।

शत्रुणां मदमत्तानां स्वसैन्य बलषालिनां।

गर्वहायः पुराचासीत् निजषक्त्या मनोभवः।। 60 ।।

स चात्र परमो योगी दया दम समन्वितः।

षट काय रक्षणे दक्षः पष्यन्नात्म समं जगत्।। 61 ।।

राजमार्गाश्रयात्पूर्णं योवैघात करंवचः।

प्राणिनां भीति जनकं जगौ सत्य विवर्ज्जितं।। 62 ।।

चतुविधं च सद्वाक्यं सत्य पूतं मनोहरं।

जिनेन्द्र वदनोद्भूतं जगौ योगी हितावहं।। 63 ।।

पुराराज्य स्थितोयोहि पर द्रव्यांगनादिकं।

मोषयन् बल संयुक्तोमत्तः पापभयोष्भितः।। 64 ।।

सोधुनापर द्रव्यं हि तृण मात्रं तथा घनं।

मनसा वचसा तन्वागृह्णाति कदाचन।। 65 ।।

पुरा गृहस्थ भावे हि ये ये भोगा मनोहराः।

भुक्त्वा रामादिभिः सार्द्धं पंचेन्द्रिय सुखा वहाः।। 66 ।।

सांप्रतं रागनिर्मुक्तास्तत्सुखं मनसापि हि।

शील नाष करं नूनं नैव चिंतति पुण्यमान्।। 67 ।।

धनैर्द्धान्यै सुरान्यैष्च गजाष्वकांचनादिभिः।

अतृप्तोयं पुराचासीत् प्रभुत्व रससंयुतः।। 68 ।।

सर्वद्वंद्व विनिर्मुक्तः सर्वं सगविवर्ज्जित।

अंतरंग रसासक्त निजदेहे नरादरः।। 69 ।।

त्रिगुप्तिष्च सदागुप्तस्तथासमित पंचके।

रक्तोयोगीष्वरो धीरोगंभीरोरार्णवत्परं।। 70 ।।

अनेन विधिना कामष्चकार दुःसहं तपः।

चारित्रं पालयामास यषसां तु महालयः।। 71 ।।

तपोवनं ध्रुवं युक्तं धीराणां च सुमेधसां।

कातराणां कुबुद्धिनां नैव युक्तं कदाचन।। 72 ।।

अथैकदा हि योगीन्द्रो दिनेचैकादषेतथा।

ध्यान योग्यं वनं प्रापगिरौरिवतके शुभे।। 73 ।।

शुद्धधीः पापनिर्मुक्तो दग्धाराति महारिपुं।

निजदर्षनसामर्थ्याद्धत्वा योसौ महावलां।। 74 ।।

तत्रैव हि वने रम्ये सहकार तरोरधः।

निर्मले जंतु रहिते निविष्टे सौ षिलातले।। 75 ।।

पर्यंकाषन योगेन स्थितो सा ववनिक्षमः।

ध्यानं कर्त्तुं तदा लग्नो निरुद्धमान सोमुनिः।। 76 ।।

कुध्यानं मुमोचासौ रौद्रं श्वभ्रस्य कारणं।

तिर्यगते निर्मित्तं हि तथैवार्त्तं जहौमुनि।। 77 ।।

धर्मध्यान वलेनासौ स्थिरं कृत्वा निजंमनः।

रतोजीव विचारे हि नाषाग्र निहिते क्षण।। 78 ।।

ततः क्रमेण योगीन्द्रः कर्म शुद्धेष्वहेतुतः।

निर्गतस्त रसाधीरः प्रमत्तादि गुणालयात्।। 79 ।।

रुंधयित्वानिजं चित्तं निरवद्यं महामुने।

तदोपरिसमारोढुमुद्यमं कृत वांस्तदा।। 80 ।।

अपूर्वसंज्ञं चक्रं च समत्य क्रमात् सुधीः।

ततो निवृत्तिसंज्ञं च चक्र पापगुणाधिकं।। 81 ।।

क्षयं तत्र गुणा योगी व्यधात्षोडष कर्मणां।

तस्यार्द्धे प्रथमं प्रोक्तं कृयंतेषां जिनष्वरैः।। 82 ।।

निद्रानिद्रात्रिकस्यापि स्वभ्रतिर्यग्गतेरपि।

सूक्ष्मत्वस्थावरस्यैवोत्रापि साधारणस्य च।। 83 ।।

प्रत्याख्यानेतराणां चाष्ठं संख्यान्वितात्मनां।

नीच वेदद्वयस्यापि क्षयं चक्रे मुनीष्वरः।। 84 ।।

हास्यादीनां षणांयाहि सम्यकत्वस्य विनाषिनी।

क्रोधादीनां त्रयाणां वैक्षयंतु कृतवान्मुनि।। 85 ।।

सोनुसंज्वलकानां हि लोभं संज्वलनाभिधं।

गुणानां निलयं सूक्ष्मसांपराये जहौ परां।। 86 ।।

क्षयं चक्रे तदा योगी निः शेषघाति कर्मणां।

द्वादषे हि स्थितः स्थाने यांति कर्म विनाषिनि।। 87 ।।

आद्यंतमुक्त संजातं हीनं सर्वमसुन्दरं।।

विषेषात् क्रमरणं ध्यानात् कि न वाप्यते।। 88 ।।

प्रायेन रहितं रम्यं लोकालोक प्रकाषकं।

सष्भानं केवलाभिख्यं सां प्राय मदनो मुनि।। 89 ।।

करणातीत सुखंस्यात्र कारणं प्रमदावहं।

आत्मनोपि हितं रम्यं पुण्यहीनैर्न्न वाप्यते।। 90 ।।

एकं छत्रं तथा दिव्यं सच्चामर युगं वरं।

भद्रासनं मनोहारि समभूदेव निर्मितं।। 91 ।।

कृतागंधकुटी दिव्यां धनदेन सुभक्तितः।

ष्शक्रादेषं समासाद्य ज्ञान कल्याण कारणं।। 92 ।।

दैत्याष्चनाग देव्याष्च किंनराद्याष्च व्यंतराः।

शक्राद्यास्त्रिदषाः सर्वे ज्योतिष्का भास्करादयः।। 93 ।।

खेचरेन्द्राः सयोषाष्च नरेन्द्राद्या नरोत्तमाः।

यादवानां समूहास्तु विष्णुसीरीयुधादयः।। 94 ।।

शम्बाद्याष्चारु लीलाष्च शुभवेष समन्विताः।

भक्तियुक्ता वृषेरक्तो वेषाद्धर्ष समन्विताः।। 95 ।।

आगत्यचाति वेगेन गिरौरेवतकाभिधे।

मुनीन्द्रो मदनोनाम प्रणम्य परयामुदा।। 96 ।।

जलगंधाक्षतैपुष्पैष्च रुचीयैस्तु निर्मलैः।

धूपै रम्य फलौघैस्तु चक्रुः पूजां परां तदा।। 97 ।।

गीतनृत्यैर्वरैर्भक्त्या वीणावंष मृदंगकैः।

वाहनरुढाः समागत्य यादवा भक्ति नोदिताः।। 98 ।।

पंचागं प्रणुति कृत्वा निविष्टाः पुरतो भुविः।

विनयेनान्विता चक्रु धर्मस्य श्रवणं मुदा।। 99 ।।

श्रुत्वा धर्मं जिनेन्द्रोक्तं नीत्वा नियम पद्धतिं।

नत्वापुनर्मुनिं यावत् यादवास्ते यथा यथं।। 100 ।।

श्रीमान् मदन योगीन्द्रो लब्ध बोधोथनेमिना।

विहर्तुं विबुधा कीर्णोदेषं पल्लवकं ययौ।। 101 ।।

आर्या या रुक्मिणीनामा सा शीलगुणभूषिता।

जातात्र सस्तुषाचैकादषांग श्रुत धारिणी।। 102 ।।

राजीमत्या समेता सा विषयं पल्लवाभिधं।

नेमिनाथेन संजाता भीता संसारतो ध्रुवं।। 103 ।।

विहारं परमं चक्रे नेमिनाथो जिनेष्वरः।

सत्संघाटक संयुक्तस्तावदन्यत्कथांतरं।। 104 ।।

अथ द्वीपायानो योगी गच्छत्सुपरमावधिं।

ज्ञात्वा गतानि वर्षाणि संख्या द्वादषकान्यपि।। 105 ।।

द्वारिकां दृष्ट मामोसौ विपर्यासात्सामगतः।

वक्तुं यादव संघस्य भयस्य नाषनं निजं।। 106 ।।

ग्रीष्मकाले षिलायां हि पुरी बाह्ये स्थितो मुनिः।

प्रकटकृतकामोहि यादवानां निजं तपः।। 107 ।।

यादवाधीष तनयाः शम्ब सत्या सुतादयः।

तद्दिनादौ गतारंतु पूर्धं रैवतकाचलं।। 108 ।।

तेपि ग्रीष्मस्य तापेन जाता तृष्णातुरावने।

पष्यंतोथ जलं सर्वे वभ्रमुर्वैदिषोदषः।। 109 ।।

पूर्वमद्यस्य भांडानि त्यक्त्वानि तु नृपाज्ञया।

जातानिगिरिटंकेषु जलैर्मेघागमे सदा।। 110 ।।

पतंति शुभ्र पुष्पानि विविधानिमरुद्वषान्।

विषेषतोपि तज्जातं मद्यमुन्मत्तकारणं।। 111 ।।

दृष्ट्वा तृषापुरेः सर्वेः पीतं तद्या दवांगजैः।

अन्मत्तास्ते ततो जातो मद्यतो रक्तलोचनाः।। 112 ।।

गायंतो विविधान् गीतान् वदंतः सत्यवज्जितं।

परस्परं हि वलांते लुंठति भुवि मंडले।। 113 ।।

कर्णमूले लगित्वा तु वार्त्तां सत्योष्भितांक्षणं।

कुर्वंतस्ते तदा सर्वे चलिताः स्वांपुरीं प्रति।। 114 ।।

केषैस्ते षिथिलैर्युक्ताः पुरीद्वारे समागताः।

तावत् तत्र स्थियो दृष्टः कृषांगोमुनि नायकः।। 115 ।।

कथंचिद्दैवयोगेनोपलक्षैन मुनीष्वरं।

जैनं वाक्यं च ते स्मृत्वा जग्मुः कोपं तदाघनं।। 116 ।।

कुचुस्तेमीवचः सर्वेरोष रक्त निरीक्षणाः।

नेमिनाथेनयः प्रोक्तः सोयं पुर्या विनाष कृत्।। 117 ।।

नकारोति दुराचारो निजपुर्या विरुपकं।

तावर्द्वहन्यतां वेगादिति सर्वे जगुस्तदा।। 118 ।।

इत्युक्त्वा लोष्टभिः दुष्टैः पाषाणै रोषपूरितैः।

तावद्वतो मुनिर्यावद्भूमौ नैव पपातसः।। 119 ।।

तयापिमुनिना चित्ते क्रोधं नैव कृतं परं।

मस्तके लघुषंकातै मातंगात्कारिता मुनेः।। 120 ।।

तया सौरोष संपूर्णां पपात वसुधाले।

मुनिः कंठगतः प्राणः कुमारास्तु पुरीं गताः।। 121 ।।

तावत् बुद्धिस्तु संजाता बलनारायणस्य सा।

वेगात्तत्र समायातौ यात्रासौ पतितो मुनिः।। 122 ।।

प्रणम्यपरया भक्त्या प्रोचतु सौ मुनीष्वरं।

मूर्खे हीनवयोभिष्च यत्कृतं तत् च क्षम्यतं।। 123 ।।

त्वयोगीन्द्रः क्षमाधारः कृपया परिभूषितः।

बालानां मूढचित्तानां क्षमस्वदुःकृतंविभो।। 124 ।।

अंगुलीभ्यां तदा चक्रे सज्ञां वाक्येन तेन सा।

समस्तायां ध्रुवं पूर्यां मोचनीयौ बलाच्युतौ।। 125 ।।

शेषेना रक्तनेत्रस्य ज्ञात्वास्य चित्तदौष्ट्यता।

बलनारायणौ वेगात् गतौ पूर्यां भयाकुलौ।। 126 ।।

कथितं सवेलोकानां जीव्यते येन यत्रवै।

तेन तत्रैव गंतव्यमत्र नाषो भविष्यति।। 127 ।।

शम्बुः सुभानुसंज्ञष्च तथा मदन नंदनः।

तेन वाक्येन संबुद्धा नत्वा तातपदांबुजं।। 128 ।।

यादवा बहवः श्चापि चरमांगा काल लब्ध भाक्।

हरि वाक्येन सा बोद्ध सुंदराभव भीरुकः।। 129 ।।

मोहपाषौसमत्यक्त्वा निर्गतः पुर वेगतः।

तावत्तत्र समादृष्टा दहनानलवापुरीं।। 130 ।।

नेमिनाथस्य वचसा गत्वा रैवतकं गिरिं।

कराभयां केषनिचयं निराकृत्याति वेगत।। 131 ।।

त्यक्त्वा वस्त्रादिकं सर्वं भूषनं लोक दुल्लर्भं।

वैराग्येणैवतैः नीतं चारित्रं परमोज्वलं।। 132 ।।

द्वारावत्या विनाषादि कृष्णस्य मरणादिकं।

यदुक्तं तत्पुराणेवै प्रोक्तं श्री हरिवंषके।। 133 ।।

असुन्दरतया नूनं नोक्तं दुःखकरं नृणां।

शम्बाद्यामुनयस्तेमीतपः कर्त्तुं समुद्यताः।। 134 ।।

नाना भेदं जिनेन्द्रोक्तं परेषामति दुर्लभं।

सहंते दुःसहं धीराः क्षत्पिपासाद्यनेकधा।। 135 ।।

आर्त्तरौद्रं परित्यज्य धर्म शुक्ले च तेरता।

नेमिनाथं तु संप्राप्ता कुर्धंते विविधं तपः।। 136 ।।

निन्युस्तेवैपुनः दीक्षां नेमिनाथ करेणहि।

बाह्याभ्यंतर भेदेन षटद्विभेदं तपोवरं।। 137 ।।

गुणानां निलयास्तेमीषील लीलाविभासुराः।

तपः कर्त्तुं समुद्युक्त्वा निरेछामुनयो वराः।। 138 ।।

यत्रास्तंतु रविर्याति तत्र तिष्टंति ते ध्रुवं।

प्राषुके भूमिदेषे वै कृत्वा जैनीं निजांक्रियां।। 139 ।।

हेमांतेबाह्ये भूमौ वै वायु शीतल के तथा।

स्थित्वातत्र निषां निन्यु वैराग्या हित चेतसः।। 140 ।।

गीष्मेधर्मा कुले ते वै चटित्वा गिरिमस्तके।

तत्रातापनयोगस्थाः कालं निन्युः सुखेनते।। 141 ।।

वृक्षमूले स्थिते संतो वर्षा काले मुनीष्वराः।

गमयंति सुखेनैते कालं धर्मं रसान्विताः।। 142 ।।

मुक्तारत्नावली चैवद्वैकाल्पाद्यनेकषः।

सिंह विक्रीडनाभिख्यं सर्वतो भद्रकं तथा।। 143 ।।

एवमादीन्यने कानि तपांसि गुण मंदिराः।

कृत्वाते मुनयोधीरा ध्यानयोग समन्विता।। 144 ।।

ततष्चतुर्दषेवर्षे पर्यंकाषनः योगत।

घातिकर्म क्षयंचक्रुर्निज ध्यान बलेन ते।। 145 ।।

क्षपक श्रेणिमारुढा हत्वा पाप महानथं।

केवलज्ञानमापुस्ते लोकालोक प्रकाषकं।। 146 ।।

नेमिनाथोपितैः सार्द्धं विजहार भुवस्तलं।

भव्यराषिं तु सम्बोध्य जिनधर्मं प्रकाष्यवैः।। 147 ।।

सुरासुरगुणैः सर्वैर्न्नरेन्द्रैः खेचरैस्तदा।

विहर्त्त्यं वसुधां दिव्यां वंद्यमानः पदे पदे।। 148 ।।

धृत्वामोहांधकारं सलोकानां हृदय स्थितं।

प्रोच्यधर्मं त्रिलोकीं वै स्वर्ग मोक्षप्रदं परं।। 149 ।।

ऊर्ज्जयंतं गिरिं प्राप्य सुरासुर नमस्कृतं।

तत्रसिद्धि षिलां प्राप्य पर्यकासन् योगतः।। 150 ।।

ध्वस्तनिः शेष कर्मासौ हत्वा प्रकृति संचयं।

सिद्धिस्वरूपं संप्राप्तो जरामरण वर्ज्जितं।। 151 ।।

श्रृंगत्रयं नगस्यास्य भूषितं तैस्त्रिभिःपरं।

अनुरुद्ध कुमारेण श्रृंगमाद्यंपवित्रितं।। 152 ।।

द्वितीयं शम्बुमुनिना कामेनापि तृतीयकं।

एवं श्रृंग त्रयं तस्य भूषितांतै कुमार कैः।। 153 ।।

ऊर्ज्जयंत गिरिर्ज्जातस्तदादि वसुधातले।

सिद्धक्षेत्र तया ख्यातिं सुरासुरनमस्कृतः।। 154 ।।

यत्र यत्र गतामुक्तिं मुनयो ज्ञान भूषिताः।

नेमिनाथा दयोप्येते कामाद्याः कर्म वर्ज्जिताः।। 155 ।।

तत्र तत्र समागत्य वासवाद्याः सुराध्रुवं।

शरीरं ज्वालयामाषुस्तेषां ते चंदनैः शुभैः।। 156 ।।

उत्सवं परमं कृत्वा भक्ति पूजादि पूर्वकं।

गिरौश्रृंग त्रये चापि सुरास्ते श्रद्धयान्विता।। 157 ।।

षिवता प्रार्थिनः सर्वे विभूत्या परयायुताः।

गीत नृत्यादिकं कृत्वा गतास्तु स्थानकं निजं।। 158 ।।

(अन्त मंगल)

येवैज्ञानविभूषिताः सुरनताः सिद्धिं गता निर्मला।

क्षुत्कृष्णादि कराग रोष रहिता येषांमनोनिष्चलं।

ये ये जन्म जरा वियोग मरणत्रासादिभि वर्जिता।

स्तेर्हंतो मम मंगलं प्रतिदिनं कुर्वन्तु पापावहा।। 159 ।।

आषायानैव पाषो गृहगुणानि वहोनैव मृत्युर्न जन्मनो।

मारीनैव बंधुः स्वजन परिजनो नैव सौख्यं न दुःखं।। 160 ।।

दषावतारो भववारितारो वंषे यदूनां गुणा रत्नंहारः।

य कृष्ण वर्णोपितमोपहारः सो नेमिनाथो विदधातु शांतिं।। 161 ।।

जन्मन्येवहृतोरिणाति विषमे क्षिप्तः परं संकटे।

तत्रस्थोपि खगेष्वरेण वलिना नीतो निजं मंदिरं।

विद्यालाभ समन्वितो निजकुलं संप्राप्यवै पुण्यत।

यो मुक्तिं गावान् ददातु विपुलं कामोपि सौख्यं मम।। 162 ।।

यः शंब संज्ञोहरिराज सूनुः कामानुजोयो गिरिराजश्रृंगे।

मुक्तिंगतो ज्ञान गुणैः समेतः पापं मदीयंह्यधुना तु सोयं।। 163 ।।

श्रीकामदेव तनयो बहु रूपशोभी।

विख्यात मूर्त्ति गुण कीर्त्ति पराक्रमौघैः।

यः शैलराज षिखरं विदितं चकार।

सोमेनुरुद्धमुनिपो विदधातु सौख्यं।। 164 ।।

(शास्त्रस्य माहात्म्य)

एतत् प्रद्युम्न संज्ञं परमगुणानिधिं शास्त्रमानंदकारिं।

ये वै श्रृण्वंति भव्याः प्रविपुलमतयो भाषयंत्यादरेण।

लक्ष्मी सौभाग्य राज्यं नृसुरगति भवं प्राप्य सौख्यं पवित्रं।

निर्वाणां यांति नूनं यति कुलमहिताः केवलज्ञानमाप्य।। 165 ।।

ग्रन्थकर्त्ता की प्रार्थना

नो जानामि सुषब्दमनघं काव्यानि तर्कादिकं।

सालंकार गुणैर्युतोति नियतं जानामि छन्दासिन।

नो कीर्त्यादिसुवांछया नहि परं मानाभिभूतेनवै।

यत्प्रोक्तं हि मया चरित्रमनघं पापायनोदायतु।। 166 ।।

ये ये भव्य जना विषुद्ध मतयः शास्त्रस्य पारंगताः।

संतोयेत्र परोपकार कुषलाः पापेनये वर्ज्जिताः।

तैः संषोध्यचरित्र मेतदमलं विस्तारणीयं क्षितौ।

प्रोक्तं मंदधिया मया गुणनिधेः श्रीकामदेवस्यत्।। 167 ।।

ग्रन्थकर्त्ता का परिचय–

नदीतटाखे विमले सुगच्छे श्री रामसेनोगुणवारि राषिः।

बभूव तस्यान्वयषोभकारी श्रीरत्नकीर्त्तिर्दुरितापहारी।। 168 ।।

श्री लक्ष्मसेनोत्र ततो बभूव शीलालयः सर्वगुणैरुपेतः।

तस्यैव पट्टोद्धरणैक धीरः श्रीधर्मसेनः प्रगुणः प्रवीरः।। 169 ।।

श्रीभीमसेनस्य पद प्रसादातु सोमादिसत्कीर्त्तियुतेनभूमौ।

रम्यं चरित्रं विततं स्वभक्त्या संबोध्य भव्यैः पठनीयमे तत्।। 170 ।।

संवत्सरे सत्तिथि संज्ञके वैवर्षेत्रत्रिंषैकयुते पवित्रे।

विनिर्मितंपौष सुदेष्य तस्यां त्रयोदषीया बुधवार युक्ता।। 171 ।।

यावन्मेरुमहीतलेति विदिमोयावद्रवेर्मंडलं।

यावद्रूपलय परं ग्रह गणाया वत्स तां चेष्टितां।

तावन्नंदतु शास्त्र मेतदमलं श्रीषांति चैत्यालये।

तावन्नं न विनिर्मितं सुखकरं तस्यास्तुवै सर्वदा।। 172 ।।

यावन्मेरुमहीयावत् चन्द्रार्कग्रहतारकाः।

तावन्नं दत्वहं नूनं चरित्रं पापनाषनं।। 173 ।।

प×चसहस्रसंख्यात् ग्रंथोयं भुवि विश्रुतः।

भूतले सततं जीया श्रीसर्वज्ञ प्रसादतः।। 174 ।।

***इतिश्री प्रद्युम्नचरिते श्रीसोमकीर्त्याचार्यविरचिते श्रीनेमिनाथप्रद्युम्नशंबु–**

–अनुरुद्धादि निर्वाणगमनोनाम

षोडश सर्गः*

यादृषंपुस्तकं दृष्ट्वा तादृषं लिखितं मया।

यदि शुद्धमषुद्धं वा मम दोषो न दीयते।। 01 ।।

शतसप्तदषोत्तरे गते संवते मन्वब्दः बुधवासरे।

आष्विनि शुक्ल हरिवासरे मुदा मुरलिना लेखि गोपपर्वते।। 01 ।।

।। श्री ।। ।। श्रीराम सहाय।।

श्री आचार्य यशकीर्त्तिस्य पुस्त्येषा।

चैत्यालय निवासिन्नः प्रभोः।

कल्याणं ददातु नितरांते मुरलिना सह शतं समाः।। 02 ।।

समीक्षा खण्डम् :–

धर्मः द्वौ प्रकारौ स्तः। एकः सागरधर्मः द्वितीयः अनागरधर्मः। सागरधर्मः गृहस्थानां कृते यतिनाम् कृते अनागार धर्मः। यातिधर्मेण मोक्षस्य प्राप्ति र्भवति। ग्रहस्थ धर्मेण स्वर्गादिकं प्राप्ति र्भवति। अनागार धर्मस्य त्रयोदष भेदाः सन्ति। प×चमहाव्रत–अंहिसा–सत्य–अस्तेय–ब्रह्मचर्य–अपरिग्रह, प×चसमिति–ईर्या–भाषा–एषणा–आदान–निक्षेपण। तिस्रः गुप्तयः मनोगुप्ति– वचनगुप्तिः काय गुप्तिष्चेति। सागर धर्मस्य द्वादष भेदाः सन्ति। प×च अणुव्रतः त्रिस्रः गुणव्रतः (दिग्व्रत–भोगोपभोग–परिणाम) अनर्थदण्डत्यागः, षिक्षाव्रतः पंचोदुम्बरः, मद्य–मांस–मधु मकार त्रयस्य त्यागः एते गृहस्थानाम् कृते सुखस्य दातारः सन्ति। परम्पराया मोक्षस्य साधकः भवति।

अनेन श्रवणेन श्रेणिक नृपं धर्मस्य श्रवणेन अपार आनन्दं प्राप्तं चेत् भव्यात्मानाम् धर्मकथायाः सन्तोषः भवति। इत्थं श्रवणानन्तरं नृपः श्रेणिकः निवेदन कृतम् हे भगवन् कृष्णनारायणस्य पुत्रः प्रद्युम्नस्य चरित्रं श्रोतुं इच्छामि। सः प्रद्युम्न कुत्र उत्पन्नं जातं तं शत्रूं केन माध्यमेन हरितं तं सर्वं श्रोतुं इच्छामि। नृपस्य प्रष्नं श्रुत्वा भगवानः वीरनाथः प्रसन्नो भूत्वा भगवान श्रीकृष्णस्य पुत्रः प्रद्युम्नस्य चरित्रं वर्णनं कृतम् । इति प्रथम सर्गे प्रतिपादितम् अस्ति। अस्य श्रवणे किं फलं प्राप्तिः अपि भवति तस्यापि वर्णनं कृतमस्ति।[51]

द्वितीयसर्गेः– जम्बूद्वीपस्य वर्णनं तस्य दक्षिण दिषि भरत क्षेत्रः शोभायमानः भवति। सः तीर्थ कराणां पंचकल्याणक स्थानेषु एकः तीर्थस्वरुप पापस्य निवारकः कल्याण प्रदान कर्तारः तत्रागछन्ति। तस्मिन् भारत क्षेत्रे सौराष्ट्र नामकः देषः यः पूण्यात्मानाम् कृते स्वर्ग सदृषमस्ति। यत्र सरोवरः पुष्पवाटिकाः विविधवृक्षाः विविधकृषिकार्याः नित्यप्रतिदिनं भवति। एतादृषः द्वारकानगरी सर्वाङ्गीण रूपेण विकास रूपेण इयं प्रसिद्धः द्वारका नगरी। नगरस्य चतुः पार्श्वे समुद्रः शोभायमान भवति। देष देषान्तर जनाः तत्रागत्य मनुष्येभ्यः तां नगरीं शोभां अभिवर्द्धयति इति द्वारका नगर्याः वैषिष्ट्यमेव[52]

तृतीयसर्गः– एकस्मिन् समये राज्य विभूत्या मण्डितो भूत्वा श्री कृष्णः स्व बान्धव जनानां महति सभायां विराजमान् आसीत्, तदा आकाष मार्गेण एक तेज पु×जम् आयान्तं दृष्ट्वा महदाष्चर्यमभवत्। यत् सूर्यमयी अग्नि पु×जः इव प्रतीयते। यदा अग्नि पु×जः अत्यन्त निकटे आगतः तदा सर्वे ज्ञातं यत् अयं तु महर्षिः नारद एव अस्ति।

श्रीकृष्णः तत्क्षणे सन्मुखं गत्वा नमस्कारमकरोत्। चरण प्रक्षालनं कृत्वा अर्घ्यम् अर्पयत् अतिथि सत्कारं च अकरोत् तस्मिन् काले श्रीनेमिनाथ स्वामी अपि तत्र आगतवान् तदा नारदः श्रीकृष्णस्य आज्ञां प्राप्य अन्तः पुरं प्रेक्षणाय अन्तः प्रविष्टवान् सर्वाङ्őसुन्दरीं सत्यभामामवलोक्य तस्या अहङ्ारं मर्दनाय विचारमकरोत् एकदा नारद आकाषमार्गेण गच्छति स्म। दैव वषात् सः कुण्डनपुर नामके रमणीय नगरे प्रविष्ठवान् यत् लक्ष्म्याः निवासः रूपवतीनां विद्यावतीनां गुणवतीना×च स्थानमासीत्। नगरेऽस्मिन् भीष्म नामक राजा आसीत्। अस्य राज्ञः श्रीमती नामनि साम्राज्ञी आसीत्। या गुणवती–मायाचारवर्जितायाः सुन्दरतायाः खानि जगद् विख्याता च आसीत् । अस्य राज्ञः भीष्मस्य पुत्री रुक्मिणी आसीत् या च जगति प्रसिद्धा आसीत्। चेदिराज षिषुपालः आसीत् यस्मै रूप्यकुमारः गुरूजनैः बान्धवैर्विना परामर्षे रुक्मिणी दानस्य वचनमददात्। नारदः उक्त कथानकं सम्पूर्ण श्रीकृष्णाय निवेद्य अकथयत् यत् सा तव नाम्नः एव जीविता अस्ति। तदा श्रीकृष्णबलदेवयोः प्रमदोद्यानगमन वृत्तान्तमभवत्।[53]

चतुर्थसर्गः प्रमदोद्यानं नन्दनवन इव सुमनोहरमासीत्। नारदः द्वारिका नगरीतः प्रस्थानं कृत्वा चेदिराज षिषुपालस्य समीपं आगच्छत् तथा षिषुपालतः रुक्मिणी षिषुपालयोर्विवाहस्य लग्न पत्रिकामदृासीत्। कलह प्रिय नारदं महती चिन्ता अभवत्। नारदस्य कथनानुसारं रुक्मिणी वनयात्रां प्रति प्रस्तुतवती जाता। तत्र द्वारिकाधीषः श्री कृष्णस्य उपस्थिति आसीत्। रुक्मिणी श्री कृष्णं बलदेव×च रूप्यकुमार द्वारा चेदिराज षिषुपालाय दानस्य चर्चायाः विषये अकथयत् तदा लक्ष्मीपतिना कृष्णेन कथितं यत् अहं तं क्षणमात्रे एव जेतुं सक्षमोऽस्मि।

इदं सर्व विलोक्य नारदः प्रसन्नौऽभवत्। तस्मिन् वने बलदेवः कृष्ण रुक्मिण्योः पाणिग्रहणमकारयत्। तथा द्वारिकां प्रति प्रस्थितवन्तः सर्वे। रुक्मिणी सत्यभामा च परस्परं भुजयोरालिÄőनमकुरुताम्। श्रीकृष्णः षिषुपालं जघान। अनेन षिषुपालस्य वधः रुक्मिणी श्रीकृष्णस्य च विवाहः सत्यभामायाः विडम्बना गर्भस्थ षिषोः सम्बन्धस्य च वर्णनं चतुर्थ सर्गे वर्णितमस्ति।[54]

पचिम्सर्गः– प×चमे् सर्गे सत्यभामायाः रुक्मिणी द्वारा मानमर्दनस्य तथा रुक्मिणी सत्यभामयोः वार्तालापस्य वर्णनम् अस्ति। रुक्मिणी द्वारा मदनोत्पत्तेः सूचकानि षड् विधानि स्वप्नानि दर्षनस्य वर्णनमस्ति।

प्रथमस्वप्ने–रुक्मिणी आत्मानं विमाने आरुढवती–राज्यवैभव सहितम् आकाष मार्गे क्रीड़ारता अपष्यत्।

द्वितीयेस्वप्ने–इन्द्रस्य ऐरावत सदृष हस्तिनं स्वकीये समीपे आरुढवन्तं गर्जनवन्त च अपष्यत्।

तृतीयेस्वप्ने–उदयाचल पर्वते उदयमानं कमलानि च विकसितवन्तं सूर्यं ददर्ष।

चतुर्थेस्वप्ने— धूमरहितमग्निमपष्यत्।

पचिमेस्वप्ने—कुमुदं सम्मुल्लसितवन्तं चन्द्रमपष्यत्।

षष्ठेस्वप्ने— स्वकीय सन्मुखे गर्जायमानं समुद्रमपष्यत्।

एतच्छ्रत्वा श्रीकृष्णः प्रसन्नतामनुभवन् स्वकीयां प्राणबल्लभां जगाद यत् निष्चितमेव आकाषगामी, मोक्षदायी च पुत्रस्य जन्म भविष्यतीति। राज्ञः मधोः जीवः नाना विध तपष्चर्यया षोडषोस्वर्ग रुक्मिणी गर्भे प्राप्त तस्मिन् एवकाले सत्यभामा अपि गर्भवती बभूव। नवमेमासि व्यतीते रुक्मिणी गर्भात् उत्तमतिथि—षुभनक्षत्र—षुभ करणयोगे प×चाङõ शुद्धौ च पुत्ररत्नं प्राप्तम्।

जन्मनः षष्ठे दिवसे बालकस्यापहरणमभवत्। अतपरं विजयार्द्धपर्वतस्य अपि वर्णनं मिलति। तस्य बालकस्य सर्वाङõवर्णनं अपि प्राप्यते। महाराज कालसंवरः तं बालकं युवराजपदे अलङ्कृतवान्। कालसंवरः मेघकूटस्य नृपतिरासीत् तथा तस्य पत्न्याः नाम कनकमाला आसीत्। ये विद्याधर विद्याधरी च आस्ताम्। प्रत्येकस्य ललनायाः परिजनानां च सः प्रद्युम्नकुमारः प्रेमपात्रं अभवत्। तस्य जन्मतः एव राज्ञः यषः दिनाद्दिनोत्तरं चतुरगुणां बृद्धिमाप्नोत् विस्तरेण वर्णितमिदम् अस्मिन् सर्गे।[55]

षष्ठम् सर्गः—बालकस्यापहरणात् रुक्मिणी चिन्ताकुला जाता तस्य अचेतावस्थायाः विलापस्य च वर्णनं प्राप्यते। श्रीकृष्णेन सान्त्वना दानस्य नारदस्य समीपे दुःख प्रकटीकरणस्य च विवेचनं षष्ठे सर्ग प्राप्यते। पुण्डरीकिनी नगÕर्याः श्रीसीमंधर स्वामिनः चतुर्धागतीनां देवगति—मनुष्यगति—तिर्य×चगति—नरकगतीना×च वर्णनं मिलति। साकमेव शालिग्राम नामक नगरस्य, श्री नन्दिवर्धन स्वामिनः द्विजपुत्राणां अग्निभूतिः वायुभूतिः पुत्रे वर्णनं प्राप्यते।

रत्नत्रयस्य, प×चविंषतिदोषाणां, i×चअणुव्रतानां, चतुर षिक्षा व्रतानां, गुणव्रतस्य, द्वादष विध सागार धर्मस्य अपि विवेचनम् अस्ति। एवं प्रकारेण नारदमुनेः महा विदेहं प्रति गमनम् श्रीसीमन्धर स्वामिनः समवषरणे गमनं, चक्रवर्तिनः प्रष्नानुसारं दिव्यध्वनि द्वारा प्रद्युम्नस्य पूर्वभव सम्बन्धिनः अग्निभूति, वायुभूत्योः स्वर्ग प्राप्तेः वर्णन विद्यते सर्गेऽस्मिन्।[56]

सप्तमसर्गः— अस्मिन् सर्गे कौषल नामक देषस्य वर्णनं अस्ति। अत्रत्या निवासिनः सज्जनाः कुबेर सदृषा धनवन्तः धर्मकर्मणः आचरणं कुर्वाणा न्यायात्पथे संचरणषीलाः प्रभावषाली गुणानां धारका आसन्। कौषलदेषस्य राजधानी अयोध्या आसीत्। अत्र अरि×जय नामकः राजा राज्यम् अकरोत्। अयोध्यायां समुद्रदत्त नामा श्रेष्ठिः

निवसतिस्म्। यः जैन शास्त्र ज्ञाता गुरोरूपासकः दयालुष्च आसीत्। सर्गेऽस्मिन् महेन्द्रसूरेः विवेचनं अष्टविध कर्मणां च वर्णनं अस्ति।

कुत्ती चाण्डालयोर्वृर्त्तान्तः ये पूर्वभवे श्रेष्ठ पुत्राणां पितरौ आस्ताम् एतदपि वर्णनं समासेन कथितमस्ति। अनेन साकमेव प्रद्युम्नकुमारस्य तृतीय भव सम्बन्धी मणिभद्र पूर्णभद्र श्रेष्ठि पुत्रयोः धर्मस्वरूप श्रवणस्य स्वर्गलोक गमनस्य वर्णनं प्राप्यते।[57]

अष्टमसर्गः— कौषलदेषस्य देवदानव सेवित नगरे पÁनाभ नामको राजा राज्यं करोति स्म। तस्य भार्या ''धारणी'' आसीत् या रूपवती—ष्यामा—गजगामिनी—नवयौवना—सर्वाङõसुन्दरी इन्द्राणी पार्वती सदृषा आसीत्। राज्ञी धारण्याः कुक्षौ शुभ लक्षण सम्पनौ द्वौ पुत्रौ समुत्पन्नौ तयोः एकस्य नाम मधु अपरस्य च नाम कैटभः आसीत।

राज्ञः हेमरथस्य तथा साम्राज्ञी चन्द्रप्रभायाः अपि विवेचनं सर्गे अस्मिन् प्राप्यते।

'' परस्त्री गमनं नूनं देव द्रव्यस्य भक्षणं।

सप्तमं नरकं यांति प्राणिनो नात्र संशयः।।''

नृपतिः मधु द्वारा प्राप्त वैराग्यस्य, कृष्णपुत्रस्य वृत्तान्तः रुक्मिणीः प्रसन्नतायाः वर्णनं अस्ति।[58]

नवमसर्ग— अस्मिन् सर्गे पूर्वभवस्य प्रभावेण प्रद्युम्नकुमारः राज्ञः कालसंवरस्य प्रसादे स्वकीय रमणीयताः चित्तं वषीकरणं कालसंवरस्य ऋद्धि—सिद्धि, धन धान्य वृद्धिः तथा प्रद्युम्नकुमारस्य शास्त्राणां शस्त्र विद्यायां च प्रवीणतायाः वर्णनं प्राप्यते।

कालसंवरस्य कनकमालायाः अतिरिक्त प×चषतं साम्राज्ञीनां प×चषतं विद्याविषारद पुत्राणां च वर्णनं अस्ति। विजयार्द्ध पर्वतस्य अलङ्ार नाम्नः नगरस्य तत्रस्थे कनकनाभि राज्ञः अनिला नाम्नी साम्राज्ञी तस्य पुत्र हिरण्यनाभेः तथा गुरु श्री पिहिताश्रवमुनिराजस्य वर्णनं विद्यते।

सर्गेऽस्मिन् भयङ्ार देव रक्षिता वाप्याः दर्षनस्य वर्णन अस्ति। प्रद्युम्नकुमारस्य मकरकेतु नाम्नः प्रसिद्धि, एकस्य मुकुट प्राप्तेः द्वे आकाषगामी पादुके प्राप्ति वर्णनं मिलति। शरावास्य पर्वत, बराहमुख नाम्नः शंखस्य, पुष्पमयी धनुषस्य प्राप्ति, इन्द्रजाल नाम्नी विद्या प्राप्तेः, कालवन नाम्नः वनगमनस्य, भीमा गुहायाः

सुन्दरषÕयायाः प्रभंजन नाम्नः विद्याधर स्वामिनः तस्य पत्नी वाक् पुत्री रतेः तथा रतिप्रद्युम्नयोः विवाहस्य वर्णनं अस्ति।

सोमशर्मणः तस्य पत्नी कमलायाः तथा तस्य पुत्री लक्ष्मीवती तथा तस्या बहुविध जन्मनां वर्णन विवेचितमस्ति। साकमेव कुण्डनपुर नाम्नः नगरस्य तत्रस्थस्य राज्ञः भीष्मस्य तथा तस्य पु=याः रुक्मिण्याः षिषुपालाय दानस्य पूर्व वर्णनं प्राप्यते। अनेन प्रकारेण षोड्ष लाभानां विद्याना×च प्राप्तेः पितृणां भातृणा×च विरोधः नारदस्य आगमनं इदं सम्पूर्णं विवेचनं नवमे सर्गे वर्णितमस्ति।[59]

दशमसर्गः— प्रद्युम्नकुमारस्य नारदस्य राज्ञः कालसंवरस्य तथा साम्राज्ञी कनकमालाया वार्तालापो। नारद ऋषेः यषोगानं तथा व्रतधारी नारदद्वारा कथनानुसारं प्रद्युम्नकुमार द्वारा स्वकीय यषोराषि इव एक श्वेत विस्मयकारी विमान रचनायाः वर्णनमस्ति। नारदेन सह प्रद्युम्नस्य स्वकीय मातरं पितरं प्रति प्रस्थान मार्गे गगानद्याः वर्णनं। हस्तिनापुरस्य कुरुवंषस्य विवेचनं तथा च अम्बा—अम्बिका अम्बालिकानां तेषां पुत्राणां धृतराष्ट्र—पाण्डु—विदुर आदिभिर्साकं गांधारी—कुन्त्योः परिचय विवेचनं।

कर्ण—दुर्योधन—युधिष्ठिर दुर्योधनस्य पु=याः उदधि कुमार्याः उल्लेखो मिलति। प्रद्युम्न द्वारा कीरात वेष धारणस्य तथा उदधि कुमार्याः अपहरणस्य वर्णनं अस्ति। प्रद्युम्नकुमारस्य भानुकुमारस्य च मेलनस्य वार्तालापस्य तथा प्रद्युम्न प्रज्ञप्ती कर्ण पिषाच्याः वर्णनं अस्ति।

ब्राह्मणेषु त्रिपाठी—चतुर्वेदी—द्विवेदी प्रभृतिनां उल्लेखः प्राप्यते। रुक्मिण्याः क्षुल्लकवेषधारी प्रद्युम्नस्य वार्तायाः वर्णनं मिलति।

''भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्'' इत्यस्य प्रद्युम्नस्य मातृमेलनं सैन्यस्य तत्परतायाः विवेचनम् सर्गे प्राप्यते।[60]

एकादशसर्गः—श्रीकृष्ण प्रद्युम्नयोः सेनयोः तस्य संगमे यत् यत् वृतान्तं अभवन् तेषां अत्र वर्णनम् अस्ति। प्रद्युम्ना स्वकीय अर्द्धचन्द्र चक्रेण श्री कृष्णस्य धनुषभङ्ग चकार। श्रीकृष्ण अपरे स्यन्दने आरुढ़ो भूत्वा क्रौध वषात् स्वकीयां सर्वोत्कृष्ट विधां आहूय अग्नि शराक्षेपं कृत्वा प्रहारमकरोत् पुनष्च प्रद्युम्ना स्वकीयं वारुणास्त्रस्य स्मरणं कृत्वा श्रीकृष्णे प्रक्षेपत्।

उदधि कुमारी प्रभृति अष्टाधिक प×चषत कन्याः प्रद्युम्नकुमारं प्ररिणीता अस्मिन् विवाहे यदुवंषी भोजवंषी प्रभृतयः सर्वे शुभ चिन्तकाः प्रसन्नतामनुभवन्। सत्यभामायाः प्रद्युम्नस्य विवाहेन दुःखी मानसस्य वर्णनं अस्ति।

प्रद्युम्नस्य युद्धं स्वजनानां मिलायो

विवाहोत्सवस्य च वर्णनं अस्ति[61]

द्वादशसर्गः— अस्मिन् सर्गे कीर्तिषाली शम्बुकुमारस्य दिव्य चरित्रस्य वर्णनं अस्ति। प्रद्युम्नकुमारस्य पूर्वभवस्य कनिष्ठ भ्राता कैटभ षोडष्स्वर्ग इन्द्रो अभवत्। निदान भगवान् ब्राह्मणस्य भवतः इन्द्रस्य भव पर्यन्तं सर्व वृत्तान्तस्य वर्णनं वर्तते।

प्रद्युम्नस्य जाम्बुवत्याः प्रासादे अत्रान्तरे वसनत ऋतोः आगमनम् प्रद्युम्नकुमारेण जाम्बुवत्याः गृहं गत्वातस्या स्वरूप् परिवर्तनरूपा देवपुनीता मूद्रिका दानम् श्रीकृष्णस्य सारथी पद्मनाभैः सुधारको, वीरनाम्नः महामन्त्रिणः बुद्धिसेन—गरूडकेतुनाम्नः सेनापतेः जयसेन नाम्नः पुत्रो जात। जाम्बुवती शम्बुकुमारः सत्यभामा च जितभानुम् अजिजनत्।

श्रीकृष्ण द्वारा शम्बुकुमारं मास पर्यन्तं राज्यं समर्पितम् प्रजा च दुःखी अभवत्। श्री कृष्णः प्रद्युम्नाय राज्यभारं समर्पितवान्। अनेन प्रकारेण प्रद्युम्नस्य पुण्यफलस्य वर्णन मिलति द्वादषमे सर्गे।[62]

त्रयोदशसर्गः— श्रीकृष्ण नारायणः विद्याधरः मानवाष्च यस्य सेवां कुर्वन्ति स्म एतादृषं जरासंघ नामकं राजनं युद्धे हत्वा सुदर्षन चक्रं च प्राप्य निष्कण्टक राज्य शासनस्य कौरवपाण्डवानां युद्धस्य वर्णनं मिलति।

नेमिनाथ भगवतः वर्णनं जैन मुनिनां त्रयोदष चरित्राणां, गृहस्थानां द्वादष चरित्राणां षण्णामावष्यक कर्मणां वर्णनं अस्ति। जिनेन्द्र देवस्य पृथ्वी विहारस्य, श्रीनेमिनाथस्य विवाह वैराग्य दीक्षा ज्ञान समवषरण देषनायाः विहारादिनां च वर्णनं अस्ति।[63]

चतुर्दशसर्गः— श्री नेमिनाथो भगवान पल्लवदेषे विहारं कृत्वा उज्जयन्तगिरौ अर्थात् गिरनार पर्वते पदार्पणम् जातम् श्री नेमिनाथेन द्वारा भगवान् श्री कृष्णेन धर्मस्य स्वरुप ज्ञानं पृच्छन चतुरप्रकारक ध्यानं, एवं श्री कृष्णः त्रेसठशलाका पुरूषाणां चरित्रम् अपृच्छत् अतः परं बलभद्र प्रष्न जिनेन्द्र देव कृत भविष्य निरूपणस्य वर्णनं चतुर्दषे सर्गे अस्ति।[64]

पंचदशसर्गः– प्रद्युम्नकुमारस्य राजसभायाम् आगमनम् स्व पितरं च नमस्कृत्यं हस्तौ संयोज्य अभयस्य याचना संसारस्य स्थितिः नित्यता रहिताक्षणभङ्गरता संसारस्य असारता दुःख कारकतायाः विवेचनमस्ति। प्रद्युम्नद्वारा संसारस्य भ्रमण निवारण कर्त्ता जिन भगवतः दीक्षा ग्रहणम्। वासुदेन श्रीकृष्ण एवं यादवैः शौककरणस्य वर्णनं।

श्रीकृष्णस्य ह्रदयः दुःखेन भरितः प्रद्युम्नाय निर्देषं यत् त्वं स्वकीय पितरौ परित्यज्य मा गच्छ इति उपदेष दानम्। मानव जन्म प्राप्ति। तस्मिन् अपि उच्चकुले जन्म ग्रहण कठिनं अस्ति। अतः परं सुकुले जन्मग्रहणं कृत्वा अपि राज्यस्य तथा धन वैभयोः प्राप्ति अतिषय कठिना अस्ति। प्रद्युम्नस्य राग रहित वचांसि श्रुत्वा साम्राज्ञीनां व्याकुलतायाः वर्णनम्।

प्रद्युम्नकुमार द्वारा पूर्वे प्राप्त षोडष लाभान् तथा सर्वविद्याः स्त्रीणां परित्यागं कृत्वा क्षमा याचना करणं तथा भानुकुमारेण अपि वैराग्य धारणकरणस्य वर्णनं अनेन प्रकारेण प्रद्युम्नकुमारः भानुकुमारस्य तथा तस्य अष्टपट्टराज्ञीनां दीक्षायाः वर्णनं सर्गे अस्मिन् विलिखितम् अस्ति।[65]

षोडशसर्गः– प्रद्युम्न मुनिं वैराग्येन विभूषितं तपः रूपा लक्ष्म्या शोभितं घोररूपां तपष्चर्यां कर्तुं विलोक्य श्रीकृष्ण बलदेव प्रभृतेः मोहात् पीडितो भूत्वा द्वारिकां प्रत्यागत्य स्वकीय कार्येषु संलग्नस्य वर्णनं प्रद्युम्ना रागद्वेष क्रोधादि आहारादिकानां त्यागस्य वर्णनं। प्रद्युम्न द्वारा जैन शास्त्रेषु वर्णितं सिंह विक्रीडित हारबन्ध–वज्रबन्ध–धर्मचक्र बाल प्रभृति नाना प्रकारैः कायक्लेषादि तपष्चर्याकरणं गुडधृतस्नेहदधिषर्करालवणादि रसानां त्यागं सम्पूर्ण दोष रहितं पापारम्भवर्जित शुद्धाहारकरणं आर्तरौद्रादिध्यानानां सर्वथा परित्याग करणं धर्मध्यानं शुक्लध्यानं सादरं करणे वर्णनं विद्यते।

कान्ति–कीर्त्ति–क्षमा–बुद्धि–दयारूपास्त्रिणा×च परित्याग निषेध वर्णनम् प्रद्युम्नकुमारेण प्रथमे भागे। षोडष कर्म प्रकृतिनां क्षयं कृतं ताः प्रकृतयः सन्ति–निद्रानिद्रा प्रचलाप्रचला, स्त्यानगृद्धि, नरकगति, नरकगत्यानुपूर्वी–तिर्य×चगति–तिर्य×चगत्यानुपूर्वी, उद्योत–आतप–एकेन्द्री साधारण सूक्ष्म स्थावर द्वि इन्द्रिय त्रेन्द्रिय चतुरिन्द्रियष्च षोडष कर्म प्रकृतिनाम् क्षयं अकरोत्।

द्वितीयभागे–प्रत्याख्यानावरणी क्रोध–मान–माया–लोभ तथा अप्रत्याख्यानावरणी क्रोध मान–माया–लोभ ऐतेषां अष्ट प्रकृतिनाम् नाषं अकरोत्

तृतीयोभागे–नपुंसकवेद प्रकृतेः, चतुर्थभागे–स्त्रीवेद प्रकृतेः प×चमेभागे–हास्य–रति–अरति–षोक–भय जुगुप्सा तथा पुरुषवेदस्य, षष्ठे सप्तमे अष्टमे भागे क्रमेण संज्वलन कोधमान मायाणां नाषं कृतः तत्पष्चात्

सूक्ष्मसाम्पराय गुणस्थानेषु संज्वलन लोभ प्रकृतेः नाषं कृतः। द्वादषे क्षीण कषाय गुण स्थानेषु सम्पूर्ण घातिया कर्माणां नाषं कृतवान्।

योगीराज श्री प्रद्युम्नकुमारः अनेकैदेवैः विद्वद्भिष्चि परिवृतः अन्ते समये जन्म–जरा–मृत्युरहित सिद्धस्वरूपं प्राप्तवान्। तेन सह शम्बुकुमार–भानुकुमार–अनुरुद्धकुमारान् अपि मोक्षं प्राप्तवान्। अनेन प्रकारेण गिरनार पर्वते त्रिणि षिखराणि सन्ति। तेषु प्रथमे षिखरे अनुरुद्धकुमारं द्वितीये षिखरे शम्बुकुमारं तृतीये षिखरे प्रद्युम्नकुमारं निर्वाण प्राप्तिः स×जाताः[66]

संस्कृतं विष्वस्य प्राचीना श्रेष्ठतमा च भाषा अस्ति। भाषायाः जन्म लिप्यापूर्वं भवति। लिपितु पष्चात् उद्भवति। भाषाया उदय वाक्य रूपे भवति। विष्लेषक बुद्धयाः विकासः भूतेसति भाषां पृथक् अवयवेषु वितिरयते। शब्दानां परिचय क्षमता विष्लेषक बुद्धेः अधिक विकसित करणे परिणाम स्वरूपा भवति।

मूल पाठात् प्रतिकरणे अर्थात् मूललेखात् सम्पादने सम्पादक द्वारा कतिपयः त्रुटयः सम्भवितुमर्हन्ति । कदाचित् शब्दार्थस्य समस्यापि आपतति। मात्राणां विकृतिः अक्षरविन्यासस्याभावो जायते विभक्ताक्षरान् पृथक कर्तु समये अक्षर विकृति अपि सम्भवति। संयुक्ताक्षर विकृति युक्त अलङ्कार विकृति अपि आयाति।

मूलपाठात् लेखन समये नवरूपाक्षरस्य परिवर्तनं भवितुमर्हति। एतमेव लुप्ताक्षरी शब्दा आगमाक्षरी विपर्याक्षरी संकेताक्षरी शब्दानां समावेषो जायते सम्पादन समये।[67] संख्यावाचक शब्दानां लेखने अपि परिवर्तनं सम्भवति कतिपयाः शब्दाः वर्तनीच्युताः भ्रमात् स्थापनायां आयान्ति। कतिपयाः शब्दाः अपरिचिता अपि भवन्ति ये मूल पाठ लेखने कदाचित् प्रयोगे भवन्ति किन्तु गच्छति कालान्तरे तेषां अपरिचितावस्था अर्थात् तत्समये तेषां शब्दानां परिचलनं न भवति अतः एतेषां शब्दानां अपरिचितत्वात् भ्रंषनम् अपि जायते।

यद्यपि ममद्वारा सम्पादकेभी अवधानेन उपर्युक्तानां मूल ग्रन्थावली प्राप्तानां त्रुटीनां यथा सम्भवं स्वविवेक पूर्वकं निराकरणं कृतमस्ति येन मूल पाठे कस्यापि विकृतेः भावो न संभूयते।

लिपिकारेण लिपिगता विकृतयः संयुक्ता भवन्ति। कस्यापि प्रतिलिपेः महत्त्वं तस्यां उल्लिखितां रचनामवलोक्य प्रतिष्ठाप्यते। अत एव पाण्डुलिपि विज्ञानं एवं पाण्डुलिपि सम्पादनस्य सन्दर्भे विहितानां त्रुटीनां ज्ञानं कर्तुं परमावष्यक प्रतीयते। सम्पादने तेषां परिमार्जनं विधातव्यम् विराकरणं प्रतिलिपिः उद्देश्येन कर्तुं शक्यते। अस्मिन् प्रतिलिपेः यत् कि×चदपि त्रुटि दृक्गोचरी विलोक्यते तेषु लिपि भ्रमेण लिपि साम्यवषात् पुन र्लेखनं कृतम् आस्ति। वर्णसाम्यं पुनर्लेखन्, शब्दसाम्यं पुनर्लेखनम् मूल लेखस्य लिपिकारेण संकेत चिहानि न अवगतानि। शब्दस्य सम्यक् अन्वयं न करणम् पंक्ते शब्दस्य अर्द्धपंक्ते च पुनरावृत्ति, उपर्युक्तानां त्रुटीनां

सम्मार्जनं लिपिकारेण महता प्रयासेन विहितमास्ति। काव्यं परिष्कृतोद्देष्येन एकं एतादृषं महाकाव्यं यत् अतिप्राचीनं ज्ञानं समृद्धं च आसीत् यच्च सम्पादनाभावे कुत्रचित् लुप्त प्रायो आसीत् तस्य सम्पादनं कृत्वा कवेः काव्ययोः च साकमेव आत्मनः कल्याणमेव मुख्योउद्देष्यम् अस्ति।

–सन्दर्भ ग्रन्थसूचीः–

क्र.सं.	ग्रन्थ / रचना	रचनाकार / प्रकाशन	भाषा	रचनाकाल्
1	अग्न्याधान एवम् अग्निहोत्र का विवेचन	डॉ. उमेष प्रसाद दाषः जगदीष संस्कृत पुस्तकालय		2005
2.	आचार्य सोमकीर्ति एवं ब्रह्म यषोधर	डॉ. कस्तूरचन्द कासलीवाल श्री महावीर ग्रन्थ अकादमी, जयपुर		1982
3.	आर्षेयब्राह्मणम्	डॉ. उमेष प्रसाद दाषः, आयुर्वेदसंस्कृतपुस्तकालय, जयपुर		
4	उत्तर रामचरित	भवभूति, विष्वविद्यालय प्रकाषन, वाराणसी,		1877
5	ऋग्वेद संहिता	सायण भाष्य, वैदिक संषोधन मण्डल पूना		1932 – 1952
6	कात्यायन शुल्बसूत्रम्	डॉ. रमेष चन्द्र दाष नाग प्रकाषक दिल्ली		1994
7	पज्जुण्णकहा	सिंह अथवा सिद्ध (पोथीखाना आमेर जयपुर)	अपभ्रंष	13 वीं शताब्दी
8	प्रद्युम्न चरित्र	महासेनाचार्य (पोथीखाना आमेर जयपुर)	संस्कृत	11वीं शताब्दी
9	प्रद्युम्न चरित्र	कवि सधारु (पोथीखाना आमेर जयपुर)	हिन्दी	स. 1411
10	प्रद्युम्न चरित्र	भट्टारक सकलकीर्ति (पोथीखाना आमेर जयपुर)	संस्कृत	15 वीं शताब्दी
11	प्रद्युम्न चरित्र	रइधू (पोथीखाना आमेर जयपुर)	अप्रभंष	15 वीं शताब्दी
12	प्रद्युम्न चरित्र	सोमकीर्ति (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	संस्कृत	1530 स.
13	प्रद्युम्न चरित्र	रविसागर (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	संस्कृत	स. 1645

14	प्रद्युम्न चरित्र	शुभचन्द्र (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	संस्कृत	17 वीं शताब्दी
15	प्रद्युम्न चरित्र	रतनचन्द्र (राजकीय संग्रहालय अलवर)	संस्कृत	स. 1671
16	प्रद्युम्न चरित्र	मल्लिभूषण (राजकीय संग्रहालय अलवर)	संस्कृत	17 वीं शताब्दी
17	प्रद्युम्नचरित्र	वादिचन्द्र (राजकीय संग्रहालय अलवर)	संस्कृत	17 वीं शताब्दी
18	प्रद्युम्नचरित्र	भोगकीर्ति (गंगा स्वर्ण जयन्ती संग्रहालय बीकानेर)	संस्कृत	17 वीं शताब्दी
19	प्रद्युम्नचरित्र	जिनेष्वरसूरी (गंगा स्वर्ण जयन्ती संग्रहालय बीकानेर)	संस्कृत	17 वीं शताब्दी
20.	प्रद्युम्नचरित्र	यषोधर (गंगा स्वर्ण जयन्ती संग्रहालय बीकानेर)	संस्कृत	17 वीं शताब्दी
21	प्रद्युम्नचरित	बख्तावरसिंह (सन्मति पुस्तकालय जयपुर)	हिन्दीगद्य	स. 1914
22	प्रद्युम्नचरित्रभाषा	यषोधर (गंगा स्वर्ण जयन्ती संग्रहालय बीकानेर)	हिन्दी गद्य	17 वीं शताब्दी
23	प्रद्युम्न चौपई	कमल केषर (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	हिन्दी	स. 1626
24	प्रद्युम्नप्रकाष	षिवचन्द (सन्मति पुस्तकालय जयपुर)	हिन्दी	स. 1879
25	प्रद्युम्नप्रबन्ध	देवेन्द्र कीर्ति (सन्मति पुस्तकालय जयपुर)	हिन्दी	स. 1722
26	प्रद्युम्नरास	मायाराम	हिन्दी	स. 1818

		(सन्मति पुस्तकालय जयपुर)		
27	प्रद्युम्न रासो	ब्रह्मरायमल्ल (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	हिन्दी	स. 1628
28	पाण्डुलिपि विज्ञान	डॉ. सत्येन्द्र, राजस्थान हिन्दी ग्रन्थ अकादमी जयपुर,		1978
29	भागवत् महापुराण	गीता प्रेस गोरखपुर		
30	भारती	भारतीय भवन बी–15 न्यू कॉलोनी, जयपुर		
31	भारतीय संस्कृतिः	वाई.एस. रमेष हंसा प्रकाषन, जयपुर		1996
32	भारतीय संस्कृति के तत्त्व	डॉ. श्रीकृष्ण ओझा अभिषेक प्रकाषन, जयपुर		
33	मनुस्मृति	निर्णयसागर प्रेस, बम्बई		1980
34	महाभारत	गीताप्रेस, गोरखपुर		
35	रचनाविमर्षः	हंसा प्रकाषन, जयपुरम्		
36	लीला पुरुषोत्तम	गीता प्रेस गोरखपुर		
37	वयम्	ज.रा. राजस्थानसंस्कृतविष्वविद्यालयः, जयपुरम्		
38	वेदविद्या	म.सा. वेदविद्या प्रतिष्ठान् उज्जैन		
39	वेदाङ्ऽवाणी	हंसा प्रकाषन, जयपुरम्		
40	वैदिकसाहित्य और संस्कृति	बलदेव उपाध्याय, वाराणसी		1958
41	वृहदारण्यक	सुरेष्वरा आचार्य, आनन्दाश्रम ग्रन्थावली , 16 पूना		1937
42	शाम्बप्रद्युम्नरास	समयसुन्दर (महावीर दिग. जैन पाण्डुलिपि संरक्षण केन्द्र जयपुर)	राजस्थानी	स. 1659
43	शाम्बप्रद्युम्न रास	ज्ञानसागर (राजकीय संग्रहालय अलवर)	हिन्दी	17 वीं शताब्दी

44	शाम्बप्रद्युम्न रास	जिनचन्द्र सूरि (राजकीय संग्रहालय अलवर)	हिन्दी	17 वीं शताब्दी
45	शाम्बप्रद्युम्नरास	हर्षविजय (सन्मति पुस्तकालय जयपुर)	हिन्दी	स. 1842
46	शोध प्रविधि एवं पाण्डु लिपि विज्ञानम्	डॉ. अभिराज राजेन्द्र मिश्र प्रतिभाप्रकाषन		
47	श्रीमद् भगवदगीता	गीताप्रेस गोरखपुर		
48	सरस्वतिसौरभम्	आयुर्वेदसंस्कृतपुस्तकालय, जयपुरम्		
49	सामवेदीयार्षेयब्राह्मणम्	डॉ. उमेष प्रसाद दाषः जगदीष संस्कृत पुस्तकालय		2004
50	संस्कृत निबन्ध रचना	डॉ. श्रीकृष्ण ओझा अभिषेक प्रकाषन, जयपुर		
51	संस्कृत वाङ्मयका इतिहास	सूर्यकान्त आरोयन्टल् लांगमैन्, नई दिल्ली,		1972
52	संस्कृत वाङ्मय में लोकतन्त्र	हंसा प्रकाषन, जयपुर		2010
53	संस्कृत हिन्दी कोष	वामन श्रीराम आप्टे, मोलीलाल बनारसी दास दिल्ली,		1987
54	संस्कृति–सौरभम् शोध पत्रिका	संस्कार–भारती मानवकल्याण संस्थान, जयपुर, राजस्थान		
55.	हरिवंष पुराण	गीता प्रेस गोरखपुर		

सन्दर्भसूची :–

1. पाण्डुलिपि आवरण : ग्रन्थ परिचय पत्र
2. प्रद्युम्नचरित्र 16 / 71
3. प्रद्युम्नचरित्र पाण्डुलिपि– 16 / 70
4. आचार्य सोमकीर्ति एवं ब्रह्म यषोधर पृष्ठ संख्या 04
5. प्रद्युम्नचरित्र पाण्डुलिपि 16–68,69,70
6. राजस्थान के जैन शास्त्र भण्डारों की सूची भाग–पंचम् पृ.सं. 492
7. आचार्य सोमकीर्ति एवं ब्रह्म यषोधर पृष्ठ संख्या 11
8. आचार्य सोमकीर्ति एवं ब्रह्म यषोधर पृष्ठ संख्या 1–25
9. पाण्डुलिपि विज्ञान पृ. सं. 194, 223, 224
10. वेद–पर्यावरण नवनीतम (हंसा प्रकाषन जयपुर) 2014
11. ऋग्वेद (5–4–11)
12. संस्कृत वाङ्मय में लोकतन्त्र (हंसा प्रकाषन जयपुर) 2014
13. रुद्राष्टाध्यायी –पं. जगदीष शर्मा जयपुर पृ. सं. 58
14. अग्न्याधान एवम् अग्निहोत्र का विवेचन – डॉ. उमेष प्रसाद दाष,
    जगदीष संस्कृत पुस्तकालय 2005
15. कात्यायन शुल्बसूत्रम् –डॉ. रमेष चन्द्र दाष , नाग प्रकाषक दिल्ली 1994
16. सामवेदीयार्षेय ब्राह्मणम् – डॉ. उमेष प्रसाद दाष जगदीष संस्कृत पुस्तकालय 2004
17. संस्कृति सौरभम् शोध पत्रिका– षष्ठम् अंक – पृष्ठ सं. 13–16
18. अग्निपुराण पृ. सं. 292
19. संस्कृति सौरभम् शोध पत्रिका षष्ठ्म अंक – पृष्ठ सं. 44–45

20. भारती संस्कृत–मास पत्रिका –अगस्त 15 पृष्ठ सं. 27

21. ऋग्वेद 5–30–9

22. ऋग्वेद 10–102–2

23. ऋग्वेद 10–108–2

24. भारती संस्कृत–मास पत्रिका –फरवरी 2015 पृष्ठ सं. 18–19

25. ऋग्वेद 1–164–46

26. बृहदारण्यक 5–4–1

27. मनुस्मृति 6–92

28. मनुस्मृति 5–109

29. संस्कृति सौरभम् शोध पत्रिका प×चम् अंक पृ.सं. 30–31

30. संस्कृति सौरभम् शोध पत्रिका प×चम् अंक पृ.सं. 21 – 23

31. श्रीमद् भगवद्गीता अध्याय 4/7

32. श्रीमद् भगवद्गीता अध्याय 4/8

33. संस्कृति सौरभम् शोध पत्रिका प×चम् अंक पृ.सं. 50– 52

34. मनुस्मृति 3–46

35. संस्कृति सौरभम् शोध पत्रिका षष्ठम् अंक पृ.सं. 64– 67

36. ईषोपनिषद्–11

37. केनोपनिषद् 2–4

38. भारतीय संस्कृत मास पत्रिका फरवरी 2015 पृष्ठ सं. 18

39. भारतीय संस्कृत मास पत्रिका फरवरी 2015 पृष्ठ सं. 21

40. रुद्राष्टाध्यायी पं. जगदीष शर्मा आरार्तिक्यम् पृ.स. 56

41. भारतीय संस्कृति पृ.स. 118

42. भारतीय संस्कृति पृ.स. 119

43. भारतीय संस्कृति पृ.स. 120

44. भारतीय संस्कृति पृ.स. 124

45. संस्कृत निबन्ध रचना, डॉ. श्रीकृष्ण ओझा पृ. सं. 27–28

46. संस्कृत निबन्ध रचना, डॉ. श्रीकृष्ण ओझा पृ. सं. 66–67

47. श्रीमद् भगवद्गीता , अध्याय 2/27

48. संस्कृत निबन्ध रचना, डॉ. श्रीकृष्ण ओझा पृ. सं. 73–74

49. संस्कृत निबन्ध रचना, डॉ. श्रीकृष्ण ओझा पृ. सं. 88–89

50. संस्कृत निबन्ध रचना, डॉ. श्रीकृष्ण ओझा पृ. सं. 92–93

51. प्रद्युम्नचरित्र पाण्डुलिपि प्रथमसर्गः

52. प्रद्युम्नचरित्र पाण्डुलिपि द्वितीयसर्गः

53. प्रद्युम्नचरित्र पाण्डुलिपि तृतीयसर्गः

54. प्रद्युम्नचरित्र पाण्डुलिपि चतुर्थसर्गः

55. प्रद्युम्नचरित्र पाण्डुलिपि प×चम्सर्गः

56. प्रद्युम्नचरित्र पाण्डुलिपि षष्ठम्सर्गः

57. प्रद्युम्नचरित्र पाण्डुलिपि सप्तमसर्गः

58. प्रद्युम्नचरित्र पाण्डुलिपि अष्टमसर्गः

59. प्रद्युम्नचरित्र पाण्डुलिपि नवमसर्गः

60. प्रद्युम्नचरित्र पाण्डुलिपि दषमसर्गः

61. प्रद्युम्नचरित्र पाण्डुलिपि एकादषसर्गः

62. प्रद्युम्नचरित्र पाण्डुलिपि द्वादषसर्गः

63. प्रद्युम्नचरित्र पाण्डुलिपि त्रयोदषसर्गः

64. प्रद्युम्नचरित्र पाण्डुलिपि चतुर्दषसर्गः

65. प्रद्युम्नचरित्र पाण्डुलिपि प×चदषसर्गः

66. प्रद्युम्नचरित्र पाण्डुलिपि षोडषसर्गः

67. पाण्डुलिपि विज्ञान डॉ. सत्येन्द्र –भूमिका

68. भारतीया संस्कृति , हंसा प्रकाषन पृ. सं. 116

69. पाण्डुलिपि विज्ञान डॉ. सत्येन्द्र – भूमिका से–

पाठालोचनः–

प्रथमसर्गः–

निर्म्मल – निर्मल , नंदंतु – नन्दन्तु , वाहुभ्यां – बाहुभ्यां , कुंर्वति – कुर्वन्ति, यं – यः

श्रुभं – शुभं, प्रवोधांर्थ – प्रबोधार्थं, मागधो– मगध, स्वर्न्नगरीसमं – स्वर्णनगरीसमं

सरणं–शरणं, गएैंद्रः – गणेन्द्रः, सुषाद्वला–पुष्पफलपरिपूर्णाः, पुष्फाणि–पुष्पाणि, ध्रव– ध्रुवं

सास्त्रे–शास्त्रे, सुर्ग्ग–स्वर्ग, षिख्या–षिक्षा

द्वितीयसर्गः–

जंवू–जम्बू पुष्फ–पुष्प, विनिर्म्मिता–विनिर्मिता, वाल्येपि–बाल्येपि, सÕया–षÕया, प्राक्रम – शौर्यं

प्रर्षिक–प्रक्षिक, विश्रुद्वा–विषूद्धा, नाषिकया–नासिकया, विंविकाफलं–बिम्बीकाफलं

द्रस्य–दृष्य, वन्धून–बन्धून, वलभद्र–बलभद्र,

तृतीयसर्गः–

लोकेस्क्त–लौकेस्तु, कृस–कृष, शंषय–संषय, बलादय–बलादय, दर्प्पणं–दर्पणं, शंपदां–सम्पदां

प्रतिविंव–प्रतिबिम्ब, कैलास–कैलाष, सहस्त्राणि–सहस्त्राणि,

चतुर्थसर्गः–

श्नेह–स्नेह, सैत्येन–सैन्येन, विंव–बिम्ब, संख–षंख, अश्रक्त–अश्रु, श्रूरं–षूरं, पषाणे–पाषाणे, वेषं–वेषं

तांवूल–ताम्बूलं, किमुत्कांग–किमुत्कंठा, ननाम–नमाम, लखं–लेखं

पचिमसर्गः–

छीघ्रं–शीघ्रं, तत्प्रमानं–तत्प्रमाणं, नयणयो–नयनयो, सोभां–शोभां, वुद्धि–बुद्धि, हरनं–हरणं वाह्ये–बाह्मे

षष्ठमसर्गः—

कत्तुं—कर्तुं, सद्दसं—सदृषं, सत्रुणा—षत्रुणां, शकलं—सकलं, सास्त्रार्थ—शास्त्रार्थ, जानाभि—जानासि

खट्खंड—षट्खण्ड, पुष्फिता—पुष्पिताः, बिवांद—विवादं, सृगाल—श्रृगाल, सास्त्रवलेन—षास्त्रबलेन

योषं—मौन

सप्तमसर्गः—

निर्दोषवंष—षुद्धवंष,

अष्टमसर्गः—

अजोध्यायाः—अयोध्यायाः, बलान्पित—बलान्वितः, विल्पसादि—विलासादि, सैख्यं—सौख्यं, वृतंत—वृतान्त

महाभग्ये—महाभाग्ये, चिनहं—चिË,

नवमसर्गः—

गिरिगरे—गिरिग à रे, परपच्छ—प्रपच्छ, शोडसलाभ—षोडषलाभः

दशमसर्गः—

रीरी—पीतल, उर्दनं—तण्डुलं, स्फिक—कटि, घोणा—नासिका, समासत—संक्षेपतः

एकादशसर्गः— सन्मार्य—शृंगारितः, परमालाड—परमाह्लाद,

द्वादशसर्गः—

पप्रच्छ—प्रपच्छ, षिबिकां—पालकी, असवं—अष्वं, तिष्ठषि— तिष्ठसि

त्रयोदशसर्गः—

शंस्यं—संषयं, कनिष्टां—कनिष्ठिका, घ्ंन्ति— घ्नंति, गगणा— गगना, मठा—आरणालं, नहिंसा—अहिंसा

चतुर्थदशसर्गः—

पद्म— पद्म, सविपयय—सविपर्ययः,

पचिदर्शसर्गः—

मुचमंच–मुंच–मुंच

षोडषसर्गः– विनिमुक्तो–विनिर्मुक्तो, तवोवनं–तपोवनं, पासौ–पाषौ